ज्ञानमार्गणाधिकारः ॥१२॥

अनंतरं श्रीनेमिचंद्रसैद्धांतचक्रवर्त्तिगळु ज्ञानमार्गणेयं पेळलुपक्रमिसि निरुक्तिपूर्व्वकं ज्ञानसामान्यलक्षणमं पेळ्दपरु ।

जाणइ तिकालविसए दव्वगुणे पज्जए य बहुभेदे ।
पच्चक्खं च परोक्खं अणेण णाणेत्ति णं बेंति ॥२९९॥

जानाति त्रिकालविषयान् द्रव्यगुणान् पर्य्यायांश्च बहुभेदान् । प्रत्यक्षं परोक्षमनेन ज्ञानमिति इदं ब्रुवंति ॥

त्रिकालविषयान् भूतभविष्यद्वर्त्तमानकालगोचरंगळप्प बहुभेदान् जीवादि ज्ञानादि स्थावरादि नानाप्रकारंगळप्प द्रव्यगुणान् जीवपुद्गलधर्म्माऽधर्म्माऽऽकाशकालंगळेंब द्रव्यंगळुमं ज्ञानदर्शनसम्यक्त्वसुखवीर्य्यादिगळुं स्पर्शरसगंधवर्णादिगळुं गतिस्थित्यवगाहनवर्त्तनाहेतुत्वादिगळुमेंबी गुणंगळुमं पर्य्यायांश्च स्थावरत्वत्रसत्वंगळुमणुत्वस्कंधत्वंगळुं अर्त्थव्यंजनभेदंगळुमं पेरगुमेंबी पर्य्यायंगळुमनात्मं प्रत्यक्षं स्पष्टं परोक्षं च अस्पष्टमुमागि अनेन जानातीति अरिगुमिदरिंदितु ज्ञानमितीदं ज्ञानमेंदितिदं करणभूतमप्प स्वार्त्थव्यवसायात्मकमप्प जीवगुणमं ब्रुवंति पेळ्वरर्हदादिगळी ज्ञानमे

मानवैः पूज्यपादाब्जं समवसृतिसंस्थितम् ।
द्वादशं तीर्थकर्तारं वासुपूज्यं जिनं स्तुवे ॥१२॥

अथ श्रीनेमिचन्द्रसैद्धान्तचक्रवर्ती ज्ञानमार्गणामुपक्रममाणो निरुक्तिपूर्वं ज्ञानसामान्यलक्षणमाह—

त्रिकालविषयान् भूतवद्भविष्यद्वर्तमानकालगोचरान् बहुभेदान्–जीवादिज्ञानादिस्थावरादिनानाप्रकारान् द्रव्याणि जीवपुद्गलधर्माधर्माकाशकालाख्यानि, गुणान् ज्ञानदर्शनसम्यक्त्वसुखवीर्यादीन् स्पर्शरसगन्धवर्णादीन् गतिस्थित्यवगाहनवर्तनाहेतुत्वादींश्च पर्यायांश्च स्थावरत्रसत्वादीन् अणुत्वस्कन्धत्वादीन् अर्थव्यञ्जनभेदानन्यांश्च आत्मप्रत्यक्षं स्पष्टं परोक्षं च अस्पष्टं अनेन जानातीति ज्ञानमितीदं करणभूतं स्वार्थव्यवसायात्मकं जीवगुणं

श्री नेमिचन्द्र सिद्धान्त चक्रवर्ती ज्ञानमार्गणाको प्रारम्भ करते हुए निरुक्तिपूर्वक ज्ञानसामान्यका लक्षण कहते हैं—

त्रिकाल अर्थात् अतीत, अनागत और वर्तमान कालवर्ती बहुत भेदोंको अर्थात् जीव आदि स्थावर आदि नाना प्रकारोंको, जीव पुद्गल धर्म अधर्म आकाश काल नामक द्रव्योंको, ज्ञान दर्शन सम्यक्त्व सुख वीर्य आदि और स्पर्श रस गन्ध वर्ण आदि गुणोंको, तथा गतिहेतुत्व, स्थितिहेतुत्व, अवगाहनहेतुत्व, वर्तनाहेतुत्व आदि पर्यायोंको, स्थावर त्रस आदिको, परमाणु स्कन्ध आदिको अर्थपर्याय और व्यंजनपर्यायोंको इसके द्वारा प्रत्यक्ष अर्थात् स्पष्ट और परोक्ष अर्थात् अस्पष्ट रूपसे जानता है इसलिए अर्हन्त आदि इसे ज्ञान कहते हैं यह जीवका व्यवसायात्मक गुण है। यह ज्ञान ही प्रत्यक्ष और परोक्षके भेदसे दो

१. म तिकालविसए । २. त्रिकालगहितान् ।

मावोदं ज्ञानोत्पत्तिप्रतिघातित्वाऽभावदिदमविवक्षेयरियल्पडुवुदु । केवलज्ञानं क्षायिकमेयक्कुमेकेंदोडे केवलज्ञानावरणवीर्यांतराय निरवशेषक्षयप्रादुर्भूतत्वदिदं, क्षये भवं क्षयः प्रयोजनमस्येति वा क्षायिकं । येत्तलानुमात्मंगे केवलज्ञानं प्रतिबंधकावस्थेयोळु शक्तिरूपदिदं विर्प्पुदंतिर्द्दोडं प्रतिबंधक-क्षयदिदमे तद्व्यक्तियक्कुमेंदितु व्यक्त्यपेक्षेयिदं कार्य्यत्वसंभवदिदं क्षायिकमेंदितु पेळल्पट्टुदु । आवरणक्षयमुंटागुत्तिरलु प्रादुर्भवति येंबी निरुक्तियिदं तद्व्यक्त्यपेक्षत्वमुंटप्पुरिदं ।

अनंतरं मिथ्याज्ञानोत्पत्तिकारणस्वरूपस्वामिभेदंगळं पेळ्दपं :—

अण्णाणतियं होदि हु सण्णाणतियं खु मिच्छअणउदए ।

णवरि विभंगं णाणं पंचिंदियसण्णिपुण्णेव ॥३०१॥

अज्ञानत्रयं भवति खलु सज्ज्ञानत्रयं खलु मिथ्यात्वानंतानुबंध्युदये । विशेषो विभंगं ज्ञानं पंचेंद्रियसंज्ञिपूर्णं एव ॥

आवुदोंदु मतिश्रुतावधिगळु सम्यग्दर्शनपरिणतजीवसंबंधि सम्यग्ज्ञानत्रयं संज्ञिपंचेंद्रियपर्य्याप्तजीवनविशेषग्रहणरूपाकारसहितोपयोगलक्षणमप्प तत् सम्यग्ज्ञानमे मिथ्यादर्शनानंतानुबंधिकषायान्यतमोदयमागुत्तिरलतत्वार्त्थश्रद्धानपरिणतजीवसंबंधिमिथ्याज्ञानत्रयं खलु स्फुटमक्कुं । णवरि विशेषमुंटदु आवुदोंदवधिज्ञानविपर्य्ययरूपमप्प विभंगमेंब पेसरनुळ्ळ मिथ्याज्ञानमक्कु

ज्ञानोत्पत्तिप्रतिघातित्वाभावात् अविवक्षा ज्ञातव्या । केवलज्ञानं पुनः क्षायिकमेव भवति केवलज्ञानावरणवीर्यान्तरायनिरवशेषक्षयेण प्रादुर्भूतत्वात् । क्षये भवं, क्षयः प्रयोजनमस्येति वा क्षायिकम् । यद्यप्यात्मनः केवलज्ञानं प्रतिबन्धकावस्थायां शक्तिरूपेण विद्यमानं तथापि प्रतिबन्धकक्षयेणैव तद्व्यक्तिः स्यात् इति व्यक्त्यपेक्षया कार्यत्वसंभवात् क्षायिकमित्युक्तं । आवरणक्षये सति प्रादुर्भवति इति निरुक्तेः तद्व्यक्त्यपेक्षत्वात् ॥३००॥

अथ मिथ्याज्ञानोत्पत्तिकारणस्वरूपस्वामिभेदानाह—

यत्सम्यग्दर्शनपरिणतजीवसंबन्धिमतिश्रुतावधिसंज्ञं सम्यग्ज्ञानत्रयं संज्ञिपञ्चेन्द्रियपर्याप्तजीवस्य विशेषग्रहणरूपाकारसहितोपयोगलक्षणं तदेव मिथ्यादर्शनानन्तानुबन्धिकषायान्यतमोदये सति अतत्त्वार्थश्रद्धानपरिणतजीवसम्बन्धिमिथ्याज्ञानत्रयं खलु–स्फुटं भवति । नवरीति विशेषोऽस्ति 'यदवधिज्ञानविपर्ययरूपं विभङ्गनामकं

है। जो क्षयोपशमसे होते हैं अथवा क्षयोपशम जिनका प्रयोजन है वे क्षायोपशमिक हैं। क्षायोपशमिक ज्ञानोंमें यद्यपि उस-उस आवरण सम्बन्धी देशघाती स्पर्धकोंका उदय विद्यमान रहता है तथापि वे ज्ञानकी उत्पत्तिके प्रतिघाती नहीं हैं इसलिए यहाँ उनकी विवक्षा नहीं है। किन्तु केवलज्ञान क्षायिक ही होता है क्योंकि वह केवल ज्ञानावरण तथा वीर्यान्तरायके सम्पूर्ण क्षयसे प्रकट होता है। जो क्षयसे होता है या क्षय जिसका प्रयोजन है वह क्षायिक है। यद्यपि आत्मामें केवलज्ञान प्रतिबन्धक अवस्थामें शक्तिरूपसे विद्यमान है तथापि प्रतिबन्धकके क्षयसे ही वह प्रकट होता है इसलिए व्यक्तिकी अपेक्षा कार्य होनेसे उसे क्षायिक कहा है। आवरणका क्षय होनेपर प्रकट होता है ऐसी निरुक्ति होनेसे उसकी व्यक्तिकी अपेक्षा है ॥३००॥

अथ मिथ्याज्ञानकी उत्पत्तिके कारण, स्वरूप और स्वामीभेदोंको कहते हैं—

जो सम्यग्दृष्टि जीवके मति, श्रुत और अवधि नामक तीन सम्यग्ज्ञान हैं, संज्ञी पंचेन्द्रिय पर्याप्त जीवके विशेष ग्रहणरूप आकार सहित उपयोग जिनका लक्षण है, वे ही तीनों मिथ्यादर्शन और अनन्तानुबन्धी कषायमेंसे किसी एक [illegible]यका उदय होनेपर अतत्त्वार्थश्रद्धानरूप परिणत मिथ्यादृष्टि जीवके मिथ्याज्ञान [illegible] किन्तु इतना विशेष है

अनंतरं मिथ्याज्ञानविशेषलक्षणमं गाथात्रयदिदं पेळ्दपं ।

विसजंतकूडपंजरबंधादिसु विणुवएसकरणेण ।
जा खलु पवट्टइ मई मइअण्णाणेत्ति णं बेंति ॥३०३॥

विषयंत्रकूटपंजरबंधादिषु विनोपदेशकरणेन । या खलु प्रवर्त्तते मतिर्मत्यज्ञानमिति
विषयंत्रकूट पंजरबंधमें बिवु मोदलाद जीवमारणबंधनहेतुगळोळु या मतिः आ
परोपदेशकरणमिल्लदे प्रवर्त्तिसुगुमदे मत्यज्ञानमें दु अर्हदादिगळु पेळ्वरल्लि परस्परसं
मारणशक्तिविशिष्टतैलकर्पूरादिद्रव्यं विषमें बुदक्कुं । सिहव्याघ्रादि क्रूरमृगंगळ धरणार्थं
कृतच्छागादिजीवमनुळ्ळ काष्ठादिरचितमप्पुदु तत्पादनिक्षेपमात्रकवाटसंघटीकरण
लितमप्पुदु यंत्रमें बुदक्कुं । मत्स्यकच्छपमूषकादिग्रहणार्थमवष्टब्धकाष्ठादिमयं कूटमें
तित्तिरीलावकहरिणादिधारणार्थं विरचितग्रंथिविशेषकलितरज्जुमयमप्प जालं पंजरमें
गजोष्ट्रादिधारणार्थमवष्टब्धमप्पगर्त्तमुखकीलितग्रंथिविशिष्टवारिरज्जुरचनाविशेषं बंधमें
आदिशब्ददिदं पक्षिगळ पक्षमं पत्तिसि सिक्किसल्कें दु दीर्घदंडाग्रदोळु तोडव पिप्पलनि
चिक्कणबंधमुं । गृहहरिणादिशृंगलग्नसूत्रग्रंथिविलोपादिगळो ग्रहणमनुपदेशपूर्वकं

संभवति नेतरदेशसंयतादिषु गुणस्थानेषु तथाविधतपोविशेषाभावात् ॥३०२॥ अथ मिथ्याज्ञानविशे
गाथात्रयेणाह—

विषयन्त्रकूटपञ्जरबन्धादिषु जीवमारणबन्धनहेतुषु या मतिः परोपदेशकरणेन विना प्रवर्तते
मत्यज्ञानमित्यर्हदादयो ब्रुवन्ति । तत्र परस्परसंयोगजनितमारणशक्तिविशिष्टं तैलकर्पूरादिद्रव्यं विषं,
व्याघ्रादिक्रूरमृगधारणार्थमभ्यन्तरीकृतछागादिजीवं काष्ठादिरचितं तत्पादनिक्षेपमात्रकवाटसंपुटीकर
सूत्रकीलितं यन्त्रं, मत्स्यकच्छपमूषकादिग्रहणार्थमवष्टब्धं काष्ठादिमयं कूटं, तित्तिरलावकहरिणादिधार
विरचितं ग्रन्थिविशेषकलितरज्जुमयं जालं पञ्जरः, गजोष्ट्रादिधारणार्थमवष्टब्धो गर्तमुखकीलितग्रन्थिवि
धारीरज्जुरचनाविशेषो बन्धः । आदिशब्देन पक्षिपक्षलगनार्थं दीर्घदण्डाग्रक्षिप्तपिप्पलनिर्यासादिचिक्क

महामुनियोंके होता है, अन्य देशसंयत आदि गुणस्थानमें नहीं होता क्योंकि वहाँ उस प्रक
का तपविशेष नहीं है ॥३०२॥

अब तीन गाथाओंसे मिथ्याज्ञानोंका विशेष लक्षण कहते हैं—

जीवोंको मारने और बन्धनमें हेतु विष, यन्त्र, कूट, पंजर, बन्ध आदिमें बिन
परोपदेशके मति प्रवर्तित होती है वह मतिअज्ञान है ऐसा अर्हन्त भगवान् आदि कहते हैं
परस्पर वस्तुके संयोगसे उत्पन्न हुई मारनेकी शक्तिसे युक्त तैल, रसकपूर आदि द्रव्य विष
है । सिंह, व्याघ्र आदि क्रूर जीवोंको पकड़नेके लिए, अन्दरमें बकरा आदि रखकर लकड़ी
आदिसे बनाया गया, जिसमें पैर रखते ही द्वार बन्द हो जाता हो, ऐसा सूत्रसे कीलित
यन्त्र होता है । मच्छ, कछुआ, चूहा आदि पकड़नेके लिए काष्ठ आदिसे रचे गयेको कूट कहते
है । तीतर, लावक, हरिण आदि पकड़नेके लिये रस्सीमें अमुक प्रकारकी गाँठ देकर बनाये
गये जालको पंजर कहते हैं । हाथी, ऊँट आदि पकड़नेके लिए गढ़ा खोदकर और उसका
मुख ढाँककर या रस्सी आदिका फन्दा लगाकर जो विशेष रचना की जाती है उसे बन्ध
कहते हैं । आदि शब्दसे पक्षियोंके पंख चिपकाने के लिए लम्बे बाँस आदिके अग्रभागमें
पीपल आदिका चिकना रस गोंद वगैरह लगाना और हरिण आदिके सींगके अग्रभागमें
फन्दा आदि डालना आदि लिया जाता है । इस प्रकारके कार्योंमें जो बिना परोपदेशके स्वयं

दंडजटाधारणादितपःकर्म्ममुं षोडशपदार्थं षट्पदार्थभावनाविधिनियोग भूतचतुष्टय पंचविंशति-सत्वचतुरार्य्यसत्यविज्ञानाद्वैतसर्व्वशून्यतादिप्रतिपादकंगळप्प आगमाभासजनितमप्प श्रुतज्ञाना-भासमदेल्लं श्रुताज्ञानमें बुदिदु निश्चैसल्पडुवुदेकें दोडे दृष्टेष्टविरुद्धार्थविषयत्वदिदं ।

विवरीयमोहिणाणं खओवसमियं च कम्मबीजं च ।
वेभंगोत्ति पउच्चइ समत्तणाणीण समयम्मि ॥३०५॥

विपरीतावधिज्ञानं क्षायोपशमिकं च कर्म्मबीजं च । विभंग इति प्रोच्यते समाप्तज्ञानिनां समये ॥

मिथ्यादर्शनकर्म्मसहितमप्प जीवंगे अवधिज्ञानावरणीयवीर्य्यांतरायक्षयोपशमजनितमप्पुदुं द्रव्य-क्षेत्रकालभावमर्यादितमप्पुदुं रूपिद्रव्यविषयमप्पुदुं आप्तागमपदार्थंगळोळु विपरीतग्राहकमप्पुदुं तिर्य्यंग्मनुष्यगतिगळोळु तीव्रकायक्लेश द्रव्यसंयमरूपगुणप्रत्ययमप्पुदुं । च शब्ददिदं देवनारकगति-गळोळु भवप्रत्ययमप्पुदु मिथ्यात्वादिकर्म्मबंधबीजमप्पुदुं चशब्ददिद केलकालं नारकादिगळोळु पूर्व्वभवदुराचारसंचितदुःकर्म्मफलतीव्रदुःखवेदनाभिभवजनितसम्यग्दर्शनज्ञानरूपधर्म्मबीजमुमप्पुदुं ।
एवंविधमवधिज्ञानं विभंगमेंदितु समाप्तज्ञानिगळु केवलज्ञानिगळ समये स्याद्वादशास्त्रदोळु प्रोच्यते पेळल्पट्टुदु । एकें दोडे नारकविभंगज्ञानदिदं वेदनाभिभवतत्कारणदर्शनस्मरणानुसंधान-

---

गृहस्थकर्म, त्रिदण्ड ? जटाधारणादितपःकर्म्म, षोडशपदार्थ, षट्पदार्थ, भावनाविधिनियोग, भूतचतुष्टय, पंचविंशतितत्त्व, चतुरार्यसत्य, विज्ञानाद्वैत, सर्वशून्यतादि-प्रतिपादक आगमाभासजनितं श्रुतज्ञानाभासं सर्वं श्रुताज्ञानमिति निश्चेतव्यं, दृष्टेष्टविरुद्धार्थविषयत्वात् ॥३०४॥

मिथ्यादर्शनकलङ्कितस्य जीवस्य अवधिज्ञानावरणीयवीर्यान्तरायक्षयोपशमजनितं द्रव्यक्षेत्रकालभाव-सीमाधिकं रूपिद्रव्यविषयं आप्तागमपदार्थेषु विपरीतग्राहकं तिर्यग्मनुष्यगत्योः तीव्रकायक्लेशद्रव्यसंयमरूपगुण-प्रत्ययं, चशब्दात् देवनारकगत्योः भवप्रत्ययं च मिथ्यात्वादिकर्मबन्धबीजं, चशब्दात् क्वचिन्नारकादिगतौ पूर्वभवदुराचारसंचितदुःकर्मफलतीव्रदुःखवेदनाभिभवजनितसम्यग्दर्शनज्ञानरूपधर्मबीजं वा अवधिज्ञानं विभङ्ग इति समाप्तज्ञानिनां केवलज्ञानिनां समये स्याद्वादशास्त्रे प्रोच्यते कथ्यते । नारकाणां विभङ्गज्ञानेन वेदनाभि-

---

गृहस्थकर्म, त्रिदण्ड तथा जटा धारण आदि तपस्वियोंका कर्म, नैयायिकोंका षोडश पदार्थवाद, वैशेषिकोंका षट्पदार्थवाद, मीमांसकोंका भावनाविधिनियोग, चार्वाकका भूत-चतुष्टयवाद, सांख्योंके पचीस तत्त्व, बौद्धोंका चार आर्यसत्य, विज्ञानाद्वैत, सर्वशून्यवाद आदिके प्रतिपादक आगमाभासोंसे होनेवाला जितना श्रुतज्ञानाभास है वह सब श्रुतअज्ञान जानना। क्योंकि प्रत्यक्ष और अनुमानसे विरुद्ध अर्थको विषय करता है ॥३०४॥

मिथ्यादृष्टि जीवके अवधिज्ञानावरण और वीर्यान्तरायके क्षयोपशमसे उत्पन्न हुआ, द्रव्य-क्षेत्र-काल-भावकी मर्यादाको लिये हुए रूपी द्रव्यको विषय करनेवाला, किन्तु देव शास्त्र और पदार्थोंको विपरीत रूपसे ग्रहण करनेवाला अवधिज्ञान केवलज्ञानियोंके द्वारा प्रतिपादित आगममें विभंग कहा जाता है। यह विभंग ज्ञान तिर्यंचगति और मनुष्यगतिमें तीव्र कायक्लेश रूप द्रव्य संयमसे उत्पन्न होता है इसलिए गुणप्रत्यय है। 'च' शब्दसे देवगति और नरकगतिमें भवप्रत्यय है तथा मिथ्यात्व आदि कर्मोंके बन्धका बीज है। 'च' शब्दसे कदाचित् नरकगति आदिमें पूर्वजन्ममें किये गये दुराचारोंसे संचित खोटे कर्मोंके फल तीव्र दुःख वेदनाके भोगनेसे होनेवाले सम्यग्दर्शन सम्यग्ज्ञान रूप धर्मका भी बीज है।

स्पर्शनरसनघ्राणचक्षुश्श्रोत्रंगळुमेंबिवरिंदं जातं पुट्टिदुदक्कुमिदरिंदमिंद्रियमनस्सुगळ्गे मतिज्ञानोत्पत्ति-कारणत्वं पेळल्पट्टुदितु कारणभेदात् कार्य्यभेदः एंदितु मतिज्ञानं षट्प्रकारमें दु पेळल्पट्टुदु।

मत्ते प्रत्येकमों दों दु मतिज्ञानक्के अवग्रहमुमीहेयवायमुं धारणे एंदितु नाल्कु नाल्कु भेदंगळ-प्पुवु-अ मदें तें दोडे :—मानसोऽवग्रहः मानसीहा मानसोऽवायः मानसी धारणा एंदितु नाल्कप्पुवु ४। स्पर्शनजोऽवग्रहः स्पर्शनजेहे स्पर्शनजोऽवायः स्पर्शनजा धारणा एंदितु नाल्कप्पुवु ४। रसनजोऽवग्रहः रसनजेहा रसनजोऽवायः रसनजा धारणा एंदितितु नाल्कप्पुवु ४। घ्राणजोऽवग्रहः घ्राणजेहा घ्राणजोऽवायः घ्राणजा धारणा एंदितु नाल्कप्पुवु ४। चाक्षुषोऽवग्रहः चाक्षुषीहा चाक्षुषोऽवायः चाक्षुषी धारणा एंदितुनाल्कप्पुवु ४। श्रोत्रजोऽवग्रहः श्रोत्रजेहा श्रोत्रजोऽवायः श्रोत्रजा धारणा एंदितितु नाल्कप्पुवु ४ । इंतु मतिज्ञानं चतुर्व्विंशतिप्रकारमक्कु २४। मवग्रहादिगळ्गे लक्षणमं मुंदे शास्त्रकारं ताने पेळ्वपं।

वेंजणअत्थअवग्गह भेदा हु हवंति पत्तपत्तत्थे।
कमसो ते वावरिदा पढमं णहि चक्खुमणसाणं ॥३०७॥

व्यंजनार्थावग्रहभेदौ खलु भवतः प्राप्ताप्राप्तार्थयोः। क्रमशस्तौ व्यापृतौ प्रथमो न हि चक्षुर्म्मनसोः॥

इन्द्रियाणि स्पर्शनरसनघ्राणचक्षुःश्रोत्राणि। तेभ्यो जातमुत्पन्नं अनिन्द्रियेन्द्रियजं, अनेन इन्द्रियमनसोर्मति-ज्ञानोत्पत्तिकारणत्वं दर्शितम्। एवं च कारणभेदात्कार्यभेद इति मतिज्ञानं षट्प्रकारमुक्तम्। पुनः प्रत्येकमेकैकस्य मतिज्ञानस्य अवग्रहः ईहा अवायः धारणा चेति चत्वारो भेदा भवन्ति। तद्यथा—मानसोऽवग्रहः मानसीहा मानसोऽवायः मानसी धारणा इति चत्वारः। स्पर्शनजोऽवग्रहः, स्पर्शनजा ईहा स्पर्शनजोऽवायः स्पर्शनजा धारणा इति चत्वारः। रसनजोऽवग्रहः रसनजा ईहा रसनजोऽवायः रसनजा धारणा इति चत्वारः। घ्राणजोऽवग्रहः घ्राणजा ईहा घ्राणजोऽवायः घ्राणजा धारणा इति चत्वारः। चाक्षुषोऽवग्रहः चाक्षुषीहा चाक्षुषोऽवायः चाक्षुषी धारणा ४। श्रोत्रजोऽवग्रहः श्रोत्रजा ईहा श्रोत्रजोऽवायः श्रोत्रजा धारणा इति चत्वारः। एवं मतिज्ञानं चतुर्विंशतिविकल्पं[3] भवति अवग्रहादीनां लक्षणं[4] उत्तरत्र ग्रन्थकारः स्वयमेव वक्ष्यति ॥३०६॥

होती है। अर्थात् सूक्ष्म परमाणु आदि, अन्तरित शंख चक्रवर्ती आदि तथा दूरार्थ मेरु आदि-को जाननेकी शक्ति उनमें नहीं है। इससे मतिज्ञानका स्वरूप कहा। वह मतिज्ञान अनिन्द्रिय मन और इन्द्रियाँ स्पर्शन, रसना, घ्राण, चक्षु, श्रोत्रसे उत्पन्न होता है। इससे इन्द्रिय और मनको मतिज्ञानकी उत्पत्तिका कारण दिखलाया है। इस प्रकार कारणके भेदसे कार्यमें भेद होनेसे मतिज्ञान छह प्रकारका कहा। पुनः प्रत्येक मतिज्ञानके अवग्रह, ईहा, अवाय और धारणा ये चार भेद होते हैं। यथा—मानस अवग्रह, मानस ईहा, मानस अवाय और मानसी धारणा। स्पर्शनजन्य अवग्रह, स्पर्शनजन्य ईहा, स्पर्शनजन्य अवाय और स्पर्शनजन्य धारणा। रसनाजन्य अवग्रह, रसनाजन्य ईहा, रसनाजन्य अवाय और रसनाजन्य धारणा। घ्राणज अवग्रह, घ्राणज ईहा, घ्राणज अवाय और घ्राणज धारणा। चाक्षुष अवग्रह, चाक्षुषी ईहा, चाक्षुष अवाय और चाक्षुषी धारणा। श्रोत्रजन्य अवग्रह, श्रोत्रजन्य ईहा, श्रोत्रजन्य अवाय और श्रोत्रजन्य धारणा। इस प्रकार मतिज्ञानके चौबीस भेद होते हैं। अवग्रह आदिका लक्षण आगे ग्रन्थकार स्वयं ही कहेंगे ॥३०६॥

१. ब कारत्वमुक्तं। २. ब षोढा कथितं। ३. ब °त्रिभेद°। ४. ब णयमे शास्त्रकारः।

ईहणकरणेण जदा सुणिण्णओ होदि सो अवाओ दु।
कालंतरेवि णिण्णिदवत्थुसुमरणस्स कारणं तुरियं ॥३०९॥

ईहनकरणेन यदा सुनिर्णयो भवति सोऽवायस्तु। कालांतरेपि निर्णीतवस्तुस्मरणस्य कारणं तुर्यं ॥

ईहनकरणेन विशेषाकांक्षाकरणदिदं बळिक्कं यदा आगळोम्में ईहितविशेषार्थद सुनिर्णयः उत्पतननिपतनपक्षविक्षेपादिचिह्नंगळिंदमिदु बलाकेये यें दिदु बलाकात्वक्कये आवुदों दु सुनिश्चयमक्कुमागळु सः अदु अवाय इति अवायमें दिदु अवयवोत्पत्तिरवायः एंब व्यपदेशमक्कुं। तु शब्दं वेरगाकांक्षितविशेषक्केये सुनिर्णयमवायमें दितवधारणार्थमिदरिदं विपर्य्यासदिदं निर्णयं मिथ्याज्ञानतेयिदमवायमें तें दिदु ग्राह्यमक्कुमल्लि बळिक्कं स एवावायः आ अवायमे पुनः पुनः प्रवृत्तिरूपाभ्यासजनितसंस्कारात्मकमागि कालांतरदोळं निर्णीतवस्तुस्मरणकारणत्वदिदं तुरियं चतुर्थं धारणाख्यं ज्ञानं भवेदक्कुं।

बहुबहुविहं च खिप्पाणिस्सिदणुत्तं धुवं च इदरं च।
तत्थेक्केक्के जादे छत्तीसं तिसयभेदं तु ॥३१०॥

बहुबहुविधक्षिप्रानिःसृतानुक्तध्रुवं चेतरं च। तत्रैकैकस्मिन् जाते षट्त्रिंशत्त्रिशतभेदं तु ॥

अर्त्थमुं व्यंजनमुमें ब मतिज्ञानविषयं द्वादशप्रकारमक्कुमें तें दोडे बहुर्बहुविधः क्षिप्रोऽनिःसृतोऽनुक्तो ध्रुवश्चेति। यें दु षट्प्रकारमुं। एक एकविधोऽक्षिप्रोऽनिःसृत उक्तोऽध्रुवश्चेति। यें दु षट्प्रकारमितरभेदमुं कूडि द्वादशविधमक्कुमल्लि बह्वादिद्वादशविषयभेदंगळोळु एकैकस्मिन्

ईहनकरणेन-विशेषाकाङ्क्षाक्रियायाः पश्चात् यत्र ईहितविशेषार्थस्य सुनिर्णयः उत्पतननिपतनपक्षविक्षेपादिभिश्चिह्नैः इयं बलाकैवेति बलाकात्वस्य यः सुनिश्चयो भवेत् तदा सः अवाय इति व्यपदिश्यते। तुशब्दः प्रागाकाङ्क्षितविशेषस्यैव सुनिर्णयोऽवाय इत्यवधारणार्थः। अनेन विपर्यासेन निर्णयो मिथ्याज्ञानतया अवायो न भवतीति ग्राह्यम्। ततः स एवावायः पुनः पुनः प्रवृत्तिरूपाभ्यासजनितसंस्कारात्मको भूत्वा कालान्तरेऽपि निर्णीतवस्तुस्मरणकारणत्वेन तुर्यं चतुर्थं धारणाख्यं ज्ञानं भवति ॥३०९॥

अर्थो व्यञ्जनं वा मतिज्ञानविषयः बहुः बहुविधः क्षिप्रः अनिःसृतः अनुक्तः ध्रुवश्चेति षोढा। तथा इतरोऽपि एकः एकविधः अक्षिप्रः निःसृतः उक्तः अध्रुवश्चेति षोढा एवं द्वादशधा भवति। तत्र द्वादशस्वपि

विशेषकी आकांक्षारूप ईहा ज्ञानके पश्चात् जब ईहित विशेष अर्थका सुनिर्णय हो जाता है। जैसे ऊपर-नीचे होने तथा पंखोंके हिलाने आदि चिह्नोंसे यह बलाका ही है इस प्रकार निश्चयके होनेको अवाय कहते हैं। 'तु' शब्द पहले आकांक्षा किये गये विशेष वस्तुके निर्णयको ही अवाय कहते हैं यह अवधारणके लिए है। इससे यह ग्रहण करना चाहिए कि वस्तु तो कुछ और है और निर्णय अन्य वस्तुका किया तो वह अवाय नहीं है। वही अवाय बार-बार प्रवृत्तिरूप अभ्याससे उत्पन्न संस्काररूप होकर कालान्तरमें भी निर्णीत वस्तुके स्मरणमें कारण होता है तो धारण नामक चतुर्थ ज्ञान होता है ॥२०९॥

अर्थ या व्यंजनरूप मतिज्ञानका विषय बारह प्रकारका होता है—बहु, बहुविध, क्षिप्र, अनिसृत, अनुक्त, ध्रुव ये छह तथा इनके प्रतिपक्षी एक, एकविध, अक्षिप्र, निसृत, उक्त

---

१. ब स अवयवोत्पादः अवाय। २. ब काङ्क्षालक्षित वि°। ३. °हां पश्चात् स°।

[1]घ्राणसिगनावासदोळग्नियुंटागुत्तिरले पुट्टिद धूमं काणल्पट्टुदु अनग्निह्रुददोळ् धूममनुपपन्नं निश्चितमक्कें सर्व्वदेशसर्व्वकालसंबंधितेयिंदमग्नि धूमंगळ अन्यथानुपपत्तिरूपाऽविनाभावसंबंधक्के ज्ञानं तर्क्कमें बुदक्कुं अदुवुं मतिज्ञानमक्कुमितनुमानस्मृतिप्रत्यभिज्ञानतर्क्काख्यंगळ् नाल्कुं मतिज्ञानंगळुमनिःसृतार्त्थविषयंगळ् केवलपरोक्षंगळेकेंदोडेकदेशदिदमुं वैशद्याभावमप्पुदरिदं। शेषस्पर्शनादींद्रियानिंद्रियव्यापारप्रभवंगळप्प बह्वाद्यर्त्थविषयमतिज्ञानंगळु सांव्यवहारिकप्रत्यक्षंगळप्पुवेकें-दोडेकदेशदिदं वैशद्यसंभवदिदं प्रत्यक्षं विशदज्ञानमेंदितु पूर्व्वाचार्य्यरुगळिदं प्रत्यक्षक्के लक्षणं पेळल्पट्टुदप्पुदरिदं। यितवेल्लमुं मतिज्ञानंगळ् प्रमाणंगळप्पुवेकेंदोडे सम्यग्ज्ञानत्वदिदं सम्यग्ज्ञानं प्रमाणमेंदितु प्रवचनदोळ् पेळल्पट्टुदरिदं।

एक्कचउक्कं चउवीसट्ठावीसं च तिप्पडिं किच्चा।
इगिछव्वारसगुणिदे मदिणाणे होंति ठाणाणि ॥३१४॥

एकं चत्वारि चतुर्विंशतिमष्टाविंशतिं च त्रिः प्रति कृत्वा। एक षड्द्वादशगुणिते मतिज्ञाने भवन्ति स्थानानि ॥

यथा अत्र इत्यर्थद्योतको वाशब्दः उदाहरणप्रदर्शने प्रयुक्तः अनन्तरगाथोक्तानिसृतार्थज्ञानस्य एतावन्त्युदाहरणानि। पक्षान्तरसूचको वा। यथा महानसे अग्नौ सत्येव धूम उत्पन्नो दृष्टः। ह्रदे अग्न्यभावे धूमोऽनुपपन्नो निश्चितः। तथैव सर्वदेशकालसंबन्धितया अग्निधूमयोरन्यथानुपपत्तिरूपस्य अविनाभावसंबन्धस्य ज्ञानं तर्कः सोऽपि मतिज्ञानं भवति। एवमनुमानस्मृतिप्रत्यभिज्ञानतर्काख्यानि चत्वारि मतिज्ञानानि अनिसृतार्थविषयाणि केवलं परोक्षाणि एकदेशतोऽपि वैशद्याभावात्। शेषाणि स्पर्शनादीन्द्रियानिन्द्रियव्यापारप्रभवानि बह्वाद्यर्थविषयाणि मतिज्ञानानि सांव्यवहारिकप्रत्यक्षाणि एकदेशतो वैशद्यसंभवात्। प्रत्यक्षं विशदं ज्ञानमिति पूर्वाचार्यैः प्रत्यक्षलक्षण[2]स्योक्तत्वात्। तानि सर्वाणि अपि मतिज्ञानानि प्रमाणानि सम्यग्ज्ञानत्वात्। सम्यग्ज्ञानं प्रमाणं, इति प्रवचने प्रतिपादनात् ॥३१३॥

गाथामें कहे अनिसृत अर्थके ज्ञानके ये उदाहरण हैं। अथवा वा शब्द पक्षान्तरका सूचक है। जैसे रसोई घरमें अग्निके होनेपर ही धूम देखा जाता है। तालाबमें अग्निका अभाव होनेसे धूम भी नहीं होता। तथा सर्वदेश और सर्वकाल सम्बन्धी रूपसे आग और धूमके अन्यथानुपपत्तिरूप अविनाभाव सम्बन्ध—कि जहाँ-जहाँ धूम होता है वहाँ-वहाँ अग्नि होती है। जहाँ आग नहीं होती वहाँ धूम भी नहीं होता—का ज्ञान तर्क है। यह भी मतिज्ञान है। इस प्रकार अनुमान, स्मृति, प्रत्यभिज्ञान और तर्क नामक चारों ज्ञान मतिज्ञान हैं। ये चारों अनिसृत अर्थको विषय करते हैं इससे केवल परोक्ष हैं, एकदेशसे भी इनमें स्पष्टताका अभाव है। शेष स्पर्शन आदि इन्द्रियों और मनके व्यापारसे उत्पन्न होनेवाले तथा बहु आदि अर्थको विषय करनेवाले मतिज्ञान सांव्यवहारिक प्रत्यक्ष हैं क्योंकि एकदेशसे स्पष्ट होते हैं। स्पष्ट ज्ञानको प्रत्यक्ष कहते हैं। इस प्रकार पूर्वाचार्योंने प्रत्यक्षका लक्षण कहा है। ये सब मतिज्ञान प्रमाण हैं क्योंकि सम्यग्ज्ञान है। 'सम्यग्ज्ञान प्रमाण है' ऐसा आगममें कहा है ॥३१३॥

१. ब प्रमाण। २. ब °स्यकथनात्।

[illegible]

[illegible]

[illegible]

[illegible]

अल्लि श्रुतज्ञानक्कनक्षरात्म अक्षरात्मकभेददिदं द्विभेदमक्कु मल्लि अनक्षरात्मकमप्प श्रुतभेददोळु पर्य्यायपर्य्यायसमासलक्षणसर्व्वजघन्यज्ञानं मोदल्गोंडु स्वोत्कृष्टपर्य्यंतं असंख्येयलोकमात्राज्ञानविकल्पंगळप्पुववुमसंख्येयलोकमात्रवारषट्स्थानवृद्धियिदं संवृद्धंगळप्पुवु। अक्षरात्मकं श्रुतज्ञानं द्विरूपवर्गधारोत्पन्नषष्ठवर्गमप्पे कट्टमेंब पेसरनुळ्ळोड्डिढनोळेनितोळवु रूपुगळनितुमेकरूपोनंगळप्पुवुमनितुमक्षरंगळुमपुनरुक्ताक्षरंगळनाश्रयिसि संख्यातविकल्पमक्कुं। विवक्षितार्त्थाभिव्यक्तिनिमित्तपुनरुक्ताक्षरग्रहणदोळिदं नोडलधिकप्रमाणमुमक्कुमें बुदत्थं।

अनंतरं श्रुतज्ञानक्के प्रकारांतरदिदं भेदप्ररूपणात्थंमागि गाथाद्वयमं पेळ्दपं :—

पज्जायक्खरपदसंघादं पडिवत्तियाणि जोगं च।
दुगवारपाहुडं च य पाहुडयं वत्थु पुव्वं च ॥३१७॥

पर्य्यायाक्षरपदसंघातं प्रतिपत्तिकानुयोगं च। द्विकवारप्राभृतं च च प्राभृतकं वस्तुपूर्वं च॥

तेसिं च समासेहि य वीसविहं वा हु होदि सुदणाणं।
आवरणस्स वि भेदा तत्तियमेत्ता हवंतित्ति ॥३१८॥

तेषां च समासैश्च विंशतिविधं वा हि भवति श्रुतज्ञानं। आवरणस्यापि भेदास्तावन्मात्रा भवंतीति॥

श्रुतज्ञानस्य अनक्षरात्मकाक्षरात्मकौ द्वौ भेदौ, तत्र अनक्षरात्मके श्रुतज्ञाने पर्यायपर्यायसमासलक्षणे सर्वजघन्यज्ञानमादिं कृत्वा स्वोत्कृष्टपर्यन्तं असंख्येयलोकमात्रा ज्ञानविकल्पा भवन्ति। ते च असंख्येयलोकमात्रवारषट्स्थानवृद्धया संवर्धिता भवन्ति। अक्षरात्मकं श्रुतज्ञानं द्विरूपवर्गधारोत्पन्नषष्ठवर्गस्य एकट्ठनाम्नो यावन्ति रूपाणि एकरूपोनानि सन्ति तावन्ति अक्षराणि अपुनरुक्ताक्षराण्याश्रित्य संख्यातविकल्पं भवति। विवक्षितार्थाभिव्यक्तिनिमित्तं पुनरुक्ताक्षरग्रहणे ततोऽधिकप्रमाणं भवतीत्यर्थः ॥३१६॥ अथ श्रुतज्ञानस्य प्रकारान्तरेण भेदान् गाथाद्वयेनाह—

श्रुतज्ञानके अक्षरात्मक और अनक्षरात्मक ये दो भेद हैं। अनक्षरात्मक श्रुतज्ञानके पर्याय और पर्यायसमास दो भेद हैं। इसमें सर्वजघन्य ज्ञानसे लेकर अपने उत्कृष्ट पर्यन्त असंख्यात लोक प्रमाण ज्ञानके भेद होते हैं। वे भेद असंख्यात लोकमात्र बार षट्स्थानपतित वृद्धिको लिये हुए हैं। अक्षरात्मक श्रुतज्ञानके संख्यात भेद हैं। सो द्विरूप वर्गधारामें उत्पन्न छठे वर्गका, जिसका प्रमाण एकट्ठी है उसके प्रमाणमें-से एक कम करनेपर जितने अपुनरुक्त अक्षर होते हैं उतने हैं। इसका आशय यह है कि विवक्षित अर्थको प्रकट करनेके लिए पुनरुक्त अक्षरोंके ग्रहण करनेपर उससे अधिक प्रमाण हो जाता है ॥३१६॥

विशेषार्थ—दोसे लेकर वर्ग करते जानेको द्विरूपवर्गधारा कहते हैं। जैसे दोका प्रथम वर्ग चार होता है। चारका वर्ग सोलह होता है। सोलहका वर्ग दो सौ छप्पन होता है। दो सौ छप्पनका वर्ग पैंसठ हजार पाँच सौ छत्तीस होता है जिसको पण्णट्ठी कहते हैं। पण्णट्ठीका वर्ग बादाल और बादालका वर्ग एकट्ठी प्रमाण होता है यही छठा वर्गस्थान है। इसमें एक कम करनेसे श्रुतज्ञानके समस्त अपुनरुक्त अक्षर होते हैं। उतने ही अक्षरात्मक श्रुतज्ञानके भेद हैं।

अब अन्य प्रकारसे श्रुतज्ञानके भेद दो गाथाओंसे कहते हैं—

पोसतप्प विशेषमरियल्पडुगुमदावुदें दोडे पर्य्यायमें ब प्रथमश्रुतज्ञानं तु मत्ते सूक्ष्मनिगोदलब्ध्यपर्य्याप्तकन संबंधि सर्व्वजघन्यश्रुतज्ञानमक्कुं। पुनः मत्ते पर्य्यायज्ञानदावरणमुं तदनंतरज्ञानभेददोळनंतभागवृद्धियुक्तपर्य्यायसमासज्ञानप्रथमभेददोळक्कुमदें तें दोडे उदयागतपर्य्यायज्ञानावरणसमयप्रबद्धदुदयनिषेकदनुभागंगळ सर्व्वघातिस्पर्द्धकंगळुदयाभावलक्षणक्षयमुमवक्केये सदवस्थालक्षणोपशममुं देशघातिस्पर्द्धकंगळुदयमुमुंटागुत्तिरलुमंतप्पावरणोदर्यादिदं पर्य्यायसमासप्रथमज्ञानमे यावरणिसल्पडुगुं। तुमत्ते पर्यायज्ञानमावरणिसल्पडदेकें दोडे तदावरणदोळु जीवगुणमप्प ज्ञानक्काभावमागुत्तिरलु गुणियप्पजीवक्केयुमभावप्रसंगमक्कुमप्पुदरिदं।

अनुभागरचनेयं स्थापिसल्पट्टल्लि सिद्धानंतैकभागमात्रद्रव्यानुभागक्रमहानिवृद्धियुक्तनानागुणहानिस्पर्द्धकवर्ग्गणात्मकमप्प श्रुतज्ञानावरणद्रव्यदल्लि सर्व्वतःस्तोकमप्प सर्व्वपश्चिमप्रक्षीणोदयानुभागसर्व्वघातिस्पर्द्धकद्रव्यमक्केयो पर्य्यायज्ञानावरणस्वर्विदं तावन्मात्रावरणद्रव्यक्के सर्व्वकालदोळमुदयाभावमप्पुदरिदं।

नवीनं विशेषं जानीहि, सः कः ? पर्यायज्ञानं—पर्यायाख्यं प्रथमं श्रुतज्ञानं, तु—पुनः, सूक्ष्मनिगोदलब्ध्यपर्याप्तकस्य संबन्धि सर्वजघन्यं श्रुतज्ञानं भवति। पुनः—पश्चात् पर्यायज्ञानस्य आवरणं तदनन्तरज्ञानभेदे अनन्तभागवृद्धियुक्ते पर्यायसमासज्ञानप्रथमभेदे भवति, तद्यथा—उदयागतपर्यायज्ञानावरणसमयप्रबद्धोदयनिषेकस्यानुभागानां सर्वघातिस्पर्धकानामुदयाभावलक्षणः क्षयः, तेषामेव सदवस्थालक्षण उपशमः, देशघातिस्पर्धकानामुदये सति तदावरणोदयेन पर्यायसमासप्रथमज्ञानमेव आव्रियते न तु पर्यायज्ञानम्। तदावरणे जीवगुणस्य ज्ञानस्याभावे गुणिनो जीवस्याप्यभावप्रसंगात्। अनुभागरचनायां विन्यस्ते सिद्धानन्तैकभागमात्रे द्रव्यानुभागक्रमहानिवृद्धियुक्ते नानागुणहानिस्पर्धकवर्गणात्मके श्रुतज्ञानावरणद्रव्ये सर्वतः स्तोकस्य सर्वपश्चिमप्रक्षीणोदयानुभागसर्वघातिस्पर्धकद्रव्यस्यैव पर्यायज्ञानावरणत्वात्। तावतः आवरणद्रव्यस्य सर्वकालेऽप्युदयाभावात् ॥३१९॥

यह विशेष जानना कि पर्याय नामक प्रथम श्रुतज्ञान सूक्ष्म निगोदिया लब्ध्यपर्याप्तकका सबसे जघन्य श्रुतज्ञान होता है। किन्तु पर्यायज्ञानका आवरण उसके अनन्तर जो ज्ञानका भेद है, जो उससे अनन्तभागवृद्धिको लिये हुए है उस पर्याय समास ज्ञानके प्रथम भेदपर होता है। जो इस प्रकार है—उदयप्राप्त पर्याय ज्ञानावरणके समयप्रबद्धका जो निषेक उदयमें आया है उसके अनुभागके सर्वघाती स्पर्द्धकोंके उदयका अभाव ही क्षय है तथा जो अगले निषेक सम्बन्धी सर्वघाती स्पर्द्धक सत्तामें वर्तमान है उनका उपशम है और देशघाती स्पर्धकोंका उदय है। ऐसा क्षायोपशम पर्याय ज्ञानावरणका सदा रहता है। अतः पर्याय ज्ञानावरणके उदयसे पर्याय समास ज्ञानका प्रथम भेद ही आवृत होता है, पर्यायज्ञान नहीं। यदि उसका भी आवरण हो जाये तो जीवके गुण ज्ञानका अभाव होनेपर गुणी जीवके भी अभावका प्रसंग आता है। तथा अनुभाग रचनामें स्थापित किया सिद्ध राशिका अनन्तवाँ भागमात्र जो श्रुतज्ञानावरणका द्रव्य अर्थात् परमाणुसमूह है वह क्रम हानि और वृद्धिसे संयुक्त है, नाना गुणहानि स्पर्धक वर्गणात्मक है, उस श्रुतज्ञानावरणके द्रव्यमें जिसका उदयरूप अनुभाग क्षीण हो गया है और जो सबसे थोड़ा तथा सबसे अन्तिम सर्वघाति स्पर्धक है उसीका नाम पर्यायज्ञानावरण है। इतने आवरणका कभी भी उदय नहीं होता। इसलिए भी पर्यायज्ञान निरावरण है ॥३१९॥

यद्दुपर्य्याप्तभवभ्रमणसंभूतबहुतमसंक्लेशवृद्धियिंदमावरणक्के तीव्रानुभागोदयसंभवमप्पुदरिदं । द्वितीयादिसमयंगळोळु ज्ञानदर्शनवृद्धि संभवमेंदितु त्रिवक्रप्रथमवक्रसमयदोळे पर्य्यायज्ञानसंभव-मरियल्पड्गुं ।

सुहुमणिगोद अपज्जत्तयस्स जादस्स पढमसमयम्मि ।
फासिंदियमदिपुव्वं सुदणाणं लद्धिअक्खरयं ॥३२२॥

सूक्ष्मनिगोदापर्य्याप्तकस्य जातस्य प्रथमसमये । स्पर्शनेंद्रियमतिपूर्वं श्रुतज्ञानं लब्ध्यक्षरकं ॥

सूक्ष्मनिगोदलब्ध्यपर्य्याप्तकन जननप्रथमसमयदोळु सर्व्वजघन्यस्पर्शनेंद्रियमतिज्ञानपूर्व्वकमप्प लब्ध्यक्षरपरनामधेयमप्प पूर्व्वोक्तचरमभवत्रिवक्रप्रथमसमयादिविशेषणविशिष्टमप्प सर्व्वजघन्य-पर्य्यायश्रुतज्ञानमक्कुमेंदितु ज्ञातव्यमक्कु । लब्धि एंबुदु श्रुतज्ञानावरणक्षयोपशममक्कुमर्थग्रहण-शक्तियेनु लब्ध्या अक्षरमविनश्वरं लब्ध्यक्षरं तावन्मात्रक्षयोपशमक्के सर्वदा विद्यमानत्वदिदं ।

अनंतरं दशगाथासूत्रंगळिदं पर्य्यायसमासप्रकरणमं पेळ्दपं :—

अवरुवरिम्मि अणंतमसंखं संखं च भागवड्ढीओ ।
संखमसंखमणंतं गुणवड्ढी होंति हु कमेण ॥३२३॥

अवरोपर्य्यनंतमसंख्यं संख्यं च भागवृद्धयः । संख्यमसंख्यमनंतं गुणवृद्धयो भवंति हि क्रमेण ॥

सर्व्वजघन्यपर्य्यायज्ञानदमेले क्रमेण वक्ष्यमाणपरिपाटियिंदमनंतभागवृद्धियुमसंख्यातभाग-वृद्धियुं संख्यातभागवृद्धियुं संख्यातगुणवृद्धियुमसंख्यातगुणवृद्धियुमनंतगुणवृद्धियुमेंदितु षट्स्थान-

---

भवति । बहुतरपर्याप्तभवभ्रमणसंभूतबहुतमसंक्लेशवृद्धया आवरणस्य तीव्रतमानुभागोदयसंभवात्, द्वितीयादि-समयेषु ज्ञानदर्शनवृद्धिसंभवात् 'त्रिवक्रप्रथमवक्रसमये एव पर्यायज्ञानसंभवो ज्ञातव्यः ॥३२१॥

सूक्ष्मनिगोदलब्ध्यपर्याप्तकस्य जननप्रथमसमये सर्वजघन्यस्पर्शनेन्द्रियमतिज्ञानपूर्वकं लब्ध्यक्षरापरनामधेयं 'पूर्वोक्तचरमभवत्रिवक्रप्रथमसमयादिविशेषणविशिष्टं' सर्वजघन्यं पर्यायश्रुतज्ञानं भवतीति ज्ञातव्यम् । लब्धिर्नाम-श्रुतज्ञानावरणक्षयोपशमः अर्थग्रहणशक्तिर्वा, लब्ध्या अक्षरं अविनश्वरं लब्ध्यक्षरं तावतः क्षयोपशमस्य सर्वदा विद्यमानत्वात् ॥३२२॥ अथ दशभिर्गाथाभिः पर्यायसमासप्रकरणं प्ररूपयति—

सर्वजघन्यपर्यायज्ञानस्य उपरि क्रमेण वक्ष्यमाणपरिपाट्या अनन्तभागवृद्धिः असंख्यातभागवृद्धिः

संक्लेशके बढ़नेसे आवरणके तीव्रतम अनुभागका उदय होता है, तथा दूसरे मोड़े आदिके समयोंमें ज्ञान और दर्शनमें वृद्धि सम्भव है। इसलिए तीन मोड़ोंमें-से प्रथम मोड़ेके समयमें ही पर्याय ज्ञान जानना ॥३२१॥

सूक्ष्म निगोद लब्ध्यपर्याप्तक जीवके जन्म लेनेके प्रथम समयमें सबसे जघन्य स्पर्शन इन्द्रियजन्य मतिज्ञानपूर्वक तथा पूर्वोक्त विशेषणोंसे विशिष्ट सबसे जघन्य पर्याय श्रुतज्ञान होता है। उसका दूसरा नाम लब्ध्यक्षर है। श्रुतज्ञानावरणके क्षयोपशमको अथवा अर्थको ग्रहण करनेकी शक्तिको लब्धि कहते हैं। लब्धिसे जो अक्षर अर्थात् अविनाशी होता है वह लब्ध्यक्षर है; क्योंकि इतना क्षयोपशम सदा विद्यमान रहता है ॥३२२॥

अब दस गाथाओंसे पर्यायसमासका कथन करते हैं—

सबसे जघन्य पर्यायज्ञानके ऊपर आगे कही गयी परिपाटीके अनुसार अनन्तभागवृद्धि,

द्विवारलिखितोर्व्वंकादिकमंगुलासंख्यातेकवारसंदृष्टिः।

मत्तमिल्लि सर्व्वजघन्यमप्प श्रुतज्ञानं पर्य्यायमें ब लब्ध्यक्षरापरनामधेयस्थानद मुंदण पर्य्यायसमासज्ञानविकल्पंगळनंतेकभागवृद्धियुक्तस्थानंगळु सूच्यंगुलासंख्यातेकभागमात्रविकल्पंगळप्पुववर वृद्धिप्रमाण क्रमविधानप्ररूपणं माडल्पडुमुमदें तें दोडनंतगुणजीवराशिप्रमितस्वार्त्थंप्रकाशनशक्त्यविभागप्रतिच्छेदात्मकसर्व्वंजघन्यश्रुतज्ञानमं। ज। एंदितु संस्थापिसि मत्तमा राशियं सर्व्वजीवराशियप्पनंतदिदं भागिसि तदेकभागमं तज्जघन्यज्ञानदोळे समच्छेदमं माडि कूडुत्तमिरलदु

अथानन्तभागवृद्धेरङ्गुलासंख्यातभागमात्रवारान् वृत्तिक्रमो दर्श्यते तद्यथा—अनन्तगुणजीवराशिमात्रस्वार्थप्रकाशनशक्त्यविभागप्रतिच्छेदात्मकं सर्वजघन्यश्रुतज्ञानं ज इति संदृष्ट्या संस्थाप्य तं राशिं सर्वजीवराशिरूपानन्तेन भक्त्वा तदेकभागे ज तज्जघन्यस्योपरि समच्छेदेन युते सति यो राशिर्जायते स पर्यायसमासश्रुत-
१६

होती है। उसकी पहचानके लिए यन्त्रमें जैसे प्रथम पंक्ति थी उसी प्रकार उसके नीचे दूसरी पंक्ति लिखी। वहाँसे आगे—तीसरी पंक्ति प्रथम पंक्तिके समान लिखी। इतना विशेष कि नौवें कोठेमें जहाँ दो उकार एक छहका अंक लिखा था वहाँ तीसरी पंक्तिमें नौवें कोठेमें दो उकार और सातका अंक लिखा। वहाँसे आगे जैसे तीनों पंक्तियोंमें आदिसे लेकर अनुक्रमसे वृद्धि हुई उसी अनुक्रमसे सूच्यंगुलके असंख्यातवें भाग प्रमाण होनेपर जब असंख्यात गुण वृद्धि भी सूच्यंगुलके असंख्यातवें भाग प्रमाण हो तब पूर्ति हो। इसीसे यन्त्रमें जैसे प्रथम तीन पंक्तियाँ थीं वैसे ही दूसरी तीन पंक्तियाँ लिखीं। इस तरह छह पंक्तियाँ हुईं। वहाँसे आगे—जैसे आदिसे लेकर तीन पंक्तियोंमें क्रमसे वृद्धियाँ कही थीं वैसे ही क्रमसे पुनः सब वृद्धियाँ हुईं। विशेष इतना कि तीसरी पंक्तिके अन्तमें जहाँ असंख्यात गुण वृद्धि कही थी, उसके स्थानमें यहाँ तीसरी पंक्तिके अन्तमें एक बार अनन्त गुणवृद्धि होती है। इसीसे यन्त्रमें पहली, दूसरी, तीसरीके समान तीन पंक्तियाँ और लिखीं। किन्तु तीसरी पंक्तिके नौवें कोठेमें जहाँ दो उकार और सातका अंक लिखा है उसके स्थानमें यहाँ तीसरी पंक्तिके नौवें कोठेमें दो उकार और आठका अंक लिखा। जो अनन्त गुणवृद्धिका सूचक है। इसके आगे किसी वृद्धिके न होनेसे अनन्त गुणवृद्धि एक ही बार होती है। उसके होनेपर जो प्रमाण हुआ वह षट्स्थान पतित वृद्धिका प्रथम स्थान जानना। इस प्रकार पर्याय समास श्रुतज्ञानमें असंख्यात लोक बार मात्र षट्स्थान पतित वृद्धि होती है।

आगे उक्त कथनको स्पष्ट करते हैं—

सबसे जघन्य पर्याय श्रुतज्ञानके अपने विषयके प्रकाशनरूप शक्तिके अविभाग प्रतिच्छेद जीवराशिसे अनन्तगुणे होते हैं। उस राशिको सब जीवराशिरूप अनन्तसे भाजित करनेपर जो एक भाग आवे उसे उस जघन्य ज्ञानमें मिलानेपर पर्याय समास श्रुतज्ञानके विकल्पोंमें-से सबसे जघन्य प्रथम भेद आता है। यह एक बार अनन्त भाग वृद्धि हुई। फिर उस पर्याय समास ज्ञानके प्रथम विकल्पको जीवराशि प्रमाण अनन्तका भाग देनेपर जो एक भाग आवे उसे पर्याय समास ज्ञानके प्रथम भेदमें मिलानेपर उसका दूसरा भेद होता है। यह दूसरी अनन्त भाग वृद्धि हुई। उस दूसरे भेदको अनन्तका भाग देनेसे जो एक भाग आवे उसे उस दूसरे विकल्पमें मिलानेपर पर्याय समास ज्ञानका तीसरा विकल्प होता है। यह तीसरी अनन्तभाग वृद्धि हुई। फिर इस तीसरे भेदमें अनन्तसे भाग देनेपर जो एक भाग

तिरलु पर्य्यायसमासप्रथमज्ञानविकल्पमक्कु ज $\frac{\overline{१६}}{१६}$ $\frac{\overline{१६}}{१६}$ $\frac{\overline{१६}}{१६}$ $\frac{\overline{१६}}{१६}$ $\frac{\overline{१६}}{१६}$ $\frac{\overline{१६}}{१६}$ मितु सूच्यंगुलासंख्यातेकभागमात्रानंतैकभागवृद्धियुतस्थानंगळु सल्वेमु नडसल्पडुवल्लि तद्वृद्धिगळ्गे तज्जघन्यं

इति पर्य्यायसमासप्रथमज्ञानविकल्पः ज $\frac{\overline{१६}}{१६}$ $\frac{\overline{१६}}{१६}$ $\frac{\overline{१६}}{१६}$ $\frac{\overline{१६}}{१६}$ $\frac{\overline{१६}}{१६}$ $\frac{\overline{१६}}{१६}$ एवं सूच्यंगुलासंख्यातैकभागमात्राणि अनन्तैकभागवृद्धियुक्तस्थानानि सर्वाण्यानेतव्यानि ।

उसीमें मिलानेपर पर्याय समास ज्ञानका भेद होता है। यहाँसे अनन्त भाग वृद्धिका प्रारम्भ हुआ। इसी प्रकार सूच्यंगुलके असंख्यातवें भाग प्रमाण अनन्त भाग वृद्धि होनेपर जो पर्याय समास ज्ञानका भेद हुआ उसमें पुनः असंख्यातसे भाग देनेपर जो परिमाण आया उसको उसी भेदमें मिलानेपर दूसरी असंख्यात भाग वृद्धिको लिये पर्याय समास ज्ञानका भेद होता है।

इसी क्रमसे सूच्यंगुलके असंख्यातवें भाग प्रमाण असंख्यात भाग वृद्धिके पूर्ण होनेपर जो पर्याय समास ज्ञानका भेद हुआ उसमें अनन्तका भाग देनेपर जो परिमाण आवे उसको उसीमें मिलानेपर पर्याय समास ज्ञानका भेद होता है। यहाँ पुनः अनन्त भाग वृद्धिका प्रारम्भ हुआ सो सूच्यंगुलके असंख्यातवें भाग प्रमाण अनन्त भाग वृद्धिके पूर्ण होनेपर जो पर्याय समास ज्ञानका भेद हुआ उसको उत्कृष्ट संख्यातसे भाग देनेपर जो परिमाण आया उसको उसीमें मिलानेपर प्रथम संख्यात भाग वृद्धिको लिये पर्याय समासका भेद होता है। इससे आगे पुनः अनन्त भाग वृद्धि प्रारम्भ होती है। सो जैसे पूर्वमें कहा है उसीके अनुसार वृद्धि जानना। इतना विशेष है कि जिस भेदसे आगे अनन्त भाग वृद्धि होती है उसी भेदमें जीवराशि प्रमाण अनन्तका भाग देनेपर जो परिमाण आवे उसे उसी भेदमें मिलानेपर अनन्तरवर्ती भेद होता है। तथा जिस भेदसे आगे असंख्यात भाग वृद्धि होती है वहाँ उसी भेदको असंख्यात लोक प्रमाण असंख्यातसे भाग देनेपर जो परिमाण आवे उसको उसी भेदमें मिलानेपर उससे अनन्तरवर्ती भेद होता है। तथा जिस भेदसे आगे संख्यात भाग वृद्धि हो वहाँ उसी भेदको उत्कृष्ट संख्यात प्रमाण संख्यातसे भाग देनेपर जो परिमाण आवे उसे उसी भेदमें मिलानेपर उससे आगेका भेद होता है। तथा जिस भेदसे आगे संख्यात गुण वृद्धि होती है वहाँ उस भेदको उत्कृष्ट संख्यातसे गुणा करनेपर उस भेदसे अनन्तरवर्ती भेद होता है। जिस भेदसे आगे असंख्यात गुण वृद्धि होती है वहाँ उसी भेदको असंख्यात लोकसे गुणा करनेपर उससे आगेका भेद होता है। जिस भेदसे आगे अनन्त गुण वृद्धि होती है वहाँ उसी भेदको जीवराशि प्रमाण अनन्तसे गुणा करनेपर उससे आगेका भेद होता है इस प्रकार षट्स्थान पतित वृद्धिका क्रम जानना।

यहाँ जो संख्या कही है सो सब संख्या ज्ञानके अविभागी प्रतिच्छेदोंकी जानना। तथा जो यहाँ भेद कहे हैं उनका भावार्थ यह है कि जीवके पर्याय ज्ञानसे यदि बढ़ता हुआ ज्ञान होता है तो पर्याय समासका प्रथम भेद ही होता है। ऐसा नहीं है कि किसी जीवके पर्यायज्ञानसे एक-दो अविभाग प्रतिच्छेद बढ़ता हुआ भी ज्ञान हो।

तिरलु पर्य्यायसमासप्रथमज्ञानविकल्पमक्कु ज १६/१६ १६/१६ १६/१६ १६/१६ १६/१६ १६/१६ मितु सूच्यंगुलासंख्यातैकभागमात्रानंतैकभागवृद्धियुतस्थानंगळु सर्व्वमु नडसल्पडुत्तुवल्लि तद्वृद्धिगळ्गे तज्जघन्यं

युते पर्यायसमासप्रथमज्ञानविकल्पः ज १६/१६ १६/१६ १६/१६ १६/१६ १६/१६ १६/१६ एवं सूच्यंगुलासंख्यातैकभागमात्राणि अनन्तैकभागवृद्धियुक्तस्थानानि सर्वाण्यानेतव्यानि।

उसीमें मिलानेपर पर्याय समास ज्ञानका भेद होता है। यहाँसे अनन्त भाग वृद्धिका प्रारम्भ हुआ। इसी प्रकार सूच्यंगुलके असंख्यातवें भाग प्रमाण अनन्त भाग वृद्धि होनेपर जो पर्याय समास ज्ञानका भेद हुआ उसमें पुनः असंख्यातसे भाग देनेपर जो परिमाण आया उसको उसी भेदमें मिलानेपर दूसरी असंख्यात भाग वृद्धिको लिये पर्याय समास ज्ञानका भेद होता है।

इसी क्रमसे सूच्यंगुलके असंख्यातवें भाग प्रमाण असंख्यात भाग वृद्धिके पूर्ण होनेपर जो पर्याय समास ज्ञानका भेद हुआ उसमें अनन्तका भाग देनेपर जो परिमाण आवे उसको उसीमें मिलानेपर पर्याय समास ज्ञानका भेद होता है। यहाँ पुनः अनन्त भाग वृद्धिका प्रारम्भ हुआ सो सूच्यंगुलके असंख्यातवें भाग प्रमाण अनन्त भाग वृद्धिके पूर्ण होनेपर जो पर्याय समास ज्ञानका भेद हुआ उसको उत्कृष्ट संख्यातसे भाग देनेपर जो परिमाण आया उसको उसीमें मिलानेपर प्रथम संख्यात भाग वृद्धिको लिये पर्याय समासका भेद होता है। इससे आगे पुनः अनन्त भाग वृद्धि प्रारम्भ होती है। सो जैसे पूर्वमें कहा है उसीके अनुसार वृद्धि जानना। इतना विशेष है कि जिस भेदसे आगे अनन्त भाग वृद्धि होती है उसी भेदमें जीवराशि प्रमाण अनन्तका भाग देनेपर जो परिमाण आवे उसे उसी भेदमें मिलानेपर अनन्तरवर्ती भेद होता है। तथा जिस भेदसे आगे असंख्यात भाग वृद्धि होती है वहाँ उसी भेदको असंख्यात लोक प्रमाण असंख्यातसे भाग देनेपर जो परिमाण आवे उसको उसी भेदमें मिलानेपर उससे अनन्तरवर्ती भेद होता है। तथा जिस भेदसे आगे संख्यात भाग वृद्धि हो वहाँ उसी भेदको उत्कृष्ट संख्यात प्रमाण संख्यातसे भाग देनेपर जो परिमाण आवे उसे उसी भेदमें मिलानेपर उससे आगेका भेद होता है। तथा जिस भेदसे आगे संख्यात गुण वृद्धि होती है वहाँ उस भेदको उत्कृष्ट संख्यातसे गुणा करनेपर उस भेदसे अनन्तरवर्ती भेद होता है। जिस भेदसे आगे असंख्यात गुण वृद्धि होती है वहाँ उसी भेदको असंख्यात लोकसे गुणा करनेपर उससे आगेका भेद होता है। जिस भेदसे आगे अनन्त गुण वृद्धि होती है वहाँ उसी भेदको जीवराशि प्रमाण अनन्तसे गुणा करनेपर उससे आगेका भेद होता है इस प्रकार षट्स्थान पतित वृद्धिका क्रम जानना।

यहाँ जो संख्या कही है सो सब संख्या ज्ञानके अविभागी प्रतिच्छेदोंकी जानना। तथा जो यहाँ भेद कहे हैं उनका भावार्थ यह है कि जीवके पर्याय ज्ञानसे यदि बढ़ता हुआ ज्ञान होता है तो पर्याय समासका प्रथम भेद ही होता है। ऐसा नहीं है कि किसी जीवके पर्यायज्ञानसे एक-दो अविभाग प्रतिच्छेद बढ़ता हुआ भी ज्ञान हो।

रलु पर्य्यायसमासयप्र श्रु तज्ञानविकल्पमक्कु ज १६/१६ १६/१६ १६/१६ १६/१६ १६/१६ १६/१६ मितु सूच्यंगुला-
ख्यातैकभागमात्रानंतैकभागवृद्धियुक्तस्थानंगळु सर्व्वमु नडसल्पडुवुवल्लि तद्वृद्धिगळ्गे तज्जघन्यं

ि पर्यायसमासपष्ठश्रुतज्ञानविकल्पः ज १६/१६ १६/१६ १६/१६ १६/१६ १६/१६ १६/१६ एवं सूच्यङ्गुलासंख्यातैक-
गगमात्राणि अनन्तैकभागवृद्धियुक्तस्थानानि सर्वाण्यानेतव्यानि ।

सीमें मिलानेपर पर्याय समास ज्ञानका भेद होता है। यहाँसे अनन्त भाग वृद्धिका प्रारम्भ आ। इसी प्रकार सूच्यंगुलके असंख्यातवें भाग प्रमाण अनन्त भाग वृद्धि होनेपर जो पर्याय मास ज्ञानका भेद हुआ उसमें पुनः असंख्यातसे भाग देनेपर जो परिमाण आया उसको सी भेदमें मिलानेपर दूसरी असंख्यात भाग वृद्धिको लिये पर्याय समास ज्ञानका भेद ोता है।

इसी क्रमसे सूच्यंगुलके असंख्यातवें भाग प्रमाण असंख्यात भाग वृद्धिके पूर्ण होनेपर ो पर्याय समास ज्ञानका भेद हुआ उसमें अनन्तका भाग देनेपर जो परिमाण आवे उसको सीमें मिलानेपर पर्याय समास ज्ञानका भेद होता है। यहाँ पुनः अनन्त भाग वृद्धिका ारम्भ हुआ सो सूच्यंगुलके असंख्यातवें भाग प्रमाण अनन्त भाग वृद्धिके पूर्ण होनेपर जो र्याय समास ज्ञानका भेद हुआ उसको उत्कृष्ट संख्यातसे भाग देनेपर जो परिमाण आया सको उसीमें मिलानेपर प्रथम संख्यात भाग वृद्धिको लिये पर्याय समासका भेद होता है। सके आगे पुनः अनन्त भाग वृद्धि प्रारम्भ होती है। सो जैसे पूर्वमें कहा है उसीके अनुसार वृद्धि जानना। इतना विशेष है कि जिस भेदसे आगे अनन्त भाग वृद्धि होती है उसी भेदमें जीवराशि प्रमाण अनन्तका भाग देनेपर जो परिमाण आवे उसे उसी भेदमें मिलानेपर अनन्तरवर्ती भेद होता है। तथा जिस भेदसे आगे असंख्यात भाग वृद्धि होती है वहाँ उसी भेदको असंख्यात लोक प्रमाण असंख्यातसे भाग देनेपर जो परिमाण आवे उसको उसी भेदमें मिलानेपर उससे अनन्तरवर्ती भेद होता है। तथा जिस भेदसे आगे संख्यात भाग वृद्धि हो वहाँ उसी भेदको उत्कृष्ट संख्यात प्रमाण संख्यातसे भाग देनेपर जो परिमाण आवे उसे उसी भेदमें मिलानेपर उससे आगेका भेद होता है। तथा जिस भेदसे आगे संख्यात गुण वृद्धि होती है वहाँ उस भेदको उत्कृष्ट संख्यातसे गुणा करनेपर उस भेदसे अनन्तरवर्ती भेद होता है। जिस भेदसे आगे असंख्यात गुण वृद्धि होती है वहाँ उसी भेदको असंख्यात लोकसे गुणा करनेपर उससे आगेका भेद होता है। जिस भेदसे आगे अनन्त गुण वृद्धि होती है वहाँ उसी भेदको जीवराशि प्रमाण अनन्तसे गुणा करनेपर उससे आगेका भेद होता है इस प्रकार षट्स्थान पतित वृद्धिका क्रम जानना।

यहाँ जो संख्या कही है सो सब संख्या ज्ञानके अविभागी प्रतिच्छेदोंकी जानना। तथा जो यहाँ भेद कहे हैं उनका भावार्थ यह है कि जीवके पर्याय ज्ञानसे यदि बढ़ता हुआ ज्ञान होता है तो पर्याय समासका प्रथम भेद ही होता है। ऐसा नहीं है कि किसी जीवके पर्यायज्ञानसे एक-दो अविभाग प्रतिच्छेद बढ़ता हुआ भी ज्ञान हो।

तद्वृद्धिगळप्प प्रक्षेपकंगळारुमं प्रक्षेपकप्रक्षेपकंगळु पदिनैदुमं पिशुलिगळिप्पत्तुमं पिशुलिपिशुलिगळु पदिनैदुमं चूर्णिगळारुमनोंदु चूर्णिचूर्णियुमं यथाक्रमदिदं केळगे केळगे स्थापिसुवुदितनंतभागवृद्धियुक्तस्थानंगळु सूच्यंगुलासंख्यातभागमात्रंगळप्पवरोळं येल्लवक्कं तंतम्म जघन्यंगळ केळगे केळगे तंतम्म प्रक्षेपकंगळु गच्छमात्रंगळप्पुववं स्थापिसि यवर केळगे प्रक्षेपकप्रक्षेपकंगळु रूपोनगच्छेय एकवारसंकलनधनमात्रंगळप्पुववं स्थापिसुवुदवर केळगे पिशुलिगळु द्विरूपोनगच्छेय द्विकवारसंकलनधनमात्रंगळप्पुववं स्थापिसि यवर केळगे पिशुलिपिशुलिगळु त्रिरूपोनगच्छेय त्रिकवारसंकलनधनमात्रंगळप्पुववं स्थापिसि यवर केळगे चूर्णिगळु चतूरूपोनगच्छेय चतुर्वारसंकलनधनमात्रंगळप्पुववं स्थापिसि यवरे केळगे चूर्णिचूर्णिगळु पंचरूपोनगच्छेय पंचवारसंकलनधनमात्रंगळप्पुववं स्थापिसुवुदितु स्थापिसुत्तं पोगुत्तिरलु चरमानंतभागवृद्धियुक्तस्थानविकल्पदोळु

तज्जघन्यमुपरि न्यस्य तदधस्तनभागे तद्वृद्धेः पञ्च प्रक्षेपकान् दश प्रक्षेपकप्रक्षेपकान् दश पिशुलीन् पञ्च पिशुलिपिशुलीन् एकं चूर्णि च अधोधो न्यसेत्। षष्ठविकल्पे तज्जघन्यमुपरि न्यस्य तदधस्तनभागे तद्वृद्धेः षट् प्रक्षेपकान् पञ्चदश प्रक्षेपकप्रक्षेपकान् विंशति पिशुलीन् पञ्चदश पिशुलिपिशुलीन् षट् चूर्णीन् एकं चूर्णिचूर्णि च अधोधो न्यस्येत्, एवमनन्तभागवृद्धियुक्तस्थानेषु सूच्यङ्गुलासंख्येयभागमात्रेषु सर्वेष्वपि स्वस्वजघन्यानामधः स्वस्वप्रक्षेपकान् गच्छमात्रान् न्यसेत्, तेषामधः प्रक्षेपकप्रक्षेपकान् रूपोनगच्छस्य एकवारसंकलनधनमात्रान् न्यस्येत्। तेषामधः पिशुलीन् द्विरूपोनगच्छस्य द्विकवारसंकलनधनमात्रान् न्यस्येत्। तेषामधः पिशुलिपिशुलीन् त्रिरूपोनगच्छस्य त्रिकवारसंकलनधनमात्रान् न्यस्येत्, तेषामधः चूर्णीन् चतूरूपोनगच्छस्य चतुर्वारसंकलनधनमात्रान् न्यस्येत्। तेषामधः चूर्णिचूर्णीन् पञ्चरूपोनगच्छस्य पञ्चवारसंकलनधनमात्रान् न्यस्येत्। एवं गत्वा

छह प्रक्षेपक-प्रक्षेपक, चार पिशुलि और एक पिशुलि-पिशुली स्थापित करें। पाँचवें विकल्पमें जघन्यको ऊपर स्थापित करके उसके नीचे-नीचे उसकी वृद्धिके पाँच प्रक्षेपक, दस प्रक्षेपक-प्रक्षेपक, दस पिशुली, पाँच पिशुली-पिशुली और एक चूर्णि स्थापित करे। छठे विकल्पमें जघन्यको ऊपर स्थापित करके उसके नीचे-नीचे उसकी वृद्धिके छह प्रक्षेपक, पन्द्रह प्रक्षेपक-प्रक्षेपक, बीस पिशुली, पन्द्रह पिशुली-पिशुली, छह चूर्णि और एक चूर्णि-चूर्णि स्थापित करे। इस प्रकार सूच्यंगुलके असंख्यातवें भाग मात्र अनन्त भाग वृद्धि युक्त सब पर्याय समास ज्ञानके स्थानोंमें अपने-अपने जघन्यके नीचे-नीचे अपने-अपने प्रक्षेपकोंको गच्छ प्रमाण स्थापित करना। उनके नीचे प्रक्षेपक-प्रक्षेपक एक कम गच्छके एक बार संकलन धन मात्र स्थापित करना। उनके नीचे पिशुली दो हीन गच्छके दो बार संकलन धन मात्र स्थापित करना। उनके नीचे पिशुली-पिशुली तीन हीन गच्छके तीन बार संकलन धन मात्र स्थापित करना। उनके नीचे चूर्णि चार हीन गच्छके चार बार संकलन धनमात्र स्थापित करना। उनके नीचे चूर्णि-चूर्णि पाँच हीन गच्छके पाँच बार संकलन धन मात्र स्थापित करना। इसी प्रकार क्रमसे एक हीन गच्छका एक-एक अधिक बार संकलन चूर्णि-चूर्णि हो अन्त पर्यन्त जानना। अनन्त भाग वृद्धि युक्त स्थानोंमें अनन्तका जो स्थान है उनमें-से जघन्यको ऊपर स्थापित करना। उसके नीचे क्रमानुसार प्रक्षेपकोंको सूच्यंगुलके असंख्यातवें भाग मात्र

१. म केळगे।

संकलनधनमात्रंगळं स्थापिसुवुदवर केळगे चूर्णिगळु चतूरूपोनगच्छेय चतुर्व्वारसंकलनधनप्रमितंगळप्पुवेंदु चतूरूपोनसूच्यंगुलासंख्यातभागगच्छेय चतुर्व्वारसंकलनधनमात्रंगळं स्थापिसुवुदवर केळगे चूर्णि चूर्णिगळु पंचरूपोनगच्छेय पंचवारसंकलनधनप्रमितंगळप्पुवेंदु पंचरूपोनसूच्यंगुलासंख्यातभागगच्छेय पंचवारसंकलनधनमात्रंगळं स्थापिसुवुदितु तदधस्तनाधस्तनचूर्णिचूर्णिगळ्

तदधः पिशुलिपिशुलयः त्रिरूपोनगच्छस्य त्रिवारसंकलनधनमात्राः सन्तीति त्रिरूपोनसूच्यङ्गुलासंख्येयभागगच्छस्य त्रिकवारसंकलनधनमात्रान् न्यसेत्। तदधः चूर्णयः चतूरूपोनगच्छस्य चतुर्वारसंकलनधनमात्राः सन्तीति चतूरूपोनसूच्यङ्गुलासंख्येयभागगच्छस्य चतुर्वारसंकलनधनमात्रान् न्यसेत्। तदधः चूर्णिचूर्णयः पञ्चरूपोनगच्छस्य पञ्चवारसंकलनधनप्रमिताः सन्तीति पञ्चरूपोनसूच्यङ्गुलासंख्यातभागगच्छस्य पञ्चवारसंकलन-

---

तरह चारका भाग देते रहनेसे द्वितीयादि चूर्णि-चूर्णिका प्रमाण चार, एक आदि जानना। ऊपर जघन्य ६५५३६ को स्थापित करके नीचे एक बार प्रक्षेपक १६३८४ स्थापित करके जोड़नेपर पर्याय समासके प्रथम भेदका प्रमाण ८१९२० होता है। फिर ऊपर जघन्य ६५५३६ स्थापित करके उसके नीचे दो प्रक्षेपक १६३८४।१६३८४ तथा एक प्रक्षेपक-प्रक्षेपक ४०९६ स्थापित करके जोड़नेपर पर्याय समासके दूसरे भेदका प्रमाण १०२४०० प्रमाण होता है। फिर ऊपर जघन्य ६५५३६ स्थापित करके उसके नीचे तीन प्रक्षेपक १६३८४। १६३८४। १६३८४। तीन प्रक्षेपक-प्रक्षेपक, एक पिशुली स्थापित करके जोड़नेपर तीसरे भेदका प्रमाण १२८००० होता है। फिर ऊपर जघन्यको स्थापित करके नीचे-नीचे चार प्रक्षेपक, छह प्रक्षेपक-प्रक्षेपक, चार पिशुली एक पिशुली-पिशुली स्थापित करके जोड़नेपर चौथे भेदका प्रमाण १६०००० होता है। फिर ऊपर जघन्य स्थापित करके नीचे-नीचे पाँच प्रक्षेपक, दस प्रक्षेपक-प्रक्षेपक, दस पिशुली, पाँच पिशुली-पिशुली, एक चूर्णि स्थापित करके जोड़नेपर पाँचवें भेदका प्रमाण दो लाख होता है। फिर ऊपर जघन्य स्थापित करके उसके नीचे-नीचे छह प्रक्षेपक, पन्द्रह प्रक्षेपक-प्रक्षेपक, बीस पिशुलि, पन्द्रह पिशुली-पिशुली, छह चूर्णि, एक चूर्णि-चूर्णि स्थापित करके जोड़नेपर छठे स्थानका प्रमाण दो लाख पचास हजार होता है। इसी तरह सब स्थानोंमें ऊपर जघन्य स्थापित करके उसके नीचे-नीचे जितना गच्छका प्रमाण है उतने प्रक्षेपक स्थापित करना। जहाँ जिस नम्बरका स्थान हो वहाँ उतना ही गच्छ जानना। जैसे छठे स्थानमें गच्छका प्रमाण छह होता है। उसके नीचे एक हीन गच्छका एक बार संकलन धनका जितना प्रमाण हो उतने प्रक्षेपक-प्रक्षेपक स्थापित करना उसके नीचे दो हीन गच्छका दो बार संकलन धनका जितना प्रमाण हो उतने पिशुली स्थापित करने। उनके नीचे तीन हीन गच्छका तीन बार संकलन धनका जितना प्रमाण हो उतने पिशुली-पिशुली स्थापित करने। उनके नीचे चार हीन गच्छका चार बार संकलन धनका जितना प्रमाण हो उतने चूर्णि स्थापित करने। उनके नीचे पाँच हीन गच्छका पाँच बार संकलन धनका जितना प्रमाण हो हो उतने चूर्णि-चूर्णि स्थापित करना। इसी तरह नीचे-नीचे छह आदि हीन गच्छका छह आदि बार संकलन धनका जितना-जितना प्रमाण हो उतने द्वितीयादि चूर्णि-चूर्णि स्थापित करना। इस तरह स्थापित करके जोड़नेपर पर्याय समास ज्ञानके भेदोंका प्रमाण आता है। यहाँ जो एक बार-दो बार आदि संकलन धन कहे हैं उनका विधान कहते हैं।

व्येकपदोत्तरघातः सरूपवारोद्धृतो मुखेन युतः।
रूपाधिकवारांताप्तपदाद्यंकैर्हतोवित्तं ॥

एंदितु पर्य्यायसमास ज्ञानविकल्पंगळोळु विवक्षितषष्ठविकल्पदोळु चतुर्व्वार संकलनधनानयनदोळु व्येकपद विगतमेकेन व्येकं। तच्च तत्पदं च व्येकपदं। अत्र चतुरूपोनगच्छ एव ६।४ पदं २। तत्र एकस्मिन्नपनीते २—१ एवं। तेनोत्तरघातः। एकवारादिसंकलनमाश्रित्यैवो-त्पत्तिसंभवात्तत्रैकोत्तरत्वादुत्तरघातः कर्त्तव्यः। १।१। सरूपवारोद्धृतः रूपेण सहितः सरूपः। स चासौ वारश्च सरूपवार $\frac{}{४}$ तेनोद्धृतो भक्तः। $\frac{१}{४}$ ०१। मुखेन युतः मुखमादिस्तेन युतः समच्छेदी कृत्य युते एवं $\frac{६}{५}$ पुनः रूपाधिकवारांताप्तपदाद्यंकैर्हतः। रूपाधिकवारावसान $\frac{१}{४}$। हार विकल्पे ४।३।२।१। रातमक्तपदाद्यंकैः। पदं गच्छ आदिर्येषां ते पदादयस्ते च ते अंकाश्च तैर्हतः ६।२।३।४।५ / ५।४।३।२।१ अपवर्त्तितं वित्तं धनं भवति एंदितो सूत्रदिदं तरल्पट्ट विवक्षितषष्ठविकल्पदोळु चतुर्व्वारसंकलनधनमारक्कु।६। इंते सर्व्वत्र समस्तवारसंकलनधनंगळं विवक्षितगळं तंदुकोळुवुदु।

प्रक्षेपकप्रक्षेपकादीनां प्रमाणानयने करणसूत्रमिदं—

व्येकपदोत्तरघातः सरूपवारोद्धृतो मुखेन युतः।
रूपादिकवाराप्तात्तपदाद्यंकैर्हतो वित्तम् ॥

अत्र षष्ठं विकल्पं विवक्षितं कृत्वा चूर्णीनां चतुर्वारसंकलितधनमानीयते। तत्र पदं चतूरूपोनगच्छ ६–४ मात्रं २। व्येकं एकरहितं २–१ अस्य उत्तरेण घातः एकवारादिसंकलनरचनामाश्रित्यैव द्विकवारादिसंकलनरचनोत्पत्तेः सर्वत्रादिः उत्तरश्चैकैकः इत्येकेन घातः कर्तव्यः १।१। गुणिते एवं १, सरूपवारोद्धृतः रूपाधिकवार $\frac{}{४}$। भक्तः $\frac{१}{४}$। मुखमादिः १ तेन समच्छेदेन $\frac{५}{५}$ सहितः $\frac{६}{५}$ रूपादिकवाराप्तात्तपदाद्यंकैः एकरूपप्रभृतिवारावसानहारभक्तपदाद्यंकैः $\frac{२}{४}$ $\frac{३}{३}$ $\frac{४}{२}$ $\frac{५}{१}$ हतः गुणितः $\frac{६}{५}$ $\frac{२}{४}$ $\frac{३}{३}$ $\frac{४}{२}$ $\frac{५}{१}$ अपवर्तितः ६ वित्तं षष्ठविकल्पचूर्णिधनं भवति, एवमेव सर्वत्र समस्तवारसंकलनधनानि विवक्षितान्यानि

प्रकार है—उसे उदाहरण द्वारा स्पष्ट करनेके लिए छठे विकल्पको विवक्षित करके चूर्णियोंका चार बार संकलित धन लाते हैं—यहाँ पद चार हीन गच्छ ६ – ४ = मात्र २ है। उसमें एक घटानेपर २ – १ = एक शेष रहता है। इसको उत्तरसे गुणा करना चाहिए। सो एक बार आदि संकलन धन रचनाकी अपेक्षा ही दो बार आदि संकलनकी रचना उत्पन्न होती है। सर्वत्र आदि और उत्तर एक-एक है अतः उसे एकसे गुणा करने पर १ × १ = एक ही रहा। इसका यहाँ चार बार संकलन कहा है सो चारमें एक मिलानेपर पाँच हुआ। उसका भाग देनेपर एकका पाँचवाँ भाग हुआ। इसमें मुख जो आदि, उसका प्रमाण एक, सो समच्छेद करके मिलानेपर छहका पाँचवाँ भाग हुआ। यहाँ चार बार कहा है सो एकसे लेकर एक-एक

---

१. म चतुर्व्वार।

मत्तं केशवण्णंगळु तम्मभिप्रायदिं तरल्पडुव विशेषकरणगाथासूत्रद्वयं :—

तिरियपदे रूऊणे तदिट्ठहेट्ठिल्ल संकळणवारा ।
कोट्ठधणस्साणयणे पभवं इट्ठूणिदुड्ढपदसंखा ॥

तिर्य्यक्पदे रूपोने तदिष्टाधनस्तनसंकलनवारा । भवंति कोष्ठधनस्यानयने प्रभवः इष्टोनितोर्ध्वपदसंख्या ॥

तत्तो रूवहियकमे गुणगारा होंति उड्ढगच्छोत्ति ।
इगिरूवमादिरूउत्तरहारा होंति पभवोत्ति ॥

ततो रूपाधिकक्रमेण गुणकारा भवंत्यूर्ध्वगच्छपर्यंतं । एकरूपादिरूपोत्तरहारा भवंति प्रभवपर्य्यंतं ।

इल्लिष्टमप्पुदावुदानुमोंदु तिर्य्यक्पददोळ् ६ रूपोनमागुत्तिरलु ६̊ तत्तत्पदप्रमाणं इष्टाधस्तनसंकलनवारा भवंति । आ तिर्य्यग्गच्छेदद केळगे प्रक्षेपकोनेकवारसंकलनादिसर्व्वसंभवद्वार-

आनये‍र् । पुनरेतदेव केशववर्णिभिः स्वाभिप्रायेण आनेतुं गाथाद्वयमुच्यते—

तिरियपदे रूऊणे तदिट्ठहेट्ठिल्लसंकलणवारा ।
कोट्ठधणस्साणयणे पभवं इट्ठूण उड्ढपदसंखा ॥१॥

तिरियपदे अनन्तभागवृद्धियुतस्थानेषु यद्विवक्षितं स्थानं तत् तिर्यक्पदं ६, तस्मिन् रूऊणे रूपोने इते ६̊ तदिट्ठहेट्ठिल्लसंकलणवारा तदिष्टपदे प्रक्षेपकादधस्तनकोष्ठेषु प्रतिकोष्ठमेकैकं संकलनमिति संभवतां क्रमेणैकवारद्विवारादिसंकलनानां संख्या भवति ५ ॥ तत्र इष्टस्य 'कोट्ठधणस्स' चतुर्थसंकलनधनगतकोष्ठधनस्य आणयणे आनयने 'इट्ठूणउड्ढपदसंखा' तदिष्टसंकलनवारस्य प्रमाणेन ४ न्यूनोर्ध्वपदं-६–४ पभवो आदिर्भवति ॥२॥

तत्तोरूवहियकमे गुणगारा होंति उड्ढगच्छोत्ति ।
इगिरूवमादिरूउत्तरहारा होंति पभवोत्ति ॥२॥

तत्तो तमादिं २ मादिं कृत्वा रूवहियकमे रूपाधिकक्रमेण गुणगारा गुणकारा अनुलोमगत्या होंति–

बढ़ते हुए चार पर्यन्त अंक रखकर १×२×३×४ परस्परमें गुणा करनेपर २४ हुए। यह भागहार हुआ। और गच्छ दो के प्रमाणसे लेकर एक-एक बढ़ता अंक रखकर २×३×४×५ परस्पर गुणा करनेपर १२० भाज्य हुआ। सो भाज्य १२० में भागहार २४ से भाग देनेपर लब्ध पाँच आया। इस पाँचसे पूर्वोक्त छहके पाँचवें भागको गुणा करनेपर पाँच रहे। यही दो का चार बार संकलन धन होता है। इसी तरह तीनका तीन बार संकलन धन लाना हो तो गच्छ तीनमें एक कम करके दो शेष रहे। उसे उत्तर एकसे गुणा करनेपर भी दो ही हुए। यहाँ तीन बार संकलन है। अतः उसमें एक अधिक बार चारका भाग देनेपर आधा रहा। उसमें मुख एक जोड़नेपर डेढ़ हुआ। यहाँ तीन बार कहा है अतः एकसे लेकर एक-एक बढ़ते तीन पर्यन्त अंक रखकर १×२×३ =परस्परमें गुणा करनेपर भागहार छह हुआ। और गच्छको आदि लेकर एक-एक अधिक अंक रख ३×४×५ परस्परमें गुणा करनेपर भाज्य साठ हुआ। भाज्य साठमें भागहार छहसे भाग देनेपर दस पाये। इस दससे पूर्वोक्त डेढ़को गुणा करनेपर छठे भेदमें तीन कम गच्छका तीन बार संकलन धनमात्र पन्द्रह पिशुली-पिशुली होती हैं। इसी तरह सर्वत्र विवक्षित संकलित धन लाना चाहिये।

तत्पदप्रमानं। इदुहेद्विल्लसंकलनवारा इष्टायस्तनसंकलनवाराः तन्न विवक्षित तिर्य्यंगच्छद कोळगे कोळगे संभविसुव प्रक्षेपकोनेकवारसंकलन आदिसर्व्ववारसंकलनगळ प्रमाणमक्कु २ मवरोळ् (२ के नीचे ०) कोष्ठघनस्थानयने विवक्षित ४ चतुर्थ्वारसंकलनघनमंतप्पल्लि प्रभवः आदि ये तुटकुमें दोडे इष्टोनितोर्ध्वपदसंख्या स्यात् तन्न विवक्षितसंकलनवारप्रमाणमं माल्कं कळेदुळिदद्रूर्ध्वपदप्रमाणमक्कु स्थानंगळु २-४ मिल्लिपूर्व्वगच्छमुं सर्व्वायस्तनचूर्णिचूर्णियागि प्रक्षेपकाख्यपर्य्यायावसानमप्प (२-४ के नीचे ०) सूच्यंगुलासंख्यातभागमात्रमेयक्कु २ मवरोळातन्निष्टवारसंकलनांकं माल्कं कळेदुळिद शेषप्रमाण- (२ के नीचे ०) मादियक्कुमेंदुदर्थं ज २-४ ततो रूपाधिकक्रमेण ६ यादिस्थानं मोदल्गोंडु मुंदे रूपाधिक (ज २-४ के नीचे १६।५।०) क्रमदिदं गुणकारा भवंतूर्ध्वगच्छपर्य्यंतं अनुलोमदि गुणकारंगळप्पुवूर्ध्वगच्छप्रमाणांकवकेन्नेवर-

मुत्पत्तियक्कुमन्नेवरं ज २-४। २-३। २-२। २-१ २ ६ गुणकारंगळगे एकरूपादि रूपोत्तर- (नीचे: १६।५।०० ० ० ०)

तस्मिन् रूपोने २ अवशिष्टं तदिष्टाधस्तनसंकलनवारा भवन्ति २ तेषु मध्ये विवक्षितस्य चतुर्थारसंकलन- (२ के नीचे ०) गतकोष्ठघनस्थानयने तद्वारप्रमाणे ४ ऊर्ध्वपदे २ अपनीते २-४ शेषप्रमाणमादिर्भवति ज २-४ ततः (नीचे: ० ० १६ ५ ०) तमादिमादिं कृत्वा अग्रे रूपाधिकक्रमेण गुणकारा भवन्ति ऊर्ध्वगच्छप्रमाणं यावदुत्पद्यते तावत् ज (नीचे: १६। ५) तेषां गुणकाराणामधः एकादेकोत्तरा आदिपर्यन्तं विलोमक्रमेण हारा

२-४। २-३। २-२। २-१। २ एवं (नीचे: ० ० ० ।० ०)

भाग देनेसे आता है। भागहार और गुणकार इस प्रकार है— २, ३, ४, ५, ६। यहाँ दो (नीचे: ५, ४, ३, २, १) तीन, चार पाँच का तो अपवर्तन हो गया। दोसे दो, तीनसे तीन, चारसे चार और पाँचसे पाँच अपवर्तित हो गये। छह और भागहार एक शेष रहा। सो छहगुना चूर्णिमात्र प्रमाण रहा। इसी प्रकार अनन्तभाग वृद्धि युक्त अन्तिम विकल्पमें यह स्थान सूच्यंगुलके असंख्यातवें भागका जितना प्रमाण है उतनेका है इसलिए तिर्यग् गच्छ सूच्यंगुलका असंख्यातवाँ भाग मात्र है। उसमें-से एक घटानेपर जो अवशेष है उतना अधस्तन संकलनके वार हैं। उनमें-से विवक्षित चार वार संकलन गत कोठाका धन लानेके लिए विवक्षित संकलन वारके प्रमाण चारमें ऊर्ध्वगच्छ सूच्यंगुलके असंख्यातवें भाग मात्रमें-से घटानेपर जो अवशेष रहता है वह आदि है। उसको आदि करके एक-एक बढ़ते क्रमसे ऊर्ध्वगच्छ सूच्यंगुलका असंख्यातवाँ भाग पर्यन्त तो गुणकार होता है। और इन गुणकारोंके नीचे उल्टे क्रमसे एकको आदि लेकर एक-एक बढ़ते हुए पाँच पर्यन्त भागहार होता है। यहाँ गुणकार और भागहार समान नहीं है

---

१. ब° रूपोन २ अवशिष्टं भवन्ति २ तेषु मध्ये। (दोनों २ के नीचे ०)

ज । २।३।४।००० । २-३ । २-२ । २-२ को गुणकारंगळ केळगे एकरूपादिरूपोत्तरहाराः
१६ २ ० ० ०

एकरूपादिरूपोत्तरमप्प हारंगळु विलोमक्रमदिं रूपाधिकेष्टवारसंकलनारूपमप्पवप्पुवागि भंति प्रमवरत्पवं । तदादिगुणकारदिरूपावसानमागियप्पुवु :—

ज । २। ३।४।००००२-३।२-२ २ २ इल्लि समापवर्तनंगळु माडुत्तिरलु

१६ २ २ २-२ २-३।०००० ० ४ ० ३ । ० २ । ० १

ज ० ० चरम चूर्णिचूर्णिगे संकलितमिल्ल द्वितीयादिस्थानाभावदिदं । सूच्यंगुलासंख्यात-
१६ ०

भागमात्रवारानन्तभक्तजघन्यप्रमितमक्कुं ज १ । ईतनंतभागवृद्धियुतस्थानंगळु सूच्यंगुला-
१६ । २
०

अधरितु— ज २ । ३ । ४ । ००० । २-३ । २-२ । २-१ । २ एषामधः रूपादिरूपोत्तर
१६ २ । ० ० ० ०
० २

हाराः विलोमक्रमेण रूपाधिकेष्टवारसंकलनारूपाज्ञाता भवन्ति प्रमाणमिदं—

ज २ ३ ४ । ००० २-३ २-२ २-१ २ अत्र समापवर्तनमस्तीति भग-
१६ २ २ २-२ २-३ ००० ० ४ ० ३ ० २ ० १
० ० ० ०

र्तिते एवं— ज २ चरमचूर्णिचूर्णेः संकलितं नास्ति [1]द्वितीयादिस्थानाभावात् । सूच्यङ्गुलासंख्यात-
१६ २ ०
२ ।
०

भागमात्रवारानन्तभक्तजघन्यप्रमितं स्यात् ज १ एवमनन्तभागवृद्धियुतस्थानानि सूच्यङ्गुलासंख्यातभाग-
१६ २
०

उनका अपवर्तन करनेपर शेष सूच्यंगुलके असंख्यातवें भागका गुणकार और एकका भागहार रहता है। इस कोठेमें अन्तिम चूर्णि-चूर्णि है उसका प्रमाण जघन्यको सूच्यंगुलके असंख्यातवें भाग मात्र बार भाग देनेपर जो प्रमाण आवे उतना जानना। इसको पूर्वोक्त गुणकारसे गुणा करनेपर और एकसे भाग देनेपर जो प्रमाण आता है वह उस कोठा सम्बन्धी प्रमाण है। अन्तिम चूर्णि चूर्णिमें संकलन नहीं है क्योंकि उसके दूसरे आदि स्थान न होनेसे वह एक ही है। सो जघन्यको सूच्यंगुलके असंख्यात भाग मात्र बार अनन्तसे भाग देनेपर अन्तिम चूर्णि-चूर्णिका प्रमाण होता है। उसमें एकसे गुणा करनेपर भी उतना ही उस कोठेमें वृद्धिका प्रमाण जानना। इस प्रकार सूच्यंगुलके असंख्यात भाग मात्र अनन्त भाग वृद्धि युक्त स्थान

1. ब द्वितयादिस्थानानि सूच्यङ्गुलासंख्यातभागमात्राणि मीत्वा ।

छट्ठाणाणं आदी अट्ठंकं होदि चरिममुव्वंकं ।
जम्हा जहण्णणाणं अट्ठंकं होदि जिणदिट्ठं ॥३२८॥

षट्स्थानानामादिरष्टांको भवति चरममूर्व्वंकः। यस्माज्जघन्यज्ञानमष्टांको भवति जिनदृष्टः॥

षट्स्थानवारंगळेनितोळवनितक्कमादिस्थानमष्टांकमेयक्कुं चरममुर्व्वंकमेयक्कुमंतागुत्तिरलु प्रथमषट्स्थानदोळष्टांकमेंतक्कुमें दोडे यस्माज्जघन्यज्ञानमष्टांको भवति जिनदृष्टत्वात्। तस्मात् आवुदोंदु जिनदृष्टत्वकारणदिदं जघन्यज्ञानमष्टांकमक्कुमदु कारणदिदं प्रथमषट्स्थानदोळष्टांकादित्वं युक्तमक्कुं। इल्लि षट्स्थानंगळादियष्टांकमवसानमुर्व्वंकमें ब नियमं पेळल्पट्टुदरिदं चरमषट्स्थानंगळगादियष्टांकमवसानमुमूर्व्वंकमुमागुत्तिरलल्लि मुंदणष्टांकमदेनक्कुमें दोडर्थाक्षरज्ञानमें दु मुंदे पेळ्वपनदु कारणदिदं जघन्यपर्य्यायज्ञानमादियें दु पेळ्दागमं निर्बाधबोधविषयमक्कु।

ई षट्स्थानंगळ्गे स्थानसंख्ये समानमें बुदं तोरिदपं :—

एक्कं खलु अट्ठंकं सत्तंकं कंडयं तदो हेट्ठा ।
रूवहियकंडएण य गुणिदकमा जाव मुव्वंकं ॥३२९॥

एकः खल्वष्टांकः सप्तांकः कांडकं ततोऽधो रूपाधिककांडकेन गुणितक्रमा यावदूर्व्वंकः॥

षट्स्थानवाराणां सर्वेषामादिः प्रथमस्थानमष्टाङ्कमेव अनन्तगुणवृद्धिस्थानमेव भवति तेषां चरमस्थानमुर्वङ्कमेव अनन्तभागवृद्धिस्थानमेव भवति। तर्हि प्रथमस्थानस्य अष्टाङ्कत्वं कथं? इति तन्न, यस्मात् कारणात् तज्जघन्यं ज्ञानं पर्यायाख्यं पूर्वस्मादेकजीवागुरुलघुगुणाविभागप्रतिच्छेदानां वर्गस्थानादनन्तगुणत्वेन अष्टाङ्कं भवतीति जिनैः अर्हदादिभिः दिष्टं कथितं दृष्टं वा, तस्मात् कारणात् प्रथमषट्स्थानेऽपि अष्टाङ्कादित्वं युक्तम्। अत्र षट्स्थानानामादिः अष्टाङ्कः, अवसानं उर्वङ्कः इति नियम उक्तोऽस्तीति। चरमषट्स्थानेऽपि आदौ अष्टाङ्के अवसाने उर्वङ्के च सति तदग्रतनोऽष्टाङ्कः कीदृगस्ति? इति चेत् अर्थाक्षर-ज्ञानरूपो भवति तथैव अग्रे वक्ष्यमाणत्वात्। तदेवं जघन्यपर्यायज्ञानमादिः इत्युक्तागमो निर्बाधबोधविषयः॥३२८॥ एषां षट्स्थानानां संख्या समानेति दर्शयति—

षट्स्थान पतित वृद्धिरूप सब स्थानोंमें प्रथम स्थान अष्टांक अर्थात् अनन्तगुण वृद्धि रूप स्थान ही होता है। यही आदि स्थान है। तथा उनका अन्तिम स्थान उर्वंक अर्थात् अनन्तभागवृद्धि युक्त स्थान ही होता है। तब प्रथम स्थानमें अष्टांक कैसे रहा, इसका समाधान यह है वह जो पर्याय नामक जघन्य ज्ञान है इस जघन्य ज्ञानसे पहला ज्ञान स्थान एक जीवके अगुरु लघु गुणके अविभाग प्रतिच्छेद प्रमाण है उससे अनन्त गुणा जघन्य ज्ञान है इसलिए जिनदेवने अष्टांक रूप देखा है। इस कारणसे प्रथम स्थानके भी आदिमें अष्टांक और अन्तिम उर्वंक है। यह नियम कहा है।

शंका—अन्तिम षट्स्थानमें भी आदिमें अष्टांक और अन्तमें उर्वंक होनेपर उससे आगेका अष्टांक किस रूपमें है?

समाधान—वह अर्थाक्षर ज्ञान रूप है। ऐसा ही आगे कहेंगे।

इस प्रकार जघन्य पर्याय ज्ञान आदि है यह कथन निर्बाध है॥३२८॥

आगे इन षट्स्थानोंकी संख्या समान है यह दर्शाते हैं—

---

१. म नदोलादि ।

इंतु द्वितीयादि षट्स्थानदोळादिभूताष्टांकदिदं मुंदे उर्व्वंकमक्कुमादोडमेकंखलु अट्ठंकमें बी नियमवचनदिंदष्टांकक्कमंगुलासंख्यातभागमात्रवाराऽभावमेयक्कुमेकें दोडे खलुशब्दक्के नियमार्त्थवाचकत्वदिदं।

सव्वसमासो णियमा रूवाहियकंडयस्स वग्गस्स।
विंदस्स य संवग्गो होदित्ति जिणेहि णिद्दिट्ठं ॥३३०॥

सर्व्वसमासो नियमाद्रूपाधिककांडकस्य वर्गस्य। वृंदस्य च संवर्गो भवतीति जिनैर्न्निर्दिष्टं॥

यल्ला अष्टांकादिषड्वृद्धिगळ संयोगं रूपाधिककांडकस्य रूपाधिककांडकद, वर्गस्य वर्गद, वृंदस्य च घनद, संवर्गः संवर्गमात्रं भवति अक्कुमें दितु जिनैर्न्निर्दिष्टं अर्हदादिगळिदं पेळल्पट्टुदिल्लि तद्युतियं माळ्प क्रममें तें दोडे अष्टांकदात्मप्रमाणमनोंदु रूपं तंदु सप्तांकद सूच्यंगुलासंख्यातभागदोळु कूडुत्तिरलु रूपाधिककांडकमक्कुमदं तोरि तदात्मप्रमाणमनोंदु रूपं षडंकसंख्येयोळ्कूडुत्तिरलु रूपाधिककांडकद्वयमक्कुमा वर्ग्गरूपाधिककांडकात्मप्रमाणमं पंचांकसंख्ये-

---

एवं द्वितीयवारषट्स्थाने आदिभूताष्टाङ्कतोऽग्रे उर्वङ्कोऽस्ति तथापि 'एकं खलु अट्ठंकं' इति नियमवचनान्न तस्याङ्गुलासंख्यातभागमात्रवारः, खलुशब्दस्य नियमार्थवाचकत्वात् ॥३२९॥

सर्वासां अष्टाङ्कादिषड्वृद्धीनां संयोगः रूपाधिककाण्डकस्य वर्गस्य वृन्दस्य च संवर्गमात्रो भवति इति जिनैरर्हदादिभिर्निर्दिष्टं कथितम्। अत्र तद्युतिः क्रियते तद्यथा—

अष्टाङ्कस्य आत्मप्रमाणैकरूपे सप्ताङ्कस्य सूच्यङ्गुलासंख्यातभागे युते सति रूपाधिककाण्डकं भवति तस्मिन् पुनः आत्मप्रमाणैकरूपे षडङ्कसंख्यायां काण्डकगुणितरूपाधिककाण्डकमात्र्यां युते सति रूपाधिक-

---

गुण वृद्धि युक्त स्थान काण्डक अर्थात् सूच्यंगुलके असंख्यात भाग मात्र ही होते हैं। उससे नीचेके षडंक, पंचांक, चतुरंक और उर्वंक क्रमसे रूपाधिक सूच्यंगुलके असंख्यातवें भाग गुणित उत्तरोत्तर उर्वंक पर्यन्त होते हैं अर्थात् असंख्यात गुण वृद्धिका प्रमाण सूच्यंगुलके असंख्यातवें भाग कहा है उसको एक अधिक सूच्यंगुलके असंख्यातवें भागसे गुणा करनेपर जो प्रमाण हो उतनी बार संख्यात गुण वृद्धि होती है। इसको भी एक अधिक सूच्यंगुलके असंख्यातवें भागसे गुणा करनेपर जो प्रमाण हो उतनी बार संख्यात भाग वृद्धि होती है। इसको भी एक अधिक सूच्यंगुलके असंख्यातवें भागसे गुणा करनेपर जो प्रमाण हो उतनी बार असंख्यात भाग वृद्धि होती है। इसको भी एक अधिक सूच्यंगुलके असंख्यातवें भागसे गुणा करनेपर जो प्रमाण हो उतनी बार अनन्त भाग वृद्धि होती है। इस प्रकार एक षट्स्थान पतित वृद्धिमें पूर्वोक्त प्रमाण एक-एक वृद्धि होती है। दूसरे षट्स्थानमें आदिमें अष्टांक उससे आगे उर्वंक है अतः एक ही अष्टांकका नियम जानना। वह अंगुलके असंख्यात भाग मात्र बार नहीं होता ॥३२९॥

अष्टांक आदि छह वृद्धियोंका जोड़ एक अधिक काण्डकके वर्गका तथा घनका परस्परमें गुणा करनेसे जो प्रमाण हो उतना है ऐसा जिन भगवान्‌ने कहा है। यहाँ उनका जोड़ दिखाते हैं—

अष्टांकके अपने प्रमाण एक रूपमें सूच्यंगुलके असंख्यातवें भागको मिलानेपर सप्तांकका प्रमाण एक अधिक काण्डक होता है। उसमें षडंककी संख्या, जो काण्डकसे गुणित एक अधिक काण्डक प्रमाण है, मिलानेपर रूपाधिक काण्डकका वर्ग होता है। उसमें पंचांककी संख्याको, जो काण्डकसे गुणित रूपाधिक काण्डकके वर्ग प्रमाण है, मिलानेपर रूपाधिक

उक्कस्ससंखमेत्तं तत्तिचउत्थेक्कदालछप्पण्णं ।
सत्तदसमं च भागं गंतूण य लद्धिपक्खरं दुगुणं ॥३३१॥

उत्कृष्टसंख्यातमात्रं तत्त्रिचतुर्थैकचत्वारिंशत् षट्पंचाशत् सप्तदशमं वा भागं गत्वा च लब्ध्यक्षरं द्विगुणं ॥

रूपाधिककांडकगुणितांगुलसंख्यातभागमात्रवारंगळनंतभागवृद्धिस्थानंगळु $\frac{२}{०}$ $\frac{२}{०}$ मवर मध्यदोळु सूच्यंगुलासंख्यातभागमात्रवारंगळसंख्यातभागवृद्धिस्थानंगळु सलुत्तिरलु $\frac{२}{०}$ तदुभयवृद्धियुक्तजघन्यद एकवारं संख्यातभागवृद्धिस्थानमुत्पन्नमक्कुं ज $\frac{१५}{१५}$ मुंदे मत्तं मुं पेळ्द क्रमवृद्धिद्वयसहचरितंगळोळु संख्यातभागवृद्धियुक्तस्थानंगळुत्कृष्टसंख्यातमात्रंगळु सलुत्तमिरलु अल्लि प्रक्षेपकवृद्धियं कूडुत्तिरलु लब्ध्यक्षरं सर्व्वजघन्यमप्प पर्य्यायमेंब श्रुतज्ञानं साधिकमागि द्विगुणमक्कुमेकें दोडे प्रक्षेपकमुत्कृष्टसंख्यातभाज्यभागहारंगळनपवर्त्तिसि कूडिदोडे अवक्के द्विगुणत्वसंभव-

---

रूपाधिककाण्डकगुणिताङ्गुलासंख्यातभागमात्रवारान् अनन्तभागवृद्धिस्थानेषु अङ्गुलासंख्यातभागमात्रवारान् असंख्येयभागवृद्धिस्थानेषु च गतेषु तदुभयवृद्धियुक्तजघन्यस्य एकवारं संख्यातभागवृद्धिस्थानमुत्पद्यते ज $\frac{१५}{१५}$ अथ पुनः प्रागुक्तक्रमवृद्धिद्वयसहचरितेषु संख्यातभागवृद्धियुतस्थानेषु उत्कृष्टसंख्यातमात्रेषु गतेषु तत्र प्रक्षेपकवृद्धिषु युतासु लब्ध्यक्षरं सर्वजघन्यपर्यायाख्यं श्रुतज्ञानं साधिकद्विगुणं भवति । कुतः ? प्रक्षेपकस्य उत्कृष्टसंख्यातभाज्यभागहारानपवर्त्य युते तस्य द्विगुणत्वसंभवात् तत्त्रिचतुर्थं पूर्वोक्तसंख्यातभागवृद्धियुक्तोत्कृष्ट-

---

एक अधिक सूच्यंगुलके असंख्यातवें भागसे गुणित अंगुलके असंख्यात भाग बार अनन्त भाग वृद्धियोंके होनेपर तथा अंगुलके असंख्यात भाग बार असंख्यात भाग वृद्धिके होनेपर इन दोनों वृद्धियोंसे युक्त जघन्य पर्याय ज्ञानका एक बार संख्यात भाग वृद्धि युक्त स्थान उत्पन्न होता है। आगे पुनः पूर्वोक्त अनन्त भाग वृद्धि और असंख्यात भाग वृद्धिके साथ संख्यात भाग वृद्धिसे युक्त स्थानोंके उत्कृष्ट संख्यात मात्र होनेपर उनमें प्रक्षेपक वृद्धियोंको जोड़नेपर लब्ध्यक्षर नामक सर्व जघन्य पर्याय श्रुतज्ञान साधिक दुगुना होता है। कैसे होता है यह बतलाते हैं—पूर्ववृद्धिके होनेपर जो साधिक जघन्य ज्ञान हुआ उसे अलग रखकर उस साधिक जघन्य ज्ञानमें उत्कृष्ट संख्यातका भाग देनेपर प्रक्षेपक होता है। तथा उत्कृष्ट संख्यात मात्र प्रक्षेपक है क्योंकि गच्छमात्र प्रक्षेपक वृद्धि होती है सो यहाँ उत्कृष्ट संख्यात मात्र संख्यात वृद्धिके स्थान हुए इसलिये उत्कृष्ट संख्यात मात्र प्रक्षेपक बढ़ाने हैं। सो यहाँ उत्कृष्ट संख्यात मात्र प्रक्षेपक होनेसे उत्कृष्ट संख्यात ही गुणकार हुआ। इस तरह गुणकार भी उत्कृष्ट संख्यात और भागहार भी उत्कृष्ट संख्यात; क्योंकि साधिक जघन्य ज्ञानमें उत्कृष्ट संख्यातका भाग देनेसे प्रक्षेपक होता है। सो गुणकार और भागहारका अपवर्तन करने पर साधिक जघन्य ज्ञान रहा। उसे अलग रखे साधिक जघन्य ज्ञानमें मिलाने पर जघन्य ज्ञान साधिक दूना होता है। तथा 'तत्तिचउत्थ' अर्थात् पूर्वोक्त संख्यात भाग वृद्धि युक्त उत्कृष्ट

साधिकजघन्यमक्कु ज मिदं मेलण साधिकजघन्यदोळकूडुत्तिरलु लब्ध्यक्षरं द्विगु
(+ओ अथवा ज २) प्रक्षेपकप्रक्षेपकदोळगण ऋणधनमं ज १– नोडलु मसंख्यातगुणही
३२
किंचिन्न्यूनं माडि शेषमं ज १– द्विगुणजघन्यदोळकूडिसाधिकं माडुवुदु।
३२

एकदाळछप्पण्णंमुंपेळ्द संख्यातभागवृद्धिस्थानंगळुत्कृष्टसंख्यातप्रमितंगळोळु एकच
दात् षट्पंचाशद्भागमात्रंस्थानंगळु सलुत्तं विरलु प्रक्षेपक प्रक्षेपकप्रक्षेपकवृद्धिद्वययोगदोळु
जघन्यं द्विगुणमक्कुमल्लि प्रक्षेपकमिदु ज १५।४१ प्रक्षेपकप्रक्षेपकमिदु रूपोनगच्छद ए
१५।५६

संकलित धनमात्रं ज १५।४१।१५।४१ इल्लिय ऋणरूपं मेरेदु वेरि
१५।१५।५६।२।१।५६

युते सति साधिकजघन्यं भवति ज। अस्मिन् पुनः उपरितनसाधिकजघन्ये युते सति लब्ध्यक्षरं द्विगुण
ज २। प्रक्षेपकप्रक्षेपकगतऋणं धनतः संख्यातगुणहीनमिति किंचिदूनं कृत्वा शेषं ज १–द्विगुणजघन्ये
३२
साधिकं कुर्यात्। एकदालछप्पण्णं प्रागुक्तसंख्यातभागवृद्धियुतस्थानानां उत्कृष्टसंख्यातमितेषु एकवारा
षट्पञ्चाशद्भागमात्रस्थानानि नीत्वा प्रक्षेपकप्रक्षेपकद्वययोगे साधिकजघन्यं द्विगुणं भवति तत्र प्रक्षेपको
ज १५ ४१। प्रक्षेपकप्रक्षेपकस्तु रूपोनगच्छस्य एकवारसंकलितधनमात्रः। ज १५ ४१ १५
१५ ५६ १५ १५ ५६ २

संख्यातके तीन चौथे भागसे गुणा करना। सो उत्कृष्ट संख्यात गुणकार भी और भागहा
उनका अपवर्तन करनेपर साधिक जघन्यका तीन चौथाई भाग मात्र प्रमाण रहा।
पूर्वोक्त एक चौथा भाग जोड़नेपर साधिक जघन्य मात्र वृद्धिका प्रमाण होता है।
मूल साधिक जघन्य ज्ञानको जोड़नेपर लब्ध्यक्षर दूना होता है। यहाँ प्रक्षेपक-प्र
सम्बन्धी ऋण राशि धन राशिसे संख्यात गुणी कम है इसलिए साधिक जघन्यका यत्

च भागं वा अथवा संख्यातभागवृद्धिस्थानंगळुत्कृष्टसंख्यातमात्रंगळोळु सप्तदशमभागमात्रंगळु सलुत्तिरलु प्रक्षेपक प्रक्षेपकप्रक्षेपक पिशुलिगळें ब मूरुं वृद्धिगळं कूडुत्तिरलु साधिकजघन्यं द्विगुणमक्कुमदें तें दोडे प्रक्षेपकं ज १५।७ / १५।१० प्रक्षेपकप्रक्षेपकं रूपोनगच्छद एकवारसंकलितधनमात्रं

ज १५ । ७ । १५ । ७
१५ । १५ । १० । २ । १० । १

पिशुलिद्विरूपोनगच्छद्विकवारसंकलितधनमात्रं

ज १५ । ७ । १५ । ७ । १५ । ७
१५।१५ । १५ । १० । ३ । १० । २ । १० । १

ई मूरुं वृद्धिगळोळु पिशुलिय प्रथम ऋणमं बेरिरिसि

ज २ १५ । ७ । ७
१५।१५।१६।१०।१०।१०

शेषधनमपर्वात्ततमिदु ज १५ । ७ । ४९ / १५ । १० । ६००० इवरोळु इनितु ऋणमं

'सत्तदसमं च भागं' वा अथवा संख्यातभागवृद्धिस्थानानां उत्कृष्टसंख्यातमात्रेषु मध्ये सप्तदशमभागमात्रेषु गतेषु प्रक्षेपक–प्रक्षेपकप्रक्षेपक–पिशुलिसंज्ञवृद्धित्रये प्रक्षिप्ते साधिकजघन्यं द्विगुणं भवति। तद्यथा प्रक्षेपकः

ज १५ ७ ।
१५ १०

प्रक्षेपकप्रक्षेपको रूपोनगच्छस्य एकवारसंकलितधनमात्रः ज १५ ७ १५ ७ ।
१५ १५ १० २ १० । १

पिशुलिः द्विरूपोनगच्छस्य द्विकवारसंकलितधनमात्रः ज १५ ७ । १५ ७ । १५ ७
१५ १५ १५ १० । ३ । १० । २ । १० । १

तद्वृद्धित्रयमध्ये पिशुलेः प्रथमऋणं पृथक् संस्थाप्यं ज २ १५ ७ । ७ ।
१५ । १५ । ६ । १० । १० । १० ।

इकतालीसका गुणकार और छप्पनका भागहार मिलानेपर अपवर्तन करनेपर साधिक जघन्य मात्रवृद्धिका प्रमाण रहा। इसमें मूल साधिक जघन्य जोड़नेपर लब्ध्यक्षर ज्ञान दूना होता है। यहाँ प्रक्षेपक-प्रक्षेपक सम्बन्धी धनसे ऋण संख्यात गुणा कम है। अतः किंचित् उन धनराशिको अधिक करनेपर साधिक दूना होता है।

'सत्तदसमं च भागं वा' अथवा संख्यात भाग वृद्धि युक्त उत्कृष्ट संख्यात मात्र स्थानोंमें-से सात बटे दस भाग मात्र स्थानोंके होनेपर उसमें प्रक्षेपक-प्रक्षेपक, और पिशुलि नामक तीन वृद्धियोंके जोड़नेपर साधिक जघन्य ज्ञान दूना होता है। यही आगे कहते हैं— साधिक जघन्यको एक बार उत्कृष्ट संख्यातसे भाग देनेपर प्रक्षेपक होता है वह गच्छ मात्र है अतः इसको उत्कृष्ट संख्यातके सात बटे दसवें भागसे गुणा और उत्कृष्ट संख्यातसे भाग देनेपर साधिक जघन्यको सातका गुणकार और दसका भागहार होता है। प्रक्षेपक-प्रक्षेपक

१. संदृष्टेरयमप्याकारः—ज २ १५ । ४७ । ७
१५ १५ ६०० । १० । १

ज ३/१० इदं प्रक्षेपकदोळु कूडिदोडे ज १०/१० अपवर्तितमिदु ज इदरोळु संख्यातगुणहीनमप्प प्रक्षेपकप्रक्षेपकऋणमं किंचिदूनं माडि धनमं ज १३ = /६००० साधिकं माडि मेलण जघन्यदोळु कूडिदोडे लब्ध्यक्षरं द्विगुणमक्कुं ज २ मुन्नं प्रक्षेपकप्रक्षेपकधनदोळु बेरिरिसिद ज १३/६०० त्रयोदश-रूपधनदोळुतन्न संख्यातभागमात्र ऋण रहितधनमं साधिकं माडुवुदु। अंतु माडुत्तिरलु साधिक-द्विगुणलब्ध्यक्षरमक्कुं ज २। मोदलोळुत्कृष्टसंख्यातगुणितसंख्यातभागद सप्तदशमभागमात्रंगळु ज १५।७/१५।१० संख्यातभागवृद्धियुतस्थानंगळु पिसुलिपर्यंतमागि नडदु लब्ध्यक्षरं द्विगुणमक्कुं।

अपवर्त्यं ज ४९/२०० । प्राक्तनपिशुलिधनंकादशरूपाणि मेलयित्वा ज ६०/२०० । अपवर्त्यं इदं ज ३/१० । प्रक्षेपके ज ७/१० । संयोज्य ज १०/१० । अपवर्त्येदं ज प्राक्पृथग्भृतकिंचिदूनत्रयोदशरूपैः संख्यातगुणहीनप्रक्षेपकप्रक्षेपक-ऋणेन पुनः किंचिदूनितैः ज १३ = /६००० । साधिकं कृत्वा उपरितनजघन्ये युते सति लब्ध्यक्षरं द्विगुणं भवति। ज २ । प्रथमतः उत्कृष्टसंख्यातगुणितसंख्यातभागस्य सप्तदशमभागमात्रेषु ज १५।७/१५।१० संख्यातभागवृद्धियुत-

---

उस सम्बन्धी द्वितीय ऋणका प्रमाण साधिक जघन्यको उनचासका गुणकार तथा उत्कृष्ट संख्यात और छह हजारका भागहार करनेपर होता है। उसको अलग रखकर शेषका अप-वर्तन करनेपर साधिक जघन्यको तीन सौ तैंतालीसका गुणकार और छह हजारका भागहार होता है। यहाँ गुणकारमें तेरह कम करके अलग रखना। उसमें साधिक जघन्यको तेरहका गुणकार और छह हजारका भागहार जानना। शेष साधिक जघन्यको तीन सौ तीसका गुणकार और छह हजारका भागहार रहा। तीससे अपवर्तन करनेपर साधिक जघन्यको ग्यारहका गुणकार और दस गुणित बीसका भागहार हुआ। उसे एक जगह स्थापित करना। यहाँ गुणकारमें-से तेरह कम करके जो अलग स्थापित किये थे उस सम्बन्धी प्रमाणसे प्रथम द्वितीय ऋण सम्बन्धी प्रमाण संख्यात गुणा कम है इसलिए कुछ कम करके साधिक जघन्य किंचित् कम तेरह गुणाको छह हजारसे भाग देनेपर इतना शेष रहा सो अलग रखे। तथा प्रक्षेपक-प्रक्षेपक सम्बन्धी गुणकारमें एक घटाया था उस सम्बन्धी ऋणका प्रमाण साधिक जघन्यको सातका गुणकार और उत्कृष्ट संख्यात तथा दो सौका भागहार किये होता है। उसको अलग रखकर शेष पूर्वोक्त प्रमाण साधिक जघन्यको उत्कृष्ट संख्यातका गुणकार और

रूपक्का लिपिरूपसंस्थानं स्थापनाक्षरं। एवंविधमप्प एकाक्षरश्रवणसंजातार्थज्ञानमेकाक्षरश्रुतज्ञान-मेंदितु जिनरुगळिंदं पेळल्पट्टुदेम्मिंदं किंचित्प्रकाशितमाय्तु।

अनंतरं श्रुतनिबद्धमं श्रुतविषयमं पेळ्दपं—

पण्णवणिज्जा भावा अणंतभागो दु अणभिलप्पाणं।
पण्णवणिज्जाणं पुण अणंतभागो दु सुदणिबद्धो ॥३३४॥

प्रज्ञापनीया भावा अनंतभागस्तु अनभिलाप्यानां। प्रज्ञापनीयानां पुनरनंतभागः श्रुत-निबद्धः ॥

अनभिलाप्यंगळप्प वाग्विषयंगळल्लदंतप्प केवलं केवलज्ञानगोचरंगळप्प भावंगळ जीवाद्यर्थं-गळ अनंतैकभागमात्रंगळु। भावाः जीवाद्यर्थंगळु प्रज्ञापनीयंगळु तीर्थंकरसातिशयदिव्यध्वनि प्रतिपाद्यंगळप्पुवु। पुनः मत्ते प्रज्ञापनीयंगळ सातिशयदिव्यध्वनिप्रतिपाद्यंगळप्प भावंगळ जीवाद्य-र्थंगळ अनंतैकभागः अनंतैकभागं श्रुतनिबद्धं द्वादशांगश्रुतस्कंधनिबद्धमक्के विषयतेयिदं निबद्ध-मक्कुं। श्रुतकेवलिगळ्गमगोचरमप्पर्थप्रतिपादनशक्ति दिव्यध्वनिगुंटु दिव्यध्वनिगमगोचर-जीवाद्यर्थग्रहणशक्ति केवलज्ञानक्के युंटप्पुदु।

अवाच्यानामनंतांशो भावाः प्रज्ञाप्यमानकाः।
प्रज्ञाप्यमानभावानामनंतांशः श्रुतोदितः॥

लिपिरूपसंस्थानं स्थापनाक्षरम्। एवंविधैकाक्षरश्रवणसंजातार्थज्ञानमेकाक्षरश्रुतज्ञानमिति जिनैः कथितमस्ति किंचित् प्रकाशितम् ॥३३३॥ अथ श्रुतनिबद्धं श्रुतविषयं च प्ररूपयति—

अनभिलाप्यानां अवाग्विषयाणां केवलं केवलज्ञानगोचराणां भावानां जीवाद्यर्थानां अनन्तैकभागमात्राः भावाः—जीवाद्यर्थाः, प्रज्ञापनीयाः तीर्थंकरसातिशयदिव्यध्वनिप्रतिपाद्याः भवन्ति। पुनः प्रज्ञापनीयानां भावानां जीवाद्यर्थानां अनन्तैकभागः श्रुतनिबद्धः द्वादशाङ्गश्रुतस्कन्धे निबद्धः विषयतया नियमितः श्रुतकेवलिनामपि अगोचरार्थप्रतिपादनशक्तिर्दिव्यध्वनेरस्ति दिव्यध्वनेरपि अगोचरजीवाद्यर्थग्रहणशक्तिः केवलज्ञानेऽस्तीत्यर्थः।

अवाच्यानामनन्तांशो भावाः प्रज्ञाप्यमानकाः। प्रज्ञाप्यमानभावानां अनन्तांशः श्रुतोदितः ॥१॥

रूप भावेन्द्रिय है। उस रूप अक्षर लब्ध्यक्षर है। क्योंकि वह अक्षर ज्ञानकी उत्पत्तिमें कारण है। कण्ठ, ओष्ठ, तालु आदि स्थानोंकी हलन-चलन आदि रूप क्रिया तथा प्रयत्नसे जिनके स्वरूपकी रचना होती है वे अकारादि स्वर, ककारादि व्यंजनरूप मूल वर्ण और उनके संयोगसे बने अक्षर निर्वृत्यक्षर हैं। पुस्तकोंमें उस-उस देशके अनुरूप लिखित अकारादिका आकार स्थापनाक्षर है। इस प्रकारके एक अक्षरके सुननेसे उत्पन्न हुआ अर्थज्ञान एकाक्षर श्रुतज्ञान है ऐसा जिनदेवने कहा है। परमागमके आधारसे मैंने किंचित् कहा है ॥३३३॥

अब श्रुतके विषयको तथा श्रुतमें कितना निबद्ध है इसको कहते हैं—

जो भाव अनभिलाप्य अर्थात् वचनके द्वारा कहनेमें नहीं आ सकते, केवल केवल-ज्ञानके ही विषय हैं ऐसे पदार्थ जीवादिके अनन्तवें भाग मात्र प्रज्ञापनीय हैं अर्थात् तीर्थंकरकी सातिशय दिव्यध्वनिके द्वारा कहे जाते हैं। पुनः प्रज्ञापनीय जीवादि पदार्थोंका अनन्तवाँ भाग द्वादशांग श्रुतस्कन्धमें विषय रूपसे निबद्ध होता है। श्रुतकेवलियोंके भी अगोचर अर्थ-को कहनेकी शक्ति दिव्यध्वनिमें होती है। और दिव्यध्वनिसे भी अगोचर अर्थको ग्रहण करनेकी शक्ति केवलज्ञानमें है ॥३३४॥

हीनाधिकमानंगळप्प प्रमाणपदार्त्थपदद्वयमध्यदोळे पेळल्पट्ट संख्याक्षरपरिमितसमूहदोळु वर्त्तमानत्वदिदं मध्यमपदमें दितन्वर्त्थतेयिदं परमागमदोळा मध्यमपदमे गृहीतमाप्तेकें दोडे प्रमाणार्त्थपदंगळु लोकव्यवहारदोळु गृहीतंगळागुत्तिरली मध्यमपदमे लोकोत्तरमप्प परमागमदोळु पदमेंदितु व्यवहारिसल्पट्टुदु ।

अनंतरं संघातश्रुतज्ञानमं पेळ्दपं :—

एयपदादो उवरिं एगेगेणक्खरेण वड्ढंतो ।
[2]संखेज्जसहस्सपदे उड्ढे संघादणाम सुदं ॥३३७॥

एकपदादुपर्य्येकैकाक्षरेण वर्द्धमाने। संख्येयसहस्रपदे वृद्धे संघातनामश्रुतं ॥

एकपदक्के पेळ्द प्रमाणाक्षरसमूहद मेले एकैकवर्णवृद्धिक्रमदिंदमेकपदाक्षरमात्रपदसमासज्ञानविकल्पंगळु सलुत्तं विरलु द्विगुणपदज्ञानमक्कु–। मदर मेले मत्तमेकैकवर्णवृद्धिक्रमदिंदमेकपदाक्षरमात्रपदसमासज्ञानविकल्पंगळु सलुत्तं विरलु त्रिगुणपदश्रुतज्ञानमक्कुमितु प्रत्येकमेकपदाक्षरमात्रविकल्पसहचरितंगळप्प चतुर्गुणपदादिसंख्यातसहस्रगुणितपदमात्रंगळु रूपोनपदसमासज्ञानविकल्पंगळु सलुत्तं विरलु प ००० प २ प २०००० प ३०००० प ४०००० प १००० १–१ ई चरमपद-

---

अष्टाशीतिश्च पदवर्णाः इत्येतद्गाथोक्तप्रमाणैकपदाश्रुनरुक्ताक्षरसमूहो मध्यमपदं १६३४८३०७८८८। हीनाधिकमानयोः प्रमाणपदार्थपदयोर्मध्ये एतदुक्तसंख्यापरिमिताक्षरसमूहे वर्तमानत्वात् मध्यमपदं इत्यन्वर्थतया परमागमे तदेव परिगृहीतं, प्रमाणपदार्थे पदे तु लोकव्यवहारे परिगृहीते। अत एव लोकोत्तरे परमागमे मध्यमपदमेव पदमिति व्यवह्रियते ॥३३६॥ अथ संघातश्रुतज्ञानं प्ररूपयति—

एकपदस्य उक्तप्रमाणाक्षरसमूहस्योपरि एकैकाक्षरवृद्धया एकपदाक्षरमात्रेषु पदसमासज्ञानविकल्पेषु गतेषु द्विगुणपदज्ञानं भवति। तस्योपरि पुनरपि एकपदाक्षरमात्रेषु पदसमासज्ञानविकल्पेषु गतेषु त्रिगुणपदज्ञानं भवति। एवं प्रत्येकमेकपदाक्षरमात्रविकल्पसहचरितेषु चतुर्गुणपदादिषु संख्यातसहस्रगुणितपदमात्रेषु रूपोनेषु पदसमासज्ञानविकल्पेषु गतेषु—

प। प प। ०० । प २। प २। प २। ०० । प ३ । प ३। प ३ ० ० ० प १ ० ० ० १ ३
१६= १६= १६= १ ० ० ० १

का समूह १६३४८३०७८८८ मध्यम पद है। प्रमाण पद और अर्थ पदमें हीन अधिक अक्षर होते हैं। उन दोनोंके मध्यमें कही गयी संख्या परिमाणवाले अक्षर समूहमें वर्तमान होनेसे इसका मध्यम पद नाम सार्थक होनेसे परमागममें वही लिया गया है। प्रमाणपद और अर्थपद तो लोकव्यवहारमें चलते हैं इसीसे लोकोत्तर परमागममें मध्यमपदको ही पद कहा है ॥३३६॥

अब संघात श्रुतज्ञानको कहते हैं—

एक पदके उक्त प्रमाण अक्षर समूहके ऊपर एक-एक अक्षरकी वृद्धि होते-होते एक [पद अ]क्षर प्रमाण पद समास ज्ञानके विकल्पोंके होनेपर पद श्रुत ज्ञान दूना होता है। उसके [ऊपर पुन]ः एक पदके अक्षर प्रमाण पदसमास ज्ञानके विकल्प बीतनेपर पदज्ञान तिगुना होता

[illegible] । २. म संखेज्जपदे उड्ढे संघादं णाम होदि सुदं ।

चउगइसरूवरूवयपडिवत्तीदो दु उवरि पुव्वं वा।
वण्णे संखेज्जे पडिवत्ती उड्ढम्मि अणियोगं ॥३३९॥

चतुर्गतिस्वरूपरूपकप्रतिपत्तितस्तूपरि पूर्ववत्। वर्णे संख्येये प्रतिपत्तिके वृद्धे अनुयोगं ॥

चतुर्गतिस्वरूपप्ररूपकप्रतिपत्तिकदिदं मुंदेयुमदर मेले प्रत्येकमेकैकवर्णवृद्धिक्रमदिदं संख्यातसहस्रपदसंघातप्रतिपत्तिकंगळु संवृद्धंगळागुत्तिरलु रूपोनतावन्मात्रप्रतिपत्तिकसमासज्ञानविकल्पंगळु सलुत्तमिरलु तच्चरमप्रतिपत्तिकसमासोत्कृष्टविकल्पद मेले एकाक्षरवृद्धियागुत्तं विरलु अनुयोगाख्यश्रुतज्ञानमक्कुं। अदुवुं चतुर्दशमार्गणास्वरूपप्रतिपादकानुयोगमें ब शब्दसंदर्भश्रवणजातार्थज्ञानमें बुदर्थं।

अनंतरं प्राभृतप्राभृतकमं गाथाद्वयदिदं पेळ्दपर :—

चोद्दसमग्गणसंजुद अणियोगादुवरि वड्ढिदे वण्णे।
चउरादी अणियोगे दुगवारं पाहुडं होदि ॥३४०॥

चतुर्दशमार्गणासंयुतानुयोगादुपरि वर्धिते वर्णे। चतुराद्यनुयोगे द्विकवारं प्राभृतं भवति ॥

चतुर्दशमार्गणासंयुतानुयोगश्रुतद मेले मुंदे पूर्वोक्तक्रमदिदं प्रत्येकमेकैकवर्णवृद्धिसहचरितपदादिवृद्धिगळिदं चतुराद्यनुयोगंगळु संवृद्धिगळागुत्तिरलु रूपोनतावन्मात्रंगळनुयोगसमासज्ञानविकल्पंगळु सलुत्तं विरलु तच्चरमानुयोगसमासोत्कृष्टविकल्पद मेले एकाक्षरवृद्धियागुत्तिरलु द्विकवारप्राभृतकमें ब श्रुतज्ञानमक्कुं।

चतुर्गतिस्वरूपनिरूपकप्रतिपत्तिकात् परं तस्योपरि प्रत्येकमेकैकवर्णवृद्धिक्रमेण संख्यातसहस्रेषु पदसंघातप्रतिपत्तिकेषु वृद्धेषु रूपोनतावन्मात्रेषु प्रतिपत्तिकसमासज्ञानविकल्पेषु गतेषु तच्चरमप्रतिपत्तिकसमासोत्कृष्टविकल्पस्योपरि एकस्मिन्नक्षरे वृद्धे सति अनुयोगाख्यं श्रुतज्ञानं भवति। तच्चतुर्दशमार्गणास्वरूपप्रतिपादकानुयोगसंज्ञकग्रन्थसंदर्भश्रवणजनितार्थज्ञानमित्यर्थः ॥३३९॥ अथ प्राभृतकप्राभृतकस्य स्वरूपं गाथाद्वयेन प्ररूपयति—

चतुर्दशमार्गणासंयुतानुयोगात्परं तस्योपरि पूर्वोक्तक्रमेण प्रत्येकमेकैकवर्णवृद्धिसहचरितपदादिवृद्धिभिश्चतुराद्यनुयोगेषु संवृद्धेषु सत्सु रूपोनतावन्मात्रानुयोगसमासज्ञानविकल्पेषु गतेषु तच्चरमानुयोगसमासोत्कृष्टविकल्पस्योपरि एकाक्षरवृद्धौ सत्यां द्विकवारप्राभृतकं नाम श्रुतज्ञानं भवति ॥३४०॥

चार गतियोंके स्वरूपको कहनेवाले प्रतिपत्तिकसे आगे उसके ऊपर एक-एक अक्षरकी वृद्धिके क्रमसे संख्यात हजार पदोंके समुदायरूप संख्यात हजार संघात और संख्यात हजार संघातोंके समूहरूप प्रतिपत्तिककी संख्यात हजार प्रमाण वृद्धि होनेपर उसमेंसे एक अक्षर कम करनेपर प्रतिपत्तिक समास ज्ञानके विकल्प होते हैं। उसके अन्तिम प्रतिपत्तिक समासके उत्कृष्ट विकल्पके ऊपर एक अक्षर बढ़ानेपर अनुयोग नामक श्रुतज्ञान होता है। चौदह मार्गणाओंके स्वरूपके प्रतिपादक अनुयोग नामक श्रुतग्रन्थके सुननेसे हुआ अर्थज्ञान अनुयोग श्रुतज्ञान है ॥३३९॥

अब दो गाथाओंसे प्राभृतक-प्राभृतकका स्वरूप कहते हैं—

चौदह मार्गणाओंसे सम्बद्ध अनुयोगसे आगे उसके ऊपर पूर्वोक्त क्रमसे प्रत्येक एक-एक अक्षरकी वृद्धिसे युक्त पद आदिकी वृद्धिके द्वारा चार आदि अनुयोगोंकी वृद्धि होनेपर प्राभृतक-प्राभृतक श्रुतज्ञान होता है। उसमें एक अक्षर कम करनेपर उतने मात्र अनुयोग

[illegible] ।
[illegible] ॥ [illegible] ॥

[illegible]

[illegible]

[illegible] ।
[illegible] ॥ [illegible] ॥

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

पूर्व्वश्रुतज्ञानद मेले प्रत्येकमेकैकाक्षरवृद्धिसहचरितपदादिवृद्धियिदं चतुर्द्दशवस्तुगळु सलुत्तं विरलु रूपोनतावन्मात्रोत्पादपूर्व्वसमासज्ञानविकल्पंगळु सलुत्तं विरलु तच्चरमोत्कृष्टोत्पादपूर्व्वसमासज्ञान-विकल्पद मेले एकाक्षरवृद्धियागुत्तविरलु अग्रायणीयपूर्व्वश्रुतज्ञानमक्कु-। मितु मुंदे मुंदे अष्ट अष्टादश द्वादश द्वादश षोडश विंशति त्रिंशत् पंचदश दश दश दश दश वस्तुगळु क्रमवृद्धंगळागुत्तं विरलु रूपोन रूपोन तावन्मात्र तावन्मात्र तत्तत् पूर्व्वसमासज्ञानविकल्पंगळु सलुत्तं विरलु तत्तत्पूर्व्व-समासोत्कृष्टज्ञानविकल्पंगळोळेकैकाक्षरवृद्धियागुत्तं विरलु तत्तद्वीर्य्यप्रवादपूर्व्व-अस्तिनास्ति-प्रवादपूर्व्वं ज्ञानप्रवादपूर्व्वं-सत्यप्रवादपूर्व्वं-आत्मप्रवादपूर्व्वं-कर्म्मप्रवादपूर्व्वं-प्रत्याख्याननामधेयपूर्व्वं-विद्यानुवादपूर्व्वं-कल्याणवादपूर्व्वं-प्राणावादपूर्व्वं-क्रियाविशालपूर्व्वं-त्रिलोकबिंदुसारपूर्व्वमेंबी श्रुत-ज्ञानंगळुत्पत्तिगळप्पुवु। इल्लि त्रिलोकबिंदुसारपूर्व्वक्के समासाभावमेकेंदोडे उत्तरज्ञानविकल्प-रहितत्वदिदं।

अनंतरं चतुर्द्दशपूर्व्वंगळ्गे वस्तु वस्तुप्राभृतकसंख्येयं पेळ्दपर :—

पण णउदिसया वत्थू पाहुडया तियसहस्सणवयसया।
एदेसु चोद्दसेसु वि पुव्वेसु हवंति मिलिदाणि ॥३४७॥

पंचनवतिशतानि वस्तूनि प्राभृतकानि त्रिसहस्रनवशतानि। एतेषु चतुर्द्दशसु पूर्व्वेषु सर्व्वेषु भवंति मिलितानि ॥

उत्पादपूर्व्वमादियागि लोकबिंदुसारपर्यंतमाद चतुर्द्दशपूर्व्वंगळोळु वस्तुगळु सर्व्वमुं कूडि पंचनवत्युत्तरशतप्रमितंगळप्पुवु १९५ प्राभृतकंगळु सर्व्वमुं कूडि नवशतोत्तरत्रिसहस्रप्रमितंगळप्पुवु

अग्रायणीयपूर्वश्रुतज्ञानं भवति। एवमग्रेऽग्रेऽष्टाष्टादशद्वादशद्वादशषोडशविंशतित्रिंशत्पंचदशदशदशदशदश-वस्तुषु क्रमेण वृद्धेषु रूपोनतावन्मात्रतावन्मात्रतत्तत्पूर्वसमासज्ञानविकल्पेषु गतेषु तत्तत्पूर्वसमासोत्कृष्टज्ञान-विकल्पस्योपरि एकैकाक्षरे वृद्धे सति तत्तद्वीर्यप्रवादपूर्वास्तिनास्तिप्रवादपूर्वज्ञानप्रवादपूर्वसत्यप्रवादपूर्वात्म-प्रवादपूर्वकर्मप्रवादपूर्वप्रत्याख्यानपूर्वविद्यानुवादपूर्वकल्याणवादपूर्वप्राणवादपूर्वक्रियाविशालपूर्वत्रिलोकबिन्दुसार-पूर्वनामश्रुतज्ञानान्युत्पद्यन्ते। अत्र त्रिलोकबिन्दुसारस्य तु समासो नास्ति उत्तरज्ञानविकल्पाभावात् ॥३४५–३४६॥ अथ चतुर्दशपूर्वगतवस्तुप्राभृतसंख्यां कथयति—

उत्पादपूर्वमादिं कृत्वा त्रिलोकबिन्दुसारपर्यन्तेषु चतुर्दशपूर्वेषु वस्तूनि सर्वाणि मिलित्वा पञ्चनवत्यु-त्तरशतप्रमितानि १९५ भवन्ति। प्राभृतकानि तु सर्वाणि मिलित्वा नवशतोत्तरत्रिसहस्रप्रमितानि भवन्ति

उत्कृष्ट उत्पाद पूर्व समास ज्ञान विकल्पके ऊपर एक अक्षरकी वृद्धि होनेपर अग्रायणी पूर्व श्रुतज्ञान होता है। इसी प्रकार आगे-आगे आठ, अठारह, बारह, बारह, सोलह, बीस, तीस, पन्द्रह, दस, दस, दस, दस वस्तुओंकी क्रमसे वृद्धि होनेपर एक अक्षर कम उतने-उतने उस-उस पूर्व समास ज्ञान पर्यन्त उस-उस पूर्व समास ज्ञान सम्बन्धी विकल्प होते हैं। उस-उस पूर्व समास ज्ञानके उत्कृष्ट विकल्पके ऊपर एक-एक अक्षर बढ़ानेपर उस-उस वीर्य प्रवाद पूर्व अस्ति, नास्ति, प्रवाद, पूर्व आदि त्रिलोकबिन्दुसार पर्यन्त पूर्व श्रुतज्ञान उत्पन्न होते हैं। त्रिलोकबिन्दुसारका समास ज्ञान नहीं है क्योंकि उसके आगे श्रुतज्ञानके विकल्प नहीं हैं ॥३४५-३४६॥

आगे चौदह पूर्वगत वस्तुओंके प्राभृतक नामक अधिकारोंकी संख्या कहते हैं—

उत्पाद पूर्वसे लेकर त्रिलोकबिन्दुसार पर्यन्त चौदह पूर्वोंमें मिलकर सब वस्तु अधिकार एक सौ पंचानवे होते हैं। तथा सब प्राभृत मिलकर तीन हजार नौ सौ होते हैं

स्वरूपमप्प भावश्रुतमुं च शब्ददिनंगबाह्यमप्प सामायिकादिचतुर्द्दशप्रकीर्णकभेदद्रव्यभावात्मकश्रुतं समुच्चयं माडल्पट्टुदु। पुद्गलद्रव्यरूपं वर्णपदवाक्यात्मकं द्रव्यश्रुतमक्कुं। तच्छ्रवणसमुत्पन्न श्रुतज्ञानपर्य्यायरूपं भावश्रुतमक्कुमेंदितिदाचार्य्याभिप्रायं।

पर्य्यायादिशब्दंगळ्गे निरुक्ति तोरल्पडुगुमदें तें दोडे परीयंते व्याप्यंते सर्व्वे जीवा अनेनेति पर्य्यायः। सर्व्वजघन्यज्ञानमितप्प ज्ञानरहितजीवक्कभावमेयक्कुमप्पुदरिदं। केवलज्ञानवंतरप्प जीवंगळोळमा ज्ञानमुमक्कुमदें तें दोडे महासंख्येयप्प कोटचादियोळु एकाद्यल्पसंख्येयुमल्लियंतंते ज्ञातव्यमक्कुं।

अक्षमिंद्रियं तस्मै अक्षाय श्रोत्रेंद्रियाय राति ददाति स्वमर्प्पयतीत्यक्षरम्। पद्यते गच्छति जानात्यर्थमात्माऽनेनेति पदम्। सम् संक्षेपेणैकदेशेन हन्यते गम्यते ज्ञायते एका गतिरनेनेति संघातः। प्रतिपद्यंते सामस्त्येन ज्ञायंते चतस्रो गतयोऽनयेति प्रतिपत्तिः। संज्ञायां कप्रत्ययविधानात्प्रतिपत्तिकः। अनु गुणस्थानानुसारेण गत्यादिषु मार्ग्गणासु युज्यंते संबंध्यंते जीवा अस्मिन्ननेनेति वा अनुयोगः।

प्रकर्षेण नामस्थापनाद्रव्यभावनिर्द्देशस्वामित्वसाधनाधिकरणस्थितिविधानसत्संख्याक्षेत्रस्पर्शनकालांतरभावाल्पबहुत्वादिविशेषेण वस्त्वधिकारार्त्थं प्राभृतं परिपूर्णं प्राभृतं वस्तुनोधिकारः प्राभृतमिति संज्ञाऽस्यास्तीति प्राभृतकं प्राभृतकस्याधिकारः प्राभृतकप्राभृतकं। वसंति पूर्व्वमहार्ण-

---

स्वरूपं भावश्रुतम्। चशब्दात् अङ्गबाह्यसामायिकादिचतुर्दशप्रकीर्णकभेदद्रव्यभावात्मकश्रुतं पुद्गलद्रव्यरूपं वर्णपदवाक्यात्मकं द्रव्यश्रुतं, तच्छ्रवणसमुत्पन्नश्रुतज्ञानपर्यायरूपं भावश्रुतं च समुच्चीयते इति आचार्यस्य अभिप्रायः। पर्यायादिशब्दानां निरुक्तिः प्रदर्श्यते। तद्यथा–परीयन्ते व्याप्यन्ते सर्वे जीवा अनेनेति पर्यायः–सर्वजघन्यज्ञानं, ईदृशज्ञानरहितस्य जीवस्याभावात्। केवलज्ञानवत्स्वपि तत्सद्भावात् महासंख्यायां कोट्यादौ एकाद्यल्पसंख्यावत्। अक्षाय–श्रोत्रेन्द्रियाय राति ददाति स्वमर्पयतीत्यक्षरम्। पद्यते गच्छति जानात्यर्थमात्मा अनेनेति पदम्। सं–संक्षेपेण एकदेशेन हन्यते गम्यते ज्ञायते एका गतिः अनेनेति संघातः। प्रतिपद्यन्ते सामस्त्येन ज्ञायन्ते चतस्रो गतयः अनयेति प्रतिपत्तिः, संज्ञायां कप्रत्ययविधानात् प्रतिपत्तिकः। अनु गुणस्थानानुसारेण गत्यादिषु मार्गणासु युज्यन्ते संबध्यन्ते जीवा अस्मिन्ननेनेति वानुयोगः। प्रकर्षेण–नामस्थापनाद्रव्यभावनिर्देशस्वामित्वसाधनाधिकारणस्थितिविधान-सत्संख्याक्षेत्रस्पर्शनकालान्तरभावाल्पबहुत्वादिविशेषेण वस्त्वधिकारार्थं रा-

---

रूप वर्णपद वाक्यात्मक द्रव्यश्रुत होता है और उसके सुननेसे उत्पन्न हुए ज्ञानरूप भावश्रुत है यह आचार्यका अभिप्राय है। अब पर्याय आदि शब्दोंकी निरुक्ति कहते हैं—इसके द्वारा सब जीव 'परीयन्ते' व्याप्त किये जाते हैं वह पर्याय अर्थात् सर्वजघन्य ज्ञान है। इस प्रकारके ज्ञानसे रहित कोई जीव नहीं है, केवलज्ञानियोंमें भी वह रहता है। जैसे कोटि आदि महासंख्यामें एक आदि अल्प संख्या गर्भित रहती है। 'अक्षाय' अर्थात् श्रोत्रेन्द्रियके लिए 'राति' अपनेको देता है वह अक्षर है। जिसके द्वारा आत्मा अर्थको 'पद्यते' जानता है वह पद है। जिसके द्वारा एक गति 'सं' संक्षेप रूपसे एकदेशसे 'हन्यते' जानी जाती है वह संघात है। जिसके द्वारा चारों गतियाँ 'प्रतिपद्यन्ते' पूर्ण रूपसे जानी जाती हैं वह प्रतिपत्ति है। संज्ञामें 'क' प्रत्यय करनेसे प्रतिपत्तिक होता है। जिसमें या जिसके द्वारा जीव 'अनु' गुणस्थानके अनुसार गति आदि मार्गणाओंमें 'युज्यन्ते' युक्त किये जाते हैं वह अनुयोग है। 'प्रकर्षेण' नाम, स्थापना, द्रव्य, भाव, निर्देश, स्वामित्व, साधन, अधिकरण, स्थिति, विधान, सत्, संख्या, क्षेत्र, स्पर्शन, काल, अन्तर, भाव, अल्पबहुत्व आदि विशेषोंसे वस्तु अधिकार

द्वादशोत्तरशतप्रमितकोटिगळुमेंभत्तमूरु लक्षंगळुमय्वत्तेंटु सासिरदय्दु द्वादशांगमध्यमसर्व्वपदप्रमाणमक्कुं ११२८३५८००५ ।

अनंतरमंगबाह्याक्षरसंख्येयं पेळ्दपनवु मेकपदाक्षरंगळि देक्कट्टुनं भागिसुतिरलु शेषाक्षरंगळप्पर प्रमाणमं पेळ्दपं :—

अडकोडिएयलक्खा अट्ठसहस्सा य एयसदिगं च ।
पण्णत्तरिवण्णाओ पइण्णयाणं पमाणं तु ॥३५१॥

अष्टकोटयेकलक्षमष्टसहस्रं चैकशतिकं च । पंचोसरसप्ततिवर्णाः प्रकीर्णकानां प्रमाणं तु ॥

एंटु कोटिगळुमेकलक्षमुमेंटुसहस्रगळु नूरेप्पत्तेदु ८०१०८१७५ मंगबाह्यांगळप्प सामायिकादिचतुर्द्दशभेदंगळोळु संभविसुव प्रकीर्णकाक्षरंगळ प्रमाणमक्कुं । तु शब्ददिदं पूर्व्वसूत्रदोळु द्वादशांगपदसंख्ये पेळल्पट्टुदी सूत्रदोळंगबाह्याक्षरसंख्ये पेळल्पट्टुदें बी विशेषमरियल्पडुगु ।

अनंतरमी पर्व्वनिर्णयार्त्थं गाथाद्वयमं पेळ्दपं :—

तेत्तीसवेंजणाइं सत्तावीसा सरा तहा भणिया ।
चत्तारिय जोगवहा चउसट्ठी मूलवण्णाओ ॥३५२॥

त्रयस्त्रिंशद्व्यंजनानि सप्तविंशति स्वराः तथा भणिताः । चत्वारश्च योगवाहाः चतुःषष्टिः मूलवर्णाः ॥

द्वादशोत्तरशतकोटयः त्र्यशीतिलक्षाणि अष्टपञ्चाशत्सहस्राणि पञ्च च द्वादशाङ्गानां मध्यमपदसंख्याप्रमाणं भवति ११२, ८३, ५८, ००५ । [अंग्यते मध्यमपदैर्लक्ष्यते इत्यङ्गम् । अथवा आचारादिद्वादशशास्त्रसमूहरूपश्रुतस्कन्धस्य अङ्गं अवयवः एकदेशः आचाराद्येकैकशास्त्रमित्यर्थः] ॥३५०॥ अथाङ्गबाह्याक्षरसंख्यां कथयति—

अष्टकोट्येकलक्षाष्टसहस्रैकशतपञ्चसप्ततिप्रमाणाः प्रकीर्णकानां अङ्गबाह्यानां सामायिकादीनां च चतुर्दशानां वर्णा भवन्ति ८०१०८१७५ तुशब्दः पूर्वसूत्रे द्वादशाङ्गपदसंख्योक्ता, अस्मिन् सूत्रे च अङ्गबाह्याक्षरसंख्योक्तेति विशेषं ज्ञापयति ॥३५१॥ अथामुमेवार्थं गाथाद्वयेनाह—

द्वादशांगके सब मध्यम पदोंका प्रमाण एक सौ बारह कोटि, तेरासी लाख, अठावन हजार पाँच है । अङ्ग्यते अर्थात् मध्यम पदोंके द्वारा जो लक्षित होता है वह अंग है । अथवा आचार आदि बारह शास्त्रसमूहरूप श्रुतस्कन्धका जो अंग अर्थात् अवयव या एकदेश है । अर्थात् आचार आदि एक-एक शास्त्र अंग है ॥३५०॥

अब अंगबाह्यकी अक्षर संख्या कहते हैं—

प्रकीर्णक अर्थात् सामायिक आदि चौदह अंगबाह्योंके अक्षर आठ कोटि, एक लाख आठ हजार एक सौ पिचहत्तर प्रमाण होते हैं । तु शब्द विशेषार्थक है वह ज्ञापित करता है कि पूर्व गाथासूत्रमें द्वादशांगके पदोंकी संख्या कही है । इस गाथा सूत्रमें अंगबाह्यके अक्षरोंकी संख्या कही है ॥३५१॥

इसी अर्थको दो गाथाओंसे कहते हैं—

---

१. [ ] एतत्कोष्ठान्तर्गतपाठो नास्ति ब प्रतौ ।

मूलवर्णप्रमाणमप्प चतुःषष्टयंकस्थानरूपंगळं विरलिसि तिर्य्यक्पंक्तिरूपदिदं स्थापिसि रूपं प्रति द्विकंगळनित्तु संगुणं कृत्वा परस्पर गुणनगं माडि तल्लब्धदोळु रूपोनं माडुतिरलु श्रुत-ज्ञानस्य द्वादशांगप्रकीर्णक श्रुतस्कंधद्रव्यश्रुतद अपुनरुक्ताक्षरंगळु तल्लब्धप्रमितंगळप्पुवे ते दोडे वाक्यार्त्थप्रतीतिनिमित्तंगळप्पपुनरुक्ताक्षरंगळो संख्यानियमाभावमप्पुदरिदं। एकद्विश्यादि चतुः-षष्टिसंयोगपर्य्यंतमप्प संयोगाक्षरंगळु संकलितमागुतिरलु श्रुतस्कंधाक्षरप्रमाणोत्पत्तियक्कुमा संकलितधनमेनिते दोडे पेळ्दपरु :—

एक्कट्ठ च च य छस्सत्तयं च च य सुण्णसत्ततियसत्ता।
सुण्णं णव पण पंच य एक्कं छक्केक्कगो य पणगं च ॥३५४॥

एकाष्टचतुःचतुःषट्सप्तकं च चतुःचतुःशून्यसप्तत्रिकसप्त। शून्यं नव पंच पंच च एकं षट्कैक-कश्च पंचकं च ॥

एंदितेकादिपं पंचांकावसानमादविंशतिस्थानात्मकद्विरूपवर्गधाराद्रूपोनषष्ठवर्ग-प्रमाणाक्षरंगळप्पुवु—१८४४६७४४०७३७०९५५१६१५।

क्	ख्	ग्	घ्	ङ्	च्	छ्	ज्	झ्	ञ्	००००६४
१	१	१	१	१	१	१	१	१	१	प्रत्येक
१	१	२	३	४	५	६	७	८	९	द्विसंयोग
	२	१	३	६	१०	१५	२१	२८	३६	त्रिसंयोग
		४	१	४	१०	२०	३५	५६	८४	चतुःसंयोग
			८	१	५	१५	३५	७०	१२६	पंचसंयोग
				१६	१	६	२१	५६	१२६	षट्संयोग
					३२	१	७	२८	८४	सप्तसंयोग
						६४	१	८	३६	अष्टसंयोग
							१२८	१	९	नवसंयोग
								२५६	१	दशसंयोग
									५१२	

मूलवर्णप्रमाणं चतुःषष्टिमदं एकैकरूपेण विरलयित्वा रूपं रूपं प्रति द्विकं दत्त्वा परस्परं सङ्गुण्य तल्लब्धे

मूल अक्षर प्रमाण चौंसठ पदोंको एक-एक रूपसे विरलन करके एक-एक रूपपर दो-

४।५।६।७।८।९ अपर्वात्ततमिदुवु ८४। अष्टसंयोगंगळु। सप्तरूपोनपदषड्वारसंकलितमक्कु
६।५।४।३।२।१

३।४।५।६।७।८।९ अपवर्त्तितमिदु ३६। नवसंयोगंगळु अष्टरूपोनपदसप्तवारसंकलितमक्कुं
७।६।५।४।३।२।१

२।३।४।५।६।७।८।९ अपर्वात्ततमिदु ९। दशसंयोगंगळु नवरूपोनपदाष्टवारसंकलित-
८।७।६।५।४।३।२।१

मक्कुमादोडमल्लि परमार्त्थदिदं संकलितमिल्लिल्लियों दे रूपमक्कु—। मिवेल्लं कूडि ५१२। इंती प्रकारदिवेल्लडेयोळु तंदु कों बुदु।

चरमस्थानदोळु सोप्पें ब दसें दोडे चरमदोळं प्रत्येकभंग एकः प्रत्येकभंगमों दु। द्विसंयोगो द्विरूपपदमात्रः। द्विसंयोगंगळ्वसंख्ये विरूपपदमात्रमक्कुं। ६३। त्रिसंयोगादिक्रमाः त्रिसंयोगचतुः-संयोगपंचसंयोगादि स्वसंभवचतुःषष्टिसंयोगावसानमाद संयोगंगळ प्रमाणं यथाक्रमं क्रममनति-क्रमिसदे रूपाधिकवारहीनपदसंकलितं रूपाधिकैकद्वित्रिवारादि-स्वसंभवद्व्युत्तरषष्टिपर्य्यवसाने-

---

१२६। सप्तसंयोगाः षड्रूपोनपदस्य पञ्चवारसंकलनमात्राः[२] ४।५।६।७।८।९ / ६।५।४।३।२।१ अपवर्तिता ८४।

अष्टसंयोगाः सप्तरूपोनपदस्य षड्वारसंकलनमात्राः ३।४।५।६।७।८।९ / ७।६।५।४।३।२।१ अपवर्तिताः ३६।

नवसंयोगाः अष्टरूपोनपदस्य सप्तवारसंकलनमात्राः २।३।४।५।६।७।८।९ / ८।७।६।५।४।३।२।१। अपवर्तिताः ९।

दशसंयोगाः नवरूपोनपदस्य अष्टवारसंकलनमात्राः। अत्र परमार्थतः संकलनमेव नास्ति इत्येकः। एते सर्वे एकप्रत्येकभङ्गनवद्विसंयोगैः द्वादशोत्तरपञ्चशतभङ्गा भवन्ति ५१२। एवं सर्वपदेष्वानयेत्। चरमस्थाने प्रत्येकभंगः एकः १। द्विसंयोगो विरूपपदमात्राः। तथा त्रिसंयोगाः द्विरूपोनपदस्यैकवारसंकलनमात्राः

पाँच हीन गच्छका चार बार संकलन धन मात्र हैं। सो पाँच, छह, सात, आठ, नौको पाँच, चार, तीन, दो, एकसे भाग देकर ५।६।७।८।९ / ५।४।३।२।१ अपवर्तन करनेपर एक सौ छब्बीस होते हैं। सात संयोगी भंग छह हीन गच्छका पाँच बार संकलन धन मात्र हैं। सो चार, पाँच, छह, सात, आठ, नौ में छह, पाँच, चार, तीन, दो, एकका भाग देकर ४।५।६।७।८।९ / ६।५।४।३।२।१ अपवर्तन करनेपर चौरासी होते हैं। आठ संयोगी भंग सात हीन गच्छका छह बार संकलन धन मात्र हैं। सो तीन, चार, पाँच, छह, सात, आठ, नौ को सात, छह, पाँच, चार, तीन, दो, एकका भाग देकर ३।४।५।६।७।८।९ / ७।६।५।४।३।२।१। अपवर्तन करनेपर छत्तीस होते हैं। नौ संयोगी भंग आठ हीन गच्छका सात बार संकलन धन मात्र हैं। सो दो, तीन, चार, पाँच, छह, सात, आठ, नौको आठ, सात, छह, पाँच, चार, तीन, दो, एकका भाग देनेपर नौ होते हैं। दस संयोगी भंग नौ हीन गच्छका आठ बार संकलन घन मात्र हैं। सो यहाँ वास्तवमें संकलन नहीं है क्योंकि एकका संकलन एक ही होता है अतः एक ही भंग है। इस प्रकार सबको जोड़नेपर दसवें स्थानमें पाँच सौ बारह भंग होते हैं इसी प्रकार सब

---

१. म °सानवार संकलनसंख्याः°। २. इतोऽग्रे मुद्रितप्रतौ सर्वं नास्ति।

नागतराशि ७ । ५७ । २९ । ५९ । ० । ६१ । ३१ । ० अपवर्तितगुणितमिदु ३८ । ७२८९४६९७
५६ । ५७ । ५८ । ५९ । ६० । ६१ । ६२ । ६३
८ । ७ । ६ । ५ । ४ । ३ । २ । १

दशसंयोगदोळु नवरूपोनपद अष्टवारसंकलितमक्कुं अप ५५ । ७ । १९ । २९ । ५९ । ० । ६१ । ३१ । ०
५५ । ५६ । ५७ । ५८ । ५९ । ६० । ६१ । ६२ । ६३
९ ८ ७ ६ ५ ४ ३ २ १

इंतीप्रकारदिदमसंवारसंजनितैकादशसंयोगादिभंगंगळु यथासंभवंगळु नडदु द्विचरमत्रिषष्टि-

संयोगंगळु रूपाधिकेकषष्टिवारसंकलनसंख्यात्रिहीनपद ६४-६१ एकषष्टिवारसंकलितमक्कुं

संयोगंगळु रूपाधिकेकषष्टिवारसंकलनसंख्यात्रिहीनपद ६४-६१ अपवर्तितमिदु ६३ । चतुःषष्टिसंयोगमों देयक्कुं । १ ।
२३ । ४ । ०००० । ६० । ६१ । ६२ । ६३
६२ ६२ । ६० । ५५४ । ३ । २ । १
मध्य
० ० ० ०

६ चरमचतुःषष्टपदस्थानदोळु प्रत्येकभंगमादियागि चतुःषष्टपदारं संयोगभंगावसानमादसमस्त ... चतुःषष्टिवर्णा-
दारविकल्पंगळु युति एरडुन अर्द्धमक्कु–१८= मितेकाद्येकोत्तरपदवृद्धिक्रमदिदं चतुःषष्टिवर्णा...
२

नवसंयोगाः अष्टरूपोनपदस्य सप्तवारसंकलनमात्राः ५६ । ५७ । ५८ । ५९ । ६० । ६१ । ६२ । ...
८ । ७ । ६ । ५ । ४ । ३ । २ । ...

अपवर्तिताः ३८०७२८९४६९७ । दशसंयोगाः नवरूपोनपदस्याष्टवारसंकलनमात्रा
५५ । ५६ । ५७ । ५८ । ५९ । ६० । ६१ । ६२ । ६३ । अनेन क्रमेण.......संवारसंजनितैकाद...
९ । ८ । ७ । ६ । ५ । ४ । ३ । २ । १ ।
शादिभङ्गा यथासंभवं नीत्वा द्विचरमत्रिषष्टिसंयोगाः द्वाषष्टिरूपोनपदस्यैकषष्टिवारसंकल...
२ । ३ । ४ । ००० । ६० । ६१ । ६२ । ६३ । अपवर्तिता ६३ । चतुःषष्टिसंयोगः एक एव ...
६२ । ६१ । ६० । मध्य ४ । ३ । २ । १ ।
अत्र चतुःषष्टिमेलापकस्थाने प्रत्येकादीनां चतुःषष्टिसंयोगान्तानां सर्वेषामक्षराणां युतिरेकरूपमार्द्ध...

भंग सात हीन गच्छका छह वार संकलन मात्र होते हैं सो सत्तावन, अट्ठावन, ... एकका भा...
साठ, इकसठ, बासठ, तिरसठको मात, छह, पाँच, चार, तीन, दो, ... होते हैं। नौ संयोगी ...
पचपन करोड़ बत्तीस लाख सत्तर हजार छह सौ इकहत्तर होते हैं। नौ संयोगी ...
हीन गच्छका सात वार संकलन मात्र। सो छप्पन, सत्तावन, अठावन, उनसठ, ...
सठ, बासठ, तिरसठको आठ, सात, छह, पाँच, चार, तीन, दो, एकका भाग दे...
अरब सत्तासी करोड़ अट्ठाईस लाख चौरानवे हजार छह सौ सत्तानवे होते हैं। ...
भंग नौ हीन गच्छका आठ वार संकलन मात्र। सो पचपन, छप्पन, सत्तावन...
उनसठ, साठ, इकसठ बासठ, तिरसठको नौ, आठ, सात, छह, पाँच, चार, तीन...
भाग देनेपर होते हैं। इसी प्रकार ग्यारह संयोगी आदि भंग जानना।

तिरसठ संयोगी भंग बासठ हीन गच्छ दोका इकसठ वार संकलन ...
दो, तीन आदि एक-एक बढ़ते तिरसठ पर्यन्तको बासठ इकसठ आदि एक-ए...
पर्यन्तका भाग देनेपर तिरसठ भंग होते हैं। चौंसठ संयोगी भंग एक ही ...

... इसी प्रकार। २. म °दस्थानं।

एवं पाप न बध्यते । इत्याद्युत्तरवाक्यप्रतिपादितमुनिजनसमस्ताचरणं वर्णिसल्पट्टुदु । सूत्रयति-संक्षेपेणार्थं सूचयतीति सूत्रं परमागमः । तदर्थं कृतं करणं ज्ञानविनयादि निर्विघ्नाध्ययनादिक्रिया । अथवा प्रज्ञापना कल्प्याकल्प्यच्छेदोपस्थापना व्यवहारधर्म्मक्रियाः स्वसमय-परसमयस्वरूपं च सूत्रैः कृतं करणं क्रियाविशेषो यस्मिन् वर्ण्यते तत्सूत्रकृतं नाम द्वितीयमंगं । तिष्ठंत्यस्मिन्नेकाद्येकोत्तराणि स्थानानीति स्थानं स्थानांगं तस्मिन् संग्रहनयेन एक एवात्मा व्यवहारनयेन संसारी मुक्तश्चेति द्विविकल्पः उत्पादव्ययध्रौव्ययुक्त इति त्रिलक्षणः, कर्म्मवशाच्चतुर्गतिषु संक्रामतीति चतुःसंक्रमणयुक्तः, औपशमिकक्षायिकक्षायोपशमिकौदयिकपारिणामिकभेदेन पंच विशिष्टधर्म्मप्रधानः, पूर्वदक्षिणपश्चिमोत्तरोर्ध्वाधोगतिभेदेन संसारावस्थायां षट्कापक्रमयुक्तः, स्यादस्ति-स्यान्नास्ति स्यादस्तिनास्ति स्यादवक्तव्यः स्यादस्त्यवक्तव्यः स्यान्नास्त्यवक्तव्यः स्यादस्तिनास्त्यवक्तव्यः इत्यादिसप्तभंगिसद्भावे उपयुक्तः, अष्टविधकर्म्मास्रवयुक्तत्वादष्टास्रवः, नवजीवाजीवास्रवबंधसंवरनिर्जरामोक्षपुण्यपापरूपाः अर्थाः पदार्थाः विषयाः यस्य स नवार्थः, पृथिव्यप्तेजोवायुप्रत्येकसाधारणद्वित्रिचतुःपंचेंद्रियभेदाद्दशस्थानकः इत्यादीनि जीवस्य, सामान्यार्थनया एकः

भुञ्जीत । एवं पापं न बध्यते । इत्याद्युत्तरवाक्यप्रतिपादितमुनिजनसमस्ताचरणं वर्ण्यते । सूत्रयति–संक्षेपेण अर्थं सूचयति इति सूत्रं परमागमः । तदर्थं कृतं करणं ज्ञानविनयादिर्निर्विघ्नाध्ययनादिक्रिया, अथवा प्रज्ञापना, कल्प्याकल्प्यं, छेदोपस्थापना, व्यवहारधर्मक्रिया, स्वसमयपरसमयस्वरूपं च सूत्रैः कृतं करणं क्रियाविशेषो यस्मिन् वर्ण्यते तत् सूत्रकृतं नाम द्वितीयमङ्गम् । तिष्ठन्ति अस्मिन् एकाद्येकोत्तराणि स्थानानीति स्थानं तस्मिन् संग्रहनयेन एक एवात्मा । व्यवहारनयेन संसारी मुक्तश्चेति द्विविकल्पः । उत्पादव्ययध्रौव्ययुक्त इति त्रिलक्षणः । कर्मवशात् चतुर्गतिषु संक्रामतीति चतुःसंक्रमणयुक्तः । औपशमिकक्षायिकक्षायोपशमिकौदयिकपारिणामिकभेदेन पञ्चविशिष्टधर्मप्रधानः । पूर्वदक्षिणपश्चिमोत्तरोर्ध्वाधोगतिभेदेन संसारावस्थायां षट्कापक्रमयुक्तः । स्यादस्ति स्यान्नास्ति स्यादस्तिनास्ति स्यादवक्तव्यः स्यादस्त्यवक्तव्यः स्यान्नास्त्यवक्तव्यः स्यादस्तिनास्त्यवक्तव्यः इत्यादिसप्तभङ्गीसद्भावे उपयुक्तः । अष्टविधकर्मास्रवयुक्तत्वादष्टास्रवः । नव जीवाजीवास्रवबन्धसंवरनिर्जरामोक्षपुण्यपापरूपा अर्थाः–पदार्थाः विषयाः यस्य स नवार्थः । पृथिव्यप्तेजोवायुप्रत्येकसाधारण-

---

और सावधानतापूर्वक भोजन करिए। ऐसा करनेसे पापका बन्ध नहीं होता, इत्यादि ऊपर वाक्योंमें प्रतिपादित मुनिजनोंका समस्त आचरण वर्णित है। 'सूत्रयति' अर्थात् जो संक्षेपसे अर्थको सूचित करता है वह सूत्र नामक परमागम है। उसमें कृत अर्थात् ज्ञानकी विनय आदि, निर्विघ्न अध्ययन आदि क्रिया अथवा प्रज्ञापना, कल्प्य-अकल्प्य, छेदोपस्थापना, व्यवहार

वाक्यानि प्रज्ञाप्यंते कथ्यन्ते यस्यां सा व्याख्याप्रज्ञप्तिनाम पंचममंगं । नाथस्त्रिलोकेश्वराणां स्वामी तीर्त्थंकरपरमभट्टारकस्तस्य धर्म्मकथा जीवादिवस्तुस्वभावकथनं । घातिकर्म्मक्षयानंतरकेवलज्ञानसहोत्पन्नतीर्त्थंकरत्वपुण्यातिशयविजृंभितमहिम्नस्तीर्त्थंकरस्य पूर्व्वाह्णमध्याह्नापराह्णार्द्धरात्रिषु षट् षट् घटिकाकालपर्यंतं द्वादशगणसभामध्ये स्वभावतो दिव्यध्वनिरुद्गच्छत्यन्यकालेपि गणधरशक्रचक्रधरप्रश्नानंतरं चोद्भवति । एवं समुद्भूतो दिव्यध्वनिः समस्तासन्नश्रोतृगणानुद्दिश्य उत्तमक्षमादिलक्षणं वा धर्म्मं कथयति । अथवा ज्ञातुर्गणधरदेवस्य जिज्ञासमानस्य प्रश्नानुसारेण तदुत्तरवाक्यरूपा धर्म्मकथातत्पृष्टास्तित्वनास्तित्वादिस्वरूपकथनं । अथवा ज्ञातृणां तीर्त्थंकरगनधरशक्रचक्रधरादीनां धर्म्मानुबंधिकथोपकथाकथनं ज्ञातृधर्म्मकथानाम षष्ठमंगं ।

तो वासयअज्झयणे अंतयडेणुत्तरोववाददसे ।
पण्हाणं वायरणे विवायसुत्ते य पदसंखा ॥३५७॥

तत उपासकाध्ययने अंतकृद्दशे अनुत्तरोपपादवदशे । प्रश्नानां व्याकरणे विपाकसूत्रे च पदसंख्या ॥

गणधरदेवप्रश्नवाक्यानि प्रज्ञाप्यन्ते कथ्यन्ते यस्यां सा व्याख्याप्रज्ञप्तिनाम पञ्चममङ्गं । नाथः—त्रिलोकेश्वराणां स्वामी तीर्थंकरपरमभट्टारकः तस्य धर्मकथा जीवादिवस्तुस्वभावकथनं, घातिकर्मक्षयानन्तरकेवलज्ञानसहोत्पन्नतीर्थंकरत्वपुण्यातिशयविजृम्भितमहिम्नः तीर्थंकरस्य पूर्वाह्णमध्याह्नापराह्णार्धरात्रेषु षट्षट्घटिकाकालपर्यन्तं द्वादशगणसभामध्ये स्वभावतो दिव्यध्वनिरुद्गच्छति । अन्यकालेऽपि गणधरशक्रचक्रधरप्रश्नानन्तरं चोद्भवति । एवं समुद्भूतो दिव्यध्वनिः समस्तासन्नश्रोतृगणानुद्दिश्य उत्तमक्षमादिलक्षणं रत्नत्रयात्मकं वा धर्मं कथयति । अथवा ज्ञातुर्गणधरदेवस्य जिज्ञासमानस्य प्रश्नानुसारेण तदुत्तरवाक्यरूपा धर्मकथा तत्पृष्टास्तित्वनास्तित्वादिस्वरूपकथनं, अथवा ज्ञातृणां तीर्थंकरगणधरशक्रचक्रधरादीनां धर्मानुबन्धिकथोपकथाकथनं नाथधर्मकथा ज्ञातृधर्मकथानाम वा षष्ठमङ्गम् ॥३५६॥

अंगमें होता है। क्या जीव है या नहीं है ? क्या जीव एक है या अनेक है ? क्या जीव नित्य है या अनित्य है ? क्या जीव वक्तव्य है या अवक्तव्य है इत्यादि गणधरदेवके साठ हजार प्रश्न भगवान् अर्हन्त तीर्थंकरके पासमें पूछे गये जिसमें विशेष अर्थात् बहुत प्रकारसे प्रज्ञाप्यन्ते कहे जाते हैं वह व्याख्याप्रज्ञप्ति नामक पाँचवाँ अंग है। नाथ अर्थात् तीनों लोकोंके ईश्वरोंका स्वामी तीर्थंकर परम भट्टारककी धर्मकथा—जीवादि वस्तुओंके स्वभावका कथन, कि घातिकर्मोंके क्षयके अनन्तर केवलज्ञानके साथ उत्पन्न तीर्थंकर नामक पुण्यातिशयसे जिनकी महिमा बढ़ गयी है उन तीर्थंकरकी पूर्वाह्न, मध्याह्न, अपराह्न और अर्धरात्रिमें छह-छह घड़ी काल पर्यन्त बारह गणोंकी सभाके मध्य स्वभावसे दिव्यध्वनि खिरती है, अन्य समयमें भी गणधर, इन्द्र और चक्रवर्तीके प्रश्न करनेपर खिरती है। इस प्रकार उत्पन्न हुई दिव्यध्वनि समस्त निकटवर्ती श्रोतागणोंके उद्देशसे उत्तमक्षमादि लक्षणरूप रत्नत्रयात्मक धर्मका कथन करती है। अथवा ज्ञाता जिज्ञासु गणधर देवके प्रश्नके अनुसार उत्तर वाक्यरूप धर्मकथा, पूछे गये अस्तित्व-नास्तित्व आदिके स्वरूपका कथन अथवा ज्ञाता तीर्थंकर गणधर इन्द्र चक्रवर्ती आदिके धर्मानुबन्धी कथोपकथन जिसमें हो वह ज्ञातृधर्मकथा नामक छठा अंग है ॥३५६॥

वाक्यानि प्रज्ञाप्यंते कथ्यन्ते यस्यां सा व्याख्याप्रज्ञप्तिनाम पंचममंगं । नाथस्त्रिलोकेश्वराणां स्वामी तीर्त्थंकरपरमभट्टारकस्तस्य धर्म्मकथा जीवादिवस्तुस्वभावकथनं । घातिकर्म्मक्षयानंतर-केवलज्ञानसहोत्पन्नतीर्त्थंकरत्वपुण्यातिशयविजृंभितमहिम्नस्तीर्त्थंकरस्य पूर्व्वाह्नमध्याह्नापराह्णाऽर्द्धरात्रिषु षट् षट् घटिकाकालपर्य्यंतं द्वादशगणसभामध्ये स्वभावतो दिव्यध्वनिरुद्गच्छत्यन्यकालेपि गणधरशक्रचक्रधरप्रश्नानंतरं चोद्भवति । एवं समुद्भूतो दिव्यध्वनिः समस्तासन्नश्रोतृगणानुद्दिश्य उत्तमक्षमादिलक्षणं वा धर्म्मं कथयति । अथवा ज्ञातुर्गणधरदेवस्य जिज्ञासमानस्य प्रश्नानुसारेण तदुत्तरवाक्यरूपा धर्म्मकथातत्पृष्टास्तित्वनास्तित्वादिस्वरूपकथनं । अथवा ज्ञातृणां तीर्त्थंकर-गणधरशक्रचक्रधरादीनां धर्म्मानुबंधिकथोपकथाकथनं ज्ञातृधर्म्मकथानाम षष्ठमंगं ।

तो वासयअज्झयणे अंतयडेणुत्तरोववाददसे ।
पण्हाणं वायरणे विवायसुत्ते य पदसंखा ॥३५७॥

तत उपासकाध्ययने अंतकृद्दशे अनुत्तरोपपाददशे । प्रश्नानां व्याकरणे विपाकसूत्रे च पद-संख्या ॥

गणधरदेवप्रश्नवाक्यानि प्रज्ञाप्यन्ते कथ्यन्ते यस्यां सा व्याख्याप्रज्ञप्तिनाम पञ्चममङ्गं । नाथः—त्रिलोकेश्वराणां स्वामी तीर्थंकरपरमभट्टारकः तस्य धर्मकथा जीवादिवस्तुस्वभावकथनं, घातिकर्मक्षयानन्तरकेवलज्ञानसहोत्पन्नतीर्थंकरत्वपुण्यातिशयविजृम्भितमहिम्नः तीर्थंकरस्य पूर्वाह्णमध्याह्नापराह्णार्धरात्रेषु षट्षट्घटिकाकाल-पर्यन्तं द्वादशगणसभामध्ये स्वभावतो दिव्यध्वनिरुद्गच्छति । अन्यकालेऽपि गणधरशक्रचक्रधरप्रश्नानन्तरं चोद्भवति । एवं समुद्भूतो दिव्यध्वनिः समस्तासन्नश्रोतृगणानुद्दिश्य उत्तमक्षमादिलक्षणं रत्नत्रयात्मकं वा धर्मं कथयति । अथवा ज्ञातुर्गणधरदेवस्य जिज्ञासमानस्य प्रश्नानुसारेण तदुत्तरवाक्यरूपा धर्मकथा तत्पृष्टा-स्तित्वनास्तित्वादिस्वरूपकथनं, अथवा ज्ञातृणां तीर्थंकरगणधरशक्रचक्रधरादीनां धर्मानुबन्धिकथोपकथाकथनं नाथधर्मकथा ज्ञातृधर्मकथानाम वा षष्ठमङ्गम् ॥३५६॥

अंगमें होता है। क्या जीव है या नहीं है ? क्या जीव एक है या अनेक है ? क्या जीव नित्य है या अनित्य है ? क्या जीव वक्तव्य है या अवक्तव्य है इत्यादि गणधरदेवके साठ हजार प्रश्न भगवान् अर्हन्त तीर्थंकरके पासमें पूछे गये जिसमें विशेष अर्थात् बहुत प्रकारसे प्रज्ञाप्यन्ते कहे जाते हैं वह व्याख्याप्रज्ञप्ति नामक पाँचवाँ अंग है। नाथ अर्थात् तीनों लोकों-के ईश्वरोंका स्वामी तीर्थंकर परम भट्टारकको धर्मकथा—जीवादि वस्तुओंके स्वभावका कथन, कि घातिकर्मोंके क्षयके अनन्तर केवलज्ञानके साथ उत्पन्न तीर्थंकर नामक पुण्याति-शयसे जिनकी महिमा बढ़ गयी है उन तीर्थंकरकी पूर्वाह्न, मध्याह्न, अपराह्न और अर्धरात्रिमें छह-छह घड़ी काल पर्यन्त बारह गणोंकी सभाके मध्य स्वभावसे दिव्यध्वनि खिरती है, अन्य समयमें भी गणधर, इन्द्र और चक्रवर्तीके प्रश्न करनेपर खिरती है। इस प्रकार उत्पन्न हुई दिव्यध्वनि समस्त निकटवर्ती श्रोतागणोंके उद्देशसे उत्तमक्षमादि लक्षणरूप रत्नत्रयात्मक धर्म-का कथन करती है। अथवा ज्ञाता जिज्ञासु गणधर देवके प्रश्नके अनुसार उत्तर वाक्यरूप धर्मकथा, पूछे गये अस्तित्व-नास्तित्व आदिके स्वरूपका कथन अथवा ज्ञाता तीर्थंकर गण-धर इन्द्र चक्रवर्ती आदिके धर्मानुबन्धी कथोपकथन जिसमें हो वह ज्ञातृधर्मकथा नामक छठा अंग है ॥३५६॥

प्रश्नानि प्रज्ञाप्यन्ते कथ्यन्ते यस्यां सा व्याख्याप्रज्ञप्तिनाम पंचममंगं। नाथस्त्रिलोकेश्वराणां स्वामी तीर्थंकरपरमभट्टारकस्तस्य धर्मकथा जीवादिवस्तुस्वभावकथनं। घातिकर्मक्षयानंतरकेवलज्ञानसहोत्पन्नतीर्थंकरत्वपुण्यातिशयविजृंभितमहिम्नस्तीर्थंकरस्य पूर्वाह्णमध्याह्नापराह्णार्धरात्रिषु षट् षट् घटिकाकालपर्यंतं द्वादशगणसभामध्ये स्वभावतो दिव्यध्वनिरुद्गच्छत्यन्यकालेपि गणधरशक्रचक्रधरप्रश्नानंतरं चोद्भवति। एवं समुद्भूतो दिव्यध्वनिः समस्तासन्नश्रोतृगणानुद्दिश्य उत्तमक्षमादिलक्षणं वा धर्मं कथयति। अथवा ज्ञातृगणधरदेवस्य जिज्ञासमानस्य प्रश्नानुसारेण तदुत्तरवाक्यरूपा धर्मकथा तत्पृष्टास्तित्वनास्तित्वादिस्वरूपकथनं। अथवा ज्ञातृणां तीर्थंकरगणधरशक्रचक्रधरादीनां धर्मानुबंधिकथोपकथनं ज्ञातृधर्मकथानाम षष्ठमंगं।

तो वासयअज्झयणे अंतयडेणुत्तरोववाददसे।
पण्हाणं वायरणे विवायसुत्ते य पदसंखा ॥३५७॥

ततः उपासकाध्ययने अंतकृद्दशे अनुत्तरौपपादिकदशे। प्रश्नानां व्याकरणे विपाकसूत्रे च पदसंख्या ॥

गणधरदेवेन ... प्रश्नानि प्रज्ञाप्यन्ते कथ्यन्ते यस्यां सा व्याख्याप्रज्ञप्तिनाम पञ्चममङ्गम्। नाथः—त्रिलोकेश्वराणां स्वामी तीर्थंकरपरमभट्टारकः तस्य धर्मकथा जीवादिवस्तुस्वभावकथनं, घातिकर्मक्षयानन्तरकेवलज्ञानसहोत्पन्नतीर्थंकरत्वपुण्यातिशयविजृम्भितमहिम्नः तीर्थंकरस्य पूर्वाह्णमध्याह्नापराह्णार्धरात्रेषु षट्षट्घटिकाकालपर्यन्तं द्वादशगणसभामध्ये स्वभावतो दिव्यध्वनिरुद्गच्छति। अन्यकालेऽपि गणधरशक्रचक्रधरप्रश्नानन्तरं चोद्भवति। एवं समुद्भूतो दिव्यध्वनिः समस्तासन्नश्रोतृगणानुद्दिश्य उत्तमक्षमादिलक्षणं रत्नत्रयात्मकं वा धर्मं कथयति। अथवा ज्ञातृगणधरदेवस्य जिज्ञासमानस्य प्रश्नानुसारेण तदुत्तरवाक्यरूपा धर्मकथा तत्पृष्टास्तित्वनास्तित्वादिस्वरूपकथनं, अथवा ज्ञातृणां तीर्थंकरगणधरशक्रचक्रधरादीनां धर्मानुबन्धिकथोपकथनं ज्ञातृधर्मकथा ज्ञातृधर्मकथाख्यं वा षष्ठमङ्गम् ॥३५६॥

अंगमें होता है। क्या जीव है या नहीं है? क्या जीव एक है या अनेक है? क्या जीव नित्य है या अनित्य है? क्या जीव वक्तव्य है या अवक्तव्य है इत्यादि गणधरदेवके साठ हजार प्रश्न भगवान् अर्हन्त तीर्थंकरके पासमें पूछे गये जिसमें विशेष अर्थात् बहुत प्रकारसे प्रज्ञापन किये जाते हैं वह व्याख्याप्रज्ञप्ति नामक पाँचवाँ अंग है। नाथ अर्थात् तीनों लोकोंके ईश्वरोंका स्वामी तीर्थंकर परम भट्टारककी धर्मकथा—जीवादि वस्तुओंके स्वभावका कथन, कि घातिकर्मोंके क्षयके अनन्तर केवलज्ञानके साथ उत्पन्न तीर्थंकर नामक पुण्यातिशयसे जिनकी महिमा बढ़ गयी है उन तीर्थंकरकी पूर्वाह्ण, मध्याह्न, अपराह्ण और अर्धरात्रिमें छह-छह घड़ी काल पर्यन्त बारह गणोंकी सभाके मध्य स्वभावसे दिव्यध्वनि खिरती है, अन्य समयमें भी गणधर, इन्द्र और चक्रवर्तीके प्रश्न करनेपर खिरती है। इस प्रकार उत्पन्न हुई दिव्यध्वनि समस्त निकटवर्ती श्रोतागणोंके उद्देशसे उत्तमक्षमादि लक्षणरूप रत्नत्रयात्मक धर्मका कथन करती है। अथवा ज्ञाता जिज्ञासु गणधर देवके प्रश्नके अनुसार उत्तर वाक्यरूप धर्मकथा, पूछे गये अस्तित्व-नास्तित्व आदिके स्वरूपका कथन अथवा ज्ञाता तीर्थंकर गणधर इन्द्र चक्रवर्ती आदिके धर्मानुबन्धी कथोपकथन जिसमें हो वह ज्ञातृधर्मकथा नामक छठा अंग है ॥३५६॥

वाक्यानि प्रज्ञाप्यंते कथ्यन्ते यस्यां सा व्याख्याप्रज्ञप्तिनाम पंचममंगं । नाथस्त्रिलोकेश्वराणां स्वामी तीर्थंकरपरमभट्टारकस्तस्य धर्म्मकथा जीवादिवस्तुस्वभावकथनं । घातिकर्म्मक्षयानंतरकेवलज्ञानसहोत्पन्नतीर्त्थंकरत्वपुण्यातिशयविजृंभितमहिम्नस्तीर्त्थंकरस्य पूर्व्वाह्णमध्याह्नापराह्णार्द्धरात्रिषु षट् षट् घटिकाकालपर्यंतं द्वादशगणसभामध्ये स्वभावतो दिव्यध्वनिरुद्गच्छत्यन्यकालेपि गणधरशक्रचक्रधरप्रश्नानंतरं चोद्भवति । एवं समुद्भूतो दिव्यध्वनिः समस्तासन्नश्रोतृगणानुद्दिश्य उत्तमक्षमादिलक्षणं वा धर्म्मं कथयति । अथवा ज्ञातुर्गणधरदेवस्य जिज्ञासमानस्य प्रश्नानुसारेण तदुत्तरवाक्यरूपा धर्म्मकथातत्पृष्टास्तित्वनास्तित्वादिस्वरूपकथनं । अथवा ज्ञातृणां तीर्थंकरगणधरशक्रचक्रधरादीनां धर्म्मानुबंधिकथोपकथाकथनं ज्ञातृधर्म्मकथानाम षष्ठमंगं ।

तो वासयअज्झयणे अंतयडेणुत्तरोववाददसे ।
पण्हाणं वायरणे विवायसुत्ते य पदसंखा ॥३५७॥

तत उपासकाध्ययने अंतकृद्दशे अनुत्तरोपपादवशे । प्रश्नानां व्याकरणे विपाकसूत्रे च पदसंख्या ॥

गणधरदेवप्रश्नवाक्यानि प्रज्ञाप्यन्ते कथ्यन्ते यस्यां सा व्याख्याप्रज्ञप्तिनाम पञ्चममङ्गं । नाथः—त्रिलोकेश्वराणां स्वामी तीर्थंकरपरमभट्टारकः तस्य धर्मकथा जीवादिवस्तुस्वभावकथनं, घातिकर्मक्षयानन्तरकेवलज्ञानसहोत्पन्नतीर्थंकरत्वपुण्यातिशयविजृम्भितमहिम्नः तीर्थंकरस्य पूर्वाह्णमध्याह्नापराह्णार्धरात्रेषु षट्षट्घटिकाकालपर्यन्तं द्वादशगणसभामध्ये स्वभावतो दिव्यध्वनिरुद्गच्छति । अन्यकालेऽपि गणधरशक्रचक्रधरप्रश्नानन्तरं चोद्भवति । एवं समुद्भूतो दिव्यध्वनिः समस्तासन्नश्रोतृगणानुद्दिश्य उत्तमक्षमादिलक्षणं रत्नत्रयात्मकं वा धर्मं कथयति । अथवा ज्ञातुर्गणधरदेवस्य जिज्ञासमानस्य प्रश्नानुसारेण तदुत्तरवाक्यरूपा धर्मकथा तत्पृष्टास्तित्वनास्तित्वादिस्वरूपकथनं, अथवा ज्ञातृणां तीर्थंकरगणधरशक्रचक्रधरादीनां धर्मानुबन्धिकथोपकथाकथनं नाथधर्मकथा ज्ञातृधर्मकथानाम वा षष्ठमङ्गम् ॥३५६॥

अंगमें होता है। क्या जीव है या नहीं है ? क्या जीव एक है या अनेक है ? क्या जीव नित्य है या अनित्य है ? क्या जीव वक्तव्य है या अवक्तव्य है इत्यादि गणधरदेवके साठ हजार प्रश्न भगवान् अर्हन्त तीर्थंकरके पासमें पूछे गये जिसमें विशेष अर्थात् बहुत प्रकारसे प्रज्ञाप्यन्ते कहे जाते हैं वह व्याख्याप्रज्ञप्ति नामक पाँचवाँ अंग है। नाथ अर्थात् तीनों लोकोंके ईश्वरोंका स्वामी तीर्थंकर परम भट्टारकको धर्मकथा—जीवादि वस्तुओंके स्वभावका कथन, कि घातिकर्मोंके क्षयके अनन्तर केवलज्ञानके साथ उत्पन्न तीर्थंकर नामक पुण्यातिशयसे जिनकी महिमा बढ़ गयी है उन तीर्थंकरकी पूर्वाह्न, मध्याह्न, अपराह्न और अर्धरात्रिमें छह-छह घड़ी काल पर्यन्त बारह गणोंकी सभाके मध्य स्वभावसे दिव्यध्वनि खिरती है, अन्य समयमें भी गणधर, इन्द्र और चक्रवर्तीके प्रश्न करनेपर खिरती है। इस प्रकार उत्पन्न हुई दिव्यध्वनि समस्त निकटवर्ती श्रोतागणोंके उद्देशसे उत्तमक्षमादि लक्षणरूप रत्नत्रयात्मक धर्मका कथन करती है। अथवा ज्ञाता जिज्ञासु गणधर देवके प्रश्नके अनुसार उत्तर वाक्यरूप धर्मकथा, पूछे गये अस्तित्व-नास्तित्व आदिके स्वरूपका कथन अथवा ज्ञाता तीर्थंकर गणधर इन्द्र चक्रवर्ती आदिके धर्मानुबन्धी कथोपकथन जिसमें हो वह ज्ञातृधर्मकथा नामक छठा अंग है ॥३५६॥

प्रश्नगानि प्रज्ञाप्यंते कथ्यन्ते यस्यां सा व्याख्याप्रज्ञप्तिनाम पंचममंगं । नाथस्त्रिलोकेश्वराणां स्वामी तीर्थंकरपरमभट्टारकस्तस्य धर्म्मकथा जीवादिवस्तुस्वभावकथनं । घातिकर्म्मक्षयानंतरकेवलज्ञानसहोत्पन्नतीर्थंकरत्वपुण्यातिशयविजृंभितमहिम्नस्तीर्थंकरस्य पूर्व्वाह्णमध्याह्नापराह्णार्द्धरात्रिषु षट् षट् घटिकाकालपर्यंतं द्वादशगणसभामध्ये स्वभावतो दिव्यध्वनिरुद्गच्छत्यन्यकालेऽपि गणधरशक्रचक्रधरप्रश्नानंतरं चोद्भवति । एवं समुद्भूतो दिव्यध्वनिः समस्तासन्नश्रोतृगणानुद्दिश्य उत्तमक्षमादिलक्षणं वा धर्म्मं कथयति । अथवा ज्ञातुर्ग्गणधरदेवस्य जिज्ञासमानस्य प्रश्नानुसारेण तदुत्तरवाक्यरूपा धर्म्मकथातत्पृष्टास्तित्वनास्तित्वादिस्वरूपकथनं । अथवा ज्ञातॄणां तीर्थंकरगणधरशक्रचक्रधरादीनां धर्म्मानुबंधिकथोपकथाकथनं ज्ञातृधर्म्मकथानाम षष्ठमंगं ।

तो वासयअज्झयणे अंतयडेणुत्तरोववाददसे ।
पण्हाणं वायरणे विवायसुत्ते य पदसंखा ॥३५७॥

तत उपासकाध्ययने अंतकृद्दशे अनुत्तरोपपादकदशे । प्रश्नानां व्याकरणे विपाकसूत्रे च पदसंख्या ॥

गणधरदेवप्रश्नवाक्यानि प्रज्ञाप्यन्ते कथ्यन्ते यस्यां सा व्याख्याप्रज्ञप्तिनाम पञ्चममङ्गं । नाथः—त्रिलोकेश्वराणां स्वामी तीर्थंकरपरमभट्टारकः तस्य धर्मकथा जीवादिवस्तुस्वभावकथनं, घातिकर्मक्षयानन्तरकेवलज्ञानसहोत्पन्नतीर्थंकरत्वपुण्यातिशयविजृम्भितमहिम्नः तीर्थंकरस्य पूर्वाह्णमध्याह्नापराह्णार्धरात्रेषु षट्षट्घटिकाकालपर्यन्तं द्वादशगणसभामध्ये स्वभावतो दिव्यध्वनिरुद्गच्छति । अन्यकालेऽपि गणधरशक्रचक्रधरप्रश्नानन्तरं चोद्भवति । एवं समुद्भूतो दिव्यध्वनिः समस्तासन्नश्रोतृगणानुद्दिश्य उत्तमक्षमादिलक्षणं रत्नत्रयात्मकं वा धर्मं कथयति । अथवा ज्ञातुर्गणधरदेवस्य जिज्ञासमानस्य प्रश्नानुसारेण तदुत्तरवाक्यरूपा धर्मकथा तत्पृष्टास्तित्वनास्तित्वादिस्वरूपकथनं, अथवा ज्ञातॄणां तीर्थंकरगणधरशक्रचक्रधरादीनां धर्मानुबन्धिकथोपकथाकथनं नाथधर्मकथा ज्ञातृधर्मकथानाम वा षष्ठमङ्गम् ॥३५६॥

अंगमें होता है। क्या जीव है या नहीं है ? क्या जीव एक है या अनेक है ? क्या जीव नित्य है या अनित्य है ? क्या जीव वक्तव्य है या अवक्तव्य है इत्यादि गणधरदेवके साठ हजार प्रश्न भगवान् अर्हन्त तीर्थंकरके पासमें पूछे गये जिसमें विशेष अर्थात् बहुत प्रकारसे प्रज्ञाप्यन्ते कहे जाते हैं वह व्याख्याप्रज्ञप्ति नामक पाँचवाँ अंग है। नाथ अर्थात् तीनों लोकोंके ईश्वरोंके स्वामी तीर्थंकर परम भट्टारककी धर्मकथा—जीवादि वस्तुओंके स्वभावका कथन, कि घातिकर्मोंके क्षयके अनन्तर केवलज्ञानके साथ उत्पन्न तीर्थंकर नामक पुण्यातिशयसे जिनकी महिमा बढ़ गयी है उन तीर्थंकरकी पूर्वाह्ण, मध्याह्न, अपराह्ण और अर्धरात्रिमें छह-छह घड़ी काल पर्यन्त बारह गणोंकी सभाके मध्य स्वभावसे दिव्यध्वनि खिरती है, अन्य समयमें भी गणधर, इन्द्र और चक्रवर्तीके प्रश्न करनेपर खिरती है। इस प्रकार उत्पन्न हुई दिव्यध्वनि समस्त निकटवर्ती श्रोतागणोंके उद्देशसे उत्तमक्षमादि लक्षणरूप रत्नत्रयात्मक धर्मका कथन करती है। अथवा ज्ञाता जिज्ञासु गणधर देवके प्रश्नके अनुसार उत्तर वाक्यरूप धर्मकथा, पूछे गये अस्तित्व-नास्तित्व आदिके स्वरूपका कथन अथवा ज्ञाता तीर्थंकर गणधर इन्द्र चक्रवर्ती आदिके धर्मानुबन्धी कथोपकथन जिसमें हो वह ज्ञातृधर्मकथा नामक छठा अंग है ॥३५६॥

अभय वारिषेण चिलातपुत्रा इत्येते दारुण महोपसर्गान्विजित्येंद्रादिकृतां पूजां लब्ध्वाऽनुत्तरविमाने- पूपपन्नाः। एवं वृषभादितीर्थेष्वपि परमागमानुसारेण ज्ञातव्याः। प्रश्नस्य दूतवाक्यनष्टमुष्टिचितादि- रूपस्यार्त्थः त्रिकालगोचरो धनधान्यादिलाभालाभसुखदुःखजीवितमरणजयपराजयादिरूपो व्याक्रियते व्याख्यायते यस्मिन् तत्प्रश्नव्याकरणं। अथवा शिष्यप्रश्नानुरूपतया आक्षेपणी विक्षेपणी संवेजनी निर्व्वेजनी चेति कथा चतुर्व्विधा। तत्र प्रथमानुयोग करणानुयोग चरणानुयोगद्रव्यानुयोगरूपपरमागम- पदार्त्थानां तीर्त्थंकरादिवृत्तांतलोकसंस्थानदेशसकलयतिधर्म्मपंचास्तिकायादीनां परमताशंकारहितं कथनमाक्षेपणीकथा। प्रमाणनयात्मकयुक्तियुक्तहेतुवादबलेन[1]सर्व्वथैकांतादिपरसमयार्त्थनिराकरणरूपा विक्षेपणीकथा। रत्नत्रयात्मकधर्म्मानुष्ठानफलभूततीर्त्थंकराद्यैश्वर्य्यप्रभावतेजोवीर्य्यज्ञानसुखादि- वर्णनारूपा संवेदनीकथा। संसारशरीरभोगजनितदुःकर्म्मफलनारकादिदुःखदुःकुलविरूपांग- दारिद्र्यापमानदुःखादिवर्णनाद्वारेण वैराग्यकथनरूपा निर्व्वेजनीकथा। एवंविधाः कथाः व्याक्रियंते

धन्य-सुनक्षत्र-कार्तिकेय-नन्द-नन्दन-शालिभद्र-अभय-वारिषेण-चिलातपुत्रा इत्येते दारुणमहोपसर्गान् विजित्य इन्द्रादिकृतां पूजां लब्ध्वा अनुत्तरविमानेषूपपन्नाः। एवं वृषभादितीर्थेष्वपि परमागमानुसारेण ज्ञातव्याः। प्रश्नस्य—दूतवाक्यनष्टमुष्टिचिन्तादिरूपस्य अर्थः त्रिकालगोचरो धनधान्यादिलाभालाभसुखदुःखजीवितमरणजय- पराजयादिरूपो व्याक्रियते व्याख्यायते यस्मिंस्तत्प्रश्नव्याकरणम्। अथवा शिष्यप्रश्नानुरूपतया आक्षेपणी विक्षे- पणी संवेजनी निर्वेजनी चेति कथा चतुर्विधा। तत्र प्रथमानुयोगकरणानुयोगचरणानुयोगद्रव्यानुयोगरूपपरमागम- पदार्थानां तीर्थंकरादिवृत्तान्तलोकसंस्थानदेशसकलयतिधर्मपञ्चास्तिकायादीनां परमताशङ्कारहितं कथनमाक्षेपणी कथा। प्रमाणनयात्मकयुक्तियुक्तहेतुत्वादिबलेन सर्वथैकान्तादि परसमयार्थनिराकरणरूपा विक्षेपणी कथा। रत्नत्रयात्मकधर्मानुष्ठानफलभूततीर्थंकराद्यैश्वर्यप्रभावतेजोवीर्यज्ञानसुखादिवर्णनारूपा संवेजनी कथा। संसार- शरीरभोगरागजनितदुष्कर्मफलनारकादिदुःखदुष्कुलविरूपाङ्गदारिद्र्यापमानदुःखादिवर्णनाद्वारेण वैराग्यकथनरूपा

स्वामीके तीर्थमें ऋजुदास, धन्य, सुनक्षत्र, कार्तिकेय, नन्द, नन्दन, शालिभद्र, अभय, वारिषेण, चिलातपुत्र ये दारुण महा उपसर्गोंको जीतकर इन्द्रादिके द्वारा की गयी पूजाको प्राप्त करके अनुत्तर विमानमें उत्पन्न हुए। इसी प्रकार ऋषभ आदि तीर्थंकरोंके तीर्थमें भी परमागमके अनुसार जानना। प्रश्न अर्थात् दूतवाक्य, नष्ट, मुष्टि चिन्तादि विषयक प्रश्नका त्रिकाल गोचर अर्थ जो धनधान्य आदिकी लाभ-हानि, सुख-दुःख, जीवन-मरण, जय-पराजय आदि- से सम्बद्ध है वह जिसमें व्याक्रियते अर्थात् उत्तरित किया गया हो, वह प्रश्नव्याकरण है। अथवा शिष्योंके प्रश्नके अनुसार अवक्षेपणी विक्षेपणी, संवेजनी और निर्वेजनी ये चार कथाएँ जिसमें वर्णित हों वह प्रश्नव्याकरण है। तीर्थंकर आदिके इतिवृत्तको कहनेवाले प्रथमानुयोग, लोकके आकार आदिका कथन करनेवाले करणानुयोग, देशचारित्र और सकलचारित्रको कहनेवाले चरणानुयोग तथा पंचास्तिकाय आदिका कथन करनेवाले द्रव्यानुयोग रूप परमागमके पदार्थोंका परमतकी आशंकाको दूर करते हुए कथनको आक्षे- पणी कथा कहते हैं। प्रमाणनयात्मक युक्ति तथा हेतु आदिके बलसे सर्वथा एकान्त आदि अन्य मतोंका निराकरण करानेवाली कथाको विक्षेपणी कथा कहते हैं। रत्नत्रयात्मक धर्मका अनुष्ठान करनेके फलस्वरूप तीर्थंकर आदिके ऐश्वर्य, प्रभाव, तेज, ज्ञान, सुख, वीर्य आदिका कथन करनेवाली संवेजनी कथा है। संसार शरीर और भोगोंसे राग करनेसे दुष्कर्मका बन्ध होता है और उसके फलस्वरूप नारक आदिका दुःख, दुष्कुलकी प्राप्ति, शरीरोंके अंगोंका विरूपपना, दारिद्र्य, अपमान आदिके वर्णनके द्वारा वैराग्यका कथन करनेवाली निर्वेजनी

---

१. अवक्षे–मु।

कर्म्ममेंदु प्रकोरकक्कुमदे तें दोडे चंद्रप्रज्ञप्तियुं । सूर्य्यप्रज्ञप्तियुं । जंबूद्वीपप्रज्ञप्तियुं । द्वीपसागरप्रज्ञप्तियुं व्याख्याप्रज्ञप्तियुमें दितु चंद्रप्रज्ञप्तियें बुदु चंद्रविमानायुःपरिवारऋद्धिगमनहानिवृद्धिसकलार्द्धचतुर्त्थांशग्रहणादिगळं वर्णिसुगुं । सूर्य्यप्रज्ञप्तियें बुदु सूर्य्यनायुर्म्मंडलपरिवारऋद्धिगमनप्रमाणग्रहणादिगळं वर्णिसुगुं । जंबूद्वीपप्रज्ञप्तियें बुदु जंबूद्वीपगतमेरुकुलशैलह्रदवर्षकुंडवेदिकावनषंडव्यंतरावासमहानदिगळमोदलादुवं वर्णिसुगुं । द्वीपसागरप्रज्ञप्तियें बुदु असंख्यातद्वीपसागरंगळ स्वरूपमं तत्रस्थितज्योतिर्व्वानभावनावासंगळोळु विद्यमानंगळप्पकृत्रिमजिनभवनादिगळ वर्णनमं माळ्कुं । व्याख्याप्रज्ञप्तियें बुदु रूप्यरूपिजीवाजीवद्रव्यंगळ भव्याभव्यभेदप्रमाणलक्षणंगळ, अनंतरसिद्ध परंपरासिद्धरुगळ पेरवुं वस्तुगळ वर्णनमं माळ्कुं । सूत्रयति सूचयति कुदृष्टिदर्शनानिति सूत्रं । जीवोऽबंधकोऽकर्त्ता निर्गुणोऽभोक्ताऽस्वप्रकाशकः परप्रकाशकोस्त्येव जीवो नास्त्येव जीव इत्यादिक्रियाक्रियाज्ञानविनयकुदृष्टिनां त्रिषष्टयुत्तरत्रिशतमिथ्यादर्शनंगळं पूर्व्वपक्षतेयिंदं पेळ्गुं । प्रथमानुयोगमें बुदु प्रथमं मिथ्यादृष्टिमव्रतिकमव्युत्पन्नं वा प्रतिपाद्यमाश्रित्य प्रवृत्तोऽनुयोगोऽधिकारः प्रथमानुयोगः ।

परितः सर्वतः कर्माणि गणितकरणसूत्राणि यस्मिन् तत्परिकर्म, तच्च पञ्चविधं चन्द्रप्रज्ञप्तिः सूर्यप्रज्ञप्तिः जम्बूद्वीपप्रज्ञप्तिः द्वीपसागरप्रज्ञप्तिः व्याख्याप्रज्ञप्तिश्चेति । तत्र चन्द्रप्रज्ञप्तिः चन्द्रस्य विमानायुःपरिवारऋद्धिगमनहानिवृद्धिसकलार्धचतुर्थांशग्रहणादीन् वर्णयति । सूर्यप्रज्ञप्तिः सूर्यस्यायुर्मण्डलपरिवारऋद्धिगमनप्रमाणग्रहणादीन्वर्णयति । जम्बूद्वीपप्रज्ञप्तिः जम्बूद्वीपगतमेरुकुलशैलह्रदवर्षकुण्डवेदिकावनखण्डव्यन्तरावासमहानद्यादीन् वर्णयति । द्वीपसागरप्रज्ञप्तिः असंख्यातद्वीपसागराणां स्वरूपं तत्रस्थितज्योतिर्वनभावनावासेषु विद्यमानाकृत्रिमजिनभवनादीन् वर्णयति । व्याख्याप्रज्ञप्तिः रूप्यरूपिजीवाजीवद्रव्याणां भव्याभव्यभेदप्रमाणलक्षणानां अनन्तरसिद्धपरम्परासिद्धानां अन्यवस्तूनां च वर्णनं करोति । सूत्रयति—सूचयति कुदृष्टिदर्शनानीति सूत्रम् । जीवः अबन्धकः अकर्ता निर्गुणः अभोक्ता स्वप्रकाशकः परप्रकाशकः अस्त्येव जीवः नास्त्येव जीवः इत्यादि क्रियाक्रियाज्ञानविनयकुदृष्टीनां त्रिषष्ट्युत्तरत्रिशतमिथ्यादर्शनानि पूर्वपक्षतया कथयति । प्रथमानुयोगः प्रथमं मिथ्यादृष्टिमव्रतिकमव्युत्पन्नं वा प्रतिपाद्यमाश्रित्य प्रवृत्तोऽनुयोगोऽधिकारः प्रथमानुयोगः । चतुर्विंशतितीर्थंकरद्वादश-

---

'परितः' अर्थात् पूरी तरहसे 'कर्माणि' अर्थात् गणितके करणसूत्र जिसमें हैं वह परिकर्म है। उसके भी पाँच भेद हैं—चन्द्रप्रज्ञप्ति, सूर्यप्रज्ञप्ति, जम्बूद्वीपप्रज्ञप्ति, द्वीपसागरप्रज्ञप्ति, व्याख्याप्रज्ञप्ति। उनमें-से चन्द्रप्रज्ञप्ति चन्द्रमाके विमान, आयु, परिवार, ऋद्धि, गमन, हानि, वृद्धि, पूर्णग्रहण, अर्धग्रहण, चतुर्थांशग्रहण आदिका वर्णन करती है। सूर्यप्रज्ञप्ति सूर्यकी आयु, मण्डल, परिवार, ऋद्धि, गमनका प्रमाण तथा ग्रहण आदिका वर्णन करती है। जम्बूद्वीपप्रज्ञप्ति जम्बूद्वीपगत मेरु, कुलाचल, तालाब, क्षेत्र, कुण्ड, वेदिका, वनखण्ड, व्यन्तरोंके आवास, महानदी आदिका वर्णन करती है। द्वीपसागरप्रज्ञप्ति असंख्यात द्वीप-समुद्रोंके स्वरूप, उनमें स्थित ज्योतिषीदेवों, व्यन्तरों और भवनवासी देवोंके आवासोंमें वर्तमान अकृत्रिम जिनालयोंका वर्णन करती है। व्याख्याप्रज्ञप्ति रूपी-अरूपी, जीव-अजीव द्रव्योंका, भव्य और अभव्य भेदोंका, उनके प्रमाण और लक्षणोंका, अनन्तर सिद्ध और परम्परा सिद्धोंका तथा अन्य वस्तुओंका वर्णन करती है। 'सूत्रयति' अर्थात् जो मिथ्यादृष्टि दर्शनोंको सूचित करता है वह सूत्र है। जीव अबन्धक है, अकर्ता है, निर्गुण है, अभोक्ता है, स्वप्रकाशक नहीं है, परप्रकाशक है, जीव अस्ति ही है या नास्ति ही है इत्यादि क्रियावादी, अक्रियावादी, अज्ञानी और वैनयिक मिथ्यादृष्टियोंके तीन सौ तिरसठ मतोंको पूर्वपक्षके रूपमें कहता है।

---

१. म प्रकारमरंतेने । २. क °तु मल्लि चं° ।

गतनम मनगं गोरम मरगत जवगातनोननं जजलक्खा ।
मननन धममननोननननामं रनधजधरानन जलादी ॥३६३॥
याजकनामेनाननमेदाणि पदाणि होंति परियम्मे ।
कानवधिदाचनाननमेसो पुण चूलियाजोगो ॥३६४॥

ग । त्रि । त । षट् । न । शून्य । म । पंच । म । पंच । न । शून्य । यं । त्रि । गो । त्रि । र । द्वि । म । पंच । म । पंच । र । द्वि । ग । त्रि । त । षट् । ज । अष्ट । व । चतुः । गा । त्रि । त । षट् । नोननं । शून्य । शून्य । शून्य । ज । अष्ट । ज । अष्ट । लक्षाणि । म । पंच । न । मन । शून्य । शून्य । शून्य । ध । नव । म । पंच । म । पंच । न । शून्य । नो । शून्य । न । शून्य । ना । शून्य । म । पंच । रा । द्वि । न । शून्य । ध । नव । ज । अष्ट । ध । नव । रा । द्वि । न । शून्य । न । शून्य । जलादयः ॥

या । एक । ज । अष्ट । क एक । ना शून्य । मे । पंच । ना शून्य । न शून्य । न शून्य । मेतानि पदानि भवंति । परिकर्म्मणि । का । एक । न शून्य । व । चतुः । धि । नव । दा चतुः । च षट् । ना शून्य । न शून्य । न शून्य । मेषः पुनश्चूलिकायोगः । अक्षरसंज्ञेयिदं गतनमनोननं षट्त्रिंशल्लक्षपंचसहस्रपदंगळु चंद्रप्रज्ञप्तियोळप्पुवु ३६०५००० । मनगं नोननं पंचलक्षत्रिसहस्रपदंगळु सूर्य्यप्रज्ञप्तियोळप्पुवु ५०३००० । गोरमनोननं त्रिलक्षपंचविंशतिसहस्रपदंगळु जंबूद्वीपप्रज्ञप्तियोळप्पुवु ३२५००० । मरगतनोननं द्विपंचाशल्लक्षषट्त्रिंशत्सहस्रपदंगळु द्वीपसागरप्रज्ञप्तियोळप्पुवु ५२३६००० । जवगातनोननं चतुरशीतिलक्षषट्त्रिंशत्सहस्रपदंगळु व्याख्याप्रज्ञप्तियोळप्पुवु । ८४३६००० । जजलक्खा अष्टाशीतिलक्षपदंगळु सूत्रदोळप्पुवु ८८००००० । मननन पंचसहस्रपदंगळु प्रथमानुयोगदोळप्पुवु ५००० । धममननोननननामं पंचनवतिकोटियुं पंचाशल्लक्षमुमय्दु पदंगळु चतुर्द्दशपूर्व्वसमुच्चयदोळप्पुवु ९५५००००००५ । रनधजधराननजलादि द्विकोटिनवलक्षनवाशीतिसहस्रद्विशतोत्तरपदंगळु प्रत्येकं जलगतादि पंचचूलिकाख्यानंगळोळु समानंगळेयप्पुवु । जलगतंगळु २०९८९२०० स्थलगतंगळु २०९८९२०० मायागतंगळु २०९८९२०० आकाशगतंगळु

अक्षरसंज्ञया चन्द्रप्रज्ञप्तौ गतनमनोननं-षट्त्रिंशल्लक्षपञ्चसहस्राणि पदानि ३६०५००० । सूर्यप्रज्ञप्तौ मनगंनोननं-पञ्चलक्षत्रिसहस्राणि पदानि ५०३००० । जम्बूद्वीपप्रज्ञप्तौ गोरमनोननं त्रिलक्षपञ्चविंशतिसहस्राणि पदानि ३२५००० । द्वीपसागरप्रज्ञप्तौ मरगतनोननं द्विपञ्चाशल्लक्षषट्त्रिंशत्सहस्राणि पदानि ५२३६००० । व्याख्याप्रज्ञप्तौ जवगातनोननं—चतुरशीतिलक्षषट्त्रिंशत्सहस्राणि पदानि ८४३६००० । सूत्रे जजलक्खा—अष्टाशीतिलक्षाणि पदानि ८८००००० । प्रथमानुयोगे मननन—पञ्चसहस्राणि पदानि ५००० । चतुर्दशपूर्वसमुच्चये धमननोननननामं—पञ्चनवतिकोटिपञ्चाशल्लक्षपञ्चपदानि ९५५००००००५ । जलादौ जलगतादिपञ्चचूलिकास्थानेषु प्रत्येकं रनधजधराननं-द्विकोटिनवलक्षनवाशीतिसहस्रद्विशतानि पदानि । २०९८९२०० ।

अक्षरोंकी संज्ञासे चन्द्रप्रज्ञप्तिमें 'गतनमनोननं' अर्थात् छत्तीस लाख पाँच हजार ३६०५००० पद हैं। सूर्यप्रज्ञप्तिमें 'मनगंनोननं' पाँच लाख तीन हजार ५०३००० पद हैं। जम्बूद्वीपप्रज्ञप्तिमें 'गोरमनोननं' तीन लाख पच्चीस हजार ३२५००० पद हैं। द्वीपसागर प्रज्ञप्तिमें 'मरगतनोननं' बावन लाख छत्तीस हजार ५२३६००० पद हैं। व्याख्याप्रज्ञप्तिमें 'जवगातनोनं' चौरासी लाख छत्तीस हजार ८४३६००० पद हैं। सूत्रमें 'जजलक्खा' अठासी लाख ८८००००० पद हैं। प्रथमानुयोगमें 'मननन' पाँच हजार ५००० पद हैं। चौदह पूर्वोंमें 'धममननोननननामं' पंचानवे कोटि पचास लाख पाँच ९५५००००००५ पद हैं। जलगता आदि

परिणतद्रव्यवर्णनमं माळ्कु-। मल्लि द्विलक्षगुणितपंचाशत्सुगळेककोटिपदंगळप्पुवु १०००००००। अयस्य द्वादशांगेषु प्रधानभूतस्य वस्तुनः अयनं ज्ञानमग्रायणं तत्प्रयोजनमग्रायणीयं द्वितीयं पूर्वमोग्रायणी पूर्व्वं सप्तशत सुनय दुर्णय पंचास्तिकाय षड्द्रव्य सप्ततत्व नवपदार्थंगळ मोदलादवनु वर्णिसुगुमल्लि द्विलक्षगुणिताष्टचत्वारिंशत्पदंगळु षण्णवतिलक्षंगळप्पुवेंदुदर्थं।—९६००००० । वीर्य्यस्य जीवादिवस्तुसामर्थ्यस्य अनुप्रवादोनुवर्णनमस्मिन्निति वीर्य्यानुप्रवादमेंबं तृतीयपूर्व्वमदु आत्मवीर्य्यं परवीर्य्यं उभयवीर्य्यं क्षेत्रवीर्य्यं कालवीर्य्यं भाववीर्य्यं तपोवीर्य्य मेंदिवु मोदलाद समस्तद्रव्यगुणपर्यायवीर्य्यंगळं वर्णिसुगुमल्लि द्विलक्षगुणितपंचत्रिंशत्पदंगळु सप्ततिलक्षपदंगळप्पुवेंदुदर्थं—७०००००० । अस्तिनास्तीत्यादि धर्म्माणां प्रवादः प्ररूपणमस्मिन्निति अस्तिनास्तिप्रवादं चतुर्थं पूर्व्वमिदु।

जीवादिवस्तु स्यादस्ति स्वद्रव्यक्षेत्रकालभावानाश्रित्य। स्यान्नास्ति परद्रव्यक्षेत्रकालभावानाश्रित्य। स्यादस्ति च नास्ति च क्रमेण स्वपरद्रव्यक्षेत्रकालभावद्वयं संयुक्तमाश्रित्य। स्यादवक्तव्यं युगपत्स्वपरद्रव्यक्षेत्रकालभावद्वयमाश्रित्य तथा वक्तुमशक्यत्वात्। स्यादस्ति चावक्तव्यं च स्वद्रव्यक्षेत्रकालभावान् युगपत्स्वपरद्रव्यक्षेत्रकालभावद्वयं च संयुक्तमाश्रित्य। स्यान्नास्ति चावक्तव्यं च परद्रव्यक्षेत्रकालभावान्युगपत्स्वपरद्रव्यक्षेत्रकालभावद्वयं च संयुक्तमाश्रित्य। स्यादस्ति च नास्ति चावक्तव्यं च क्रमेण स्वपरद्रव्यक्षेत्रकालभावद्वयं युगपत्स्वपरद्रव्यक्षेत्रकालभावद्वयं च संयुक्तमाश्रित्य एंदितेकानेकनित्यानित्याद्यनंतधर्म्मंगळ्ग विधिनिषेधावक्तव्यभंगंगळ प्रत्येक-

---

द्रव्यस्य वर्णनं करोति। तत्र द्विलक्षगुणितपञ्चाशल्लक्षाणि एका कोटिरित्यर्थः १०००००००। अग्रस्य द्वादशाङ्गेषु प्रधानभूतस्य वस्तुनः अयनं ज्ञानं अग्रायणं। तत्प्रयोजनम् अग्रायणीयं, द्वितीयं पूर्वं। तच्च सप्तशतसुनयदुर्णयपञ्चास्तिकायषड्द्रव्यसप्ततत्त्वनवपदार्थादीन् वर्णयति। तत्र द्विलक्षगुणिताष्टचत्वारिंशल्लक्षाणि षण्णवतिलक्षाणि इत्यर्थः। ९६०००००। वीर्यस्य—जीवादिवस्तुसामर्थ्यस्य अनुप्रवादः—अनुवर्णनं अस्मिन्निति वीर्यानुप्रवादं नाम तृतीयं पूर्वं। तच्च आत्मवीर्यपरवीर्योभयवीर्यक्षेत्रवीर्यकालवीर्यभाववीर्यतपोवीर्यादिसमस्तद्रव्यगुणपर्यायवीर्याणि वर्णयति। तत्र द्विलक्षगुणितपञ्चत्रिंशल्लक्षाणि सप्ततिलक्षाणीत्यर्थः ७००००००। अस्तिनास्तीत्यादिधर्माणां प्रवादः-प्ररूपणमस्मिन्निति अस्तिनास्तिप्रवादं चतुर्थं पूर्वं। तच्च जीवादिवस्तु स्यादस्ति स्वद्रव्यक्षेत्रकालभावानाश्रित्य, स्यान्नास्ति परद्रव्यक्षेत्रकालभावानाश्रित्य। स्यादस्ति नास्ति च क्रमेण स्वपरद्रव्यक्षेत्रकालभावद्वयं संयुक्तमाश्रित्य। स्यादवक्तव्यं युगपत्स्वपरद्रव्यक्षेत्रकालभावद्वयमाश्रित्य तथा वक्तुमशक्यत्वात्। स्यादस्ति

प्रकार हो सकते हैं अतः इत्यादि धर्म परिणत द्रव्यका वर्णन करता है। उसमें दो लाखसे गुणित पचास अर्थात् एक कोटि पद होते हैं। अग्र अर्थात् द्वादशांगमें प्रधान भूत वस्तुका 'अयन' अर्थात् ज्ञान अग्रायण है। वह जिसका प्रयोजन है वह दूसरा पूर्व अग्रायण है। वह सात सौ सुनयों, दुर्नयों, पाँच अस्तिकाय, छह द्रव्य, सात तत्त्व, नौ पदार्थ आदिका वर्णन करता है। उसमें दो लाखसे गुणित अड़तालीस अर्थात् छानबे लाख पद हैं। वीर्य अर्थात् जीवादि वस्तुकी सामर्थ्यका 'अनुप्रवाद' अर्थात् वर्णन जिसमें होता है वह वीर्यानुप्रवाद नामक तीसरा पूर्व है। वह अपने वीर्य, पराये वीर्य, उभयवीर्य, क्षेत्रवीर्य, कालवीर्य, भाववीर्य, तपवीर्य आदि समस्त द्रव्य गुण पर्यायोंके वीर्य[illegible] करता है। उसमें दो लाखसे गुणित पैंतीस अर्थात् सत्तर लाख पद हैं। अस्ति [illegible] धर्मोंका 'प्रवाद' अर्थात् प्ररूपण जिसमें है वह अस्ति-नास्ति [illegible] नाम[illegible] । जीवादि वस्तु स्वद्रव्य, स्वक्षेत्र, स्वकाल और स्वभावकी [illegible] क्षेत्र, परकाल और परभावकी अपेक्षा स्यात्नास्ति [illegible]। क्रमसे [illegible] परद्रव्यक्षेत्रकाल

मदें तें दोडे असत्यनिवृत्तियुं मेणु मौनमुं वाग्गुप्तियुमें बुदक्कुं। उरःकंठ शिरोजिह्वामूलदंत-नासिकाताल्वोष्ठद्वयंगळष्टस्थानंगळुं स्पृष्टतेयपस्पृष्टता विवृततेयद्विवृतता संवृतता एंबिवुं पंच-प्रयत्नंगळुं वाक्संस्कार कारणंगळें बुदक्कुं। शिष्टदुष्टरूपमप्प वाक्प्रयोगमुं तल्लक्षणशास्त्र संस्कृतादि व्याकरणंगळुं वाक्प्रयोगमें बुदक्कुं। इदिवनिदं माडल्पट्टुदें बनिष्टकथनरूपमभ्याख्यानमुं। परस्परविरोधकारणकलहवचनमुं परगे दोषसूचनपैशुन्यवचनमुं। धर्मार्थकाममोक्षासंबंधवचन-रूपमबद्धप्रलापमुं इंद्रियविषयंगळोळु रत्युत्पादिकेयप्प वाग्रतिवचनमुं। अवरोळरत्युत्पादिका वाग्ररतिवचनमुं परिग्रहार्ज्जनसंरक्षणाद्यासक्तिहेतु वागुपधिवचनमें बुदक्कुं। व्यवहारदोळु वंचनाहेतुवाक् निकृतिवाक्कें बुदक्कुं। तपोज्ञानाधिकरोळविनयहेतुवाक्कप्रणतिवागें बुदु अक्कुं। स्तेयहेतुवचनं मोषवागें बुदक्कुं। सन्मार्गोपदेशवाक् सम्यग्दर्शनवागें बुदक्कुं। मिथ्यामार्गोपदेशवाक् मिथ्यादर्शनवागें बुदक्कुमितु द्वादशभाषेगळें बुदक्कुं।

द्वींद्रियादिपंचेंद्रियपर्य्यंतमाद जीवंगळु व्यक्तवक्तृत्वपर्य्यायमनुळ्ळ वक्तृगळप्पुवु। द्रव्य-क्षेत्रकालभावाश्रितमप्प बहुविधमसत्यवचनं मृषाभिधानमक्कुं। जनपदसत्यादिदशप्रकारमप्प सत्यं मुंपेळल्पट्टु व्रतमुमुळ्ळदक्कुमी सत्यप्रवादपूर्वदोळु द्विकदशगुणितसंख्याशतपदंगळु षडुत्तरकोटियक्कु-

---

वक्तृभेदान् बहुविधं मृषाभिधानं दशविधं सत्यं च प्ररूपयति। तद्यथा-असत्यनिवृत्तिर्मौनं वा वाग्गुप्तिः। उरःकण्ठशिरोजिह्वामूलदन्तनासिकाताल्वोष्ठाख्यानि अष्टौ स्थानानि। स्पृष्टतेषत्स्पृष्टताविवृततेषद्विवृततासंवृता-रूपाः पञ्च प्रयत्नाश्च वाक्संस्कारकारणानि। शिष्टदुष्टरूपः प्रयोगः वाक्प्रयोगः तल्लक्षणशास्त्रं संस्कृतादि-व्याकरणं वा। इदमनेन कृतमित्यनिष्टवचनरूपमभ्याख्यानं। परस्परविरोधकारणं कलहवचनं। परदोषसूचन-पैशुन्यवचनं। धर्मार्थकाममोक्षासंबद्धवचनरूपः अबद्धप्रलापः। इन्द्रियविषयेषु रत्युत्पादिका वाक् रतिवाक्। तेषु अरत्युत्पादिका वाक् अरतिवाक्। परिग्रहार्जनरक्षणाद्यासक्तिहेतुर्वाक् उपधिवाक्। व्यवहारवञ्चनाहेतुर्वाक् निकृतिवाक्। तपोज्ञानादिषु अविनयहेतुर्वाक् अप्रणतिवाक्। स्तेयहेतुर्वाक् मोषवाक्। सन्मार्गोपदेशवाक् सम्यग्दर्शनवाक्। मिथ्यामार्गोपदेशवाक् मिथ्यादर्शनवाक्। एवं द्वादशभाषाः। द्वीन्द्रियादिपञ्चेन्द्रियपर्यन्ता जीवा व्यक्ताव्यक्तवक्तृत्वपर्यायाः वक्तारः। द्रव्यक्षेत्रकालभावाश्रितं बहुविधमसत्यवचनं मृषावाक्। जनपदसत्यादि-

---

दस प्रकारके सत्यका कथन करता है। इन सबका स्वरूप इस प्रकार है—असत्यसे निवृत्ति या मौनको वचन गुप्ति कहते हैं। उर, कण्ठ, शिर, जिह्वा मूल, दाँत, नाक, तालु, ओठ ये आठ स्थान हैं। स्पृष्टता, किंचित् स्पृष्टता, विवृतता, किंचित् विवृतता, संवृतता ये पाँच प्रयत्न हैं। ये सब स्थान और प्रयत्न वचन संस्कारके कारण हैं। शिष्टरूप और दुष्टरूप वचनप्रयोग होता है। 'यह इसने किया है' ऐसा अनिष्ट वचन अभ्याख्यान है। परस्परमें विरोधका कारण वचन कलह वचन है। दूसरेके दोषको सूचन करना पैशून्य वचन है। धर्म, अर्थ, काम और मोक्ष-से असम्बद्ध वचन असम्बद्ध प्रलाप है। जो वचन इन्द्रियोंके विषयोंमें रति उत्पन्न करे वह रतिवाक् है। जो उनमें अरति उत्पन्न करे वह अरतिवाक् है। परिग्रहके अर्जन और संरक्षण-में आसक्ति उत्पन्न करनेवाले वचन उपधिवाक् है। व्यवहारमें छल-कपट करनेमें हेतु वचन निकृतिवाक् है। तपस्वी और ज्ञानी जनोंके प्रति अविनयमें हेतु वचन अप्रणतिवाक् है। चोरी करनेमें हेतु वचन मोषवाक् है। सन्मार्गका उपदेश करनेवाले वचन सम्यक्दर्शनवाक् हैं। मिथ्या मार्गका उपदेश करनेवाले वचन मिथ्यादर्शनवाक् है। इस प्रकार बारह प्रकार-की भाषा है। दोइन्द्रियसे लेकर पंचेन्द्रिय पर्यन्त जीव, जिनमें वक्तृत्व पर्याय व्यक्त और अव्यक्त हैं वे वक्ता हैं। द्रव्य-क्षेत्र-काल और भावकी अपेक्षा अनेक प्रकारका असत्य वचन

स्वयंभूः। व्यवहारेणौदारिकादिशरीरमस्यास्तीति शरीरी निश्चयेनाशरीरः। व्यवहारेण मानवादि-पर्यायपरिणतो मानवः। उपचारात्। [illegible] निश्चयेन मनौ ज्ञाने भवो मानवः। व्यवहारेण स्वजनमित्रादिवर्गेषु सजतीति सक्ता। निश्चयेनासक्ता। व्यवहारेण चतुर्गतिसंसारे मातापित्रादिषु जायत इति जंतुः। संसारीत्यर्थः। निश्चयेनाजंतुः। व्यवहारेण [illegible] मानी निश्चयेनामानी। व्यवहारेण माया वंचनाऽस्यास्तीति मायी निश्चयेनामायी। व्यवहारेण योगः कायवाङ्मनःकर्माऽस्यास्तीति योगी। निश्चयेनायोगी। व्यवहारेण सूक्ष्मनिगोद[illegible]-[illegible]शरीरमात्रेण संकुचति संकुचितप्रदेशो भवतीति संकुटः। समुद्घाते सर्वलोकं व्याप्नो-तीत्यसंकुटः। निश्चयेन प्रदेशसंहारविसर्पाभावादसंकुटः [illegible]। व्यवहारेण क्षेत्रं लोकालोकं स्वरूपं च जानातीति क्षेत्रज्ञः। व्यवहारेणाष्ट[illegible]-त्वात्। निश्चयेन चैतन्यमात्र[illegible]। इति [illegible]

[illegible] इति [illegible]। व्यवहारेण [illegible] शरीरी निश्चयेनाशरीरः। व्यवहारेण मानवादिपर्यायपरिणतो मानवः, [illegible]। निश्चयेन मनौ ज्ञाने भव मानवः। व्यवहारेण स्वजनमित्रादिवर्गेषु [illegible]। निश्चयेनासक्ता। व्यवहारेण चतुर्गतिसंसारे मातापित्रादिषु जायत इति जंतुः [illegible]। निश्चयेनाजंतुः। व्यवहारेण [illegible] मानी, निश्चयेनामानी। व्यवहारेण माया वंचनाऽस्यास्तीति मायी निश्चयेनामायी। व्यवहारेण योगः कायवाङ्मनःकर्माऽस्यास्तीति योगी, निश्चयेनायोगी। व्यवहारेण [illegible] शरीरमात्रेण संकुचति संकुचितप्रदेशो भवतीति संकुटः, समुद्घाते सर्वलोकं [illegible]। निश्चयेन प्रदेशसंहारविसर्पाभावादसंकुटः [illegible]। व्यवहारेण क्षेत्रं [illegible] जानातीति क्षेत्रज्ञः। व्यवहारेण [illegible], निश्चयेन [illegible]। [illegible]।

पाके बिना स्वयं सब पदार्थोंको जानता है अतः वेत्ता या वेद है। व्यवहार नयसे अपने गृहीत शरीरको और समुद्घात दशामें सर्व लोकको व्यापता है, निश्चयनयसे ज्ञानके द्वारा सबको 'वेवेष्टि' अर्थात् व्यापता है जानता है अतः विष्णु है। व्यवहारनयसे चतुर्गति भव-भवमें परिणमन करता है तथापि निश्चयनयसे 'स्वयं' अपनेमें ही अपने चैतन्य स्वभावसे 'भवति' अर्थात् परिणमन करता है अतः स्वयंभू है। व्यवहारनयसे औदारिक शरीरवाला होनेसे शरीरी है और निश्चयसे अशरीरी है। व्यवहारसे मानव आदि पर्यायरूप

भौमाङ्गस्वरस्वप्नलक्षणव्यञ्जनच्छिन्नाख्याष्टाङ्गमहानिमित्तानि च वर्णयति विद्यानुवादं नाम दशमं पूर्वं एककोटिदशलक्षपदपुञ्जं पूर्वम्। ११० ल। ११००००००। कल्याणानां वादः प्रवादोऽस्मिन्निति कल्याणवादनामधेयमेकादशं पूर्वम्। तीर्थंकरचक्रधरबलदेववासुदेवप्रतिवासुदेवादीनां गर्भावतरणादिकल्याणमहोत्सवं तत्कारणतीर्थंकरत्वादिपुण्यविशेषहेतुषोडशभावना तपोविशेषाद्यनुष्ठानानि चन्द्रसूर्यग्रहनक्षत्रचारग्रहणशकुनादिफलादिकं च वर्णयति तच्च षड्विंशतिकोटिपदपुञ्जं पूर्वम्। २६ को २६०००००००। प्राणानामावादः प्ररूपणमस्मिन्निति प्राणावादं द्वादशं पूर्वं तत्। कायचिकित्साद्यष्टाङ्गमायुर्वेदं भूतिकर्मजाङ्गुलिप्रक्रमं ईडापिङ्गलादि बहुप्रकारप्राणापानविभागं दशप्राणानामुपकारकापकारकद्रव्याणि गत्याद्यनुसारेण वर्णयति तच्च त्रयोदशकोटिपदपुञ्जं पूर्वम्। १३ को १३०००००००।

क्रियाभिर्नृत्यादिभिर्विशालं विस्तीर्णं शोभमानं वा क्रियाविशालं त्रयोदशं पूर्वम्। संगीतशास्त्रच्छन्दोऽलंकारादिद्वासप्ततिकलाः स्त्रैणचतुःषष्टिगुणान् शिल्पादिविज्ञानानि चतुरशीतिगर्भाधानादिक्रियाः अष्टोत्तरशतं सम्यग्दर्शनादिक्रियाः पञ्चविंशतिं देववन्दना-

[illegible] सिद्धविद्यानां फलविशेषं [illegible] (अन्तरिक्ष [illegible]) [illegible]
[illegible] च वर्णयति। तच्च [illegible]
११० ल। [illegible] पूर्वं, [illegible]
[illegible]
[illegible] च वर्णयति। तच्च [illegible]
[illegible] ११ को। [illegible]
[illegible]
[illegible] वर्णयति। तच्च [illegible]
[illegible] १३ को। [illegible]
पूर्वम्। [illegible]

रोहिणी आदि पाँच सौ महाविद्याओंका स्वरूप, सामर्थ्य, साधन, मन्त्र-तन्त्र-पूजा विधान, सिद्ध विद्याओंका फल विशेष तथा आकाश, भौम, अंग, स्वर, स्वप्न, लक्षण, व्यंजन, छिन्न नामक आठ महानिमित्तोंका वर्णन करता है। इसमें दो लाखसे गुणित पचपन अर्थात् एक करोड़ दस लाख पद हैं। कल्याणोंका वाद अर्थात् कथन जिसमें है वह कल्याणवाद नामक ग्यारहवाँ पूर्व है। वह तीर्थंकर, चक्रवर्ती, बलदेव, वासुदेव, प्रतिवासुदेव आदिके गर्भके अवतरण कल्याण आदि महोत्सवोंका, उनके कारण तीर्थंकरत्व आदि पुण्य विशेषके हेतु सोलह भावना, तपोविशेष आदिके अनुष्ठान, चन्द्रमा-सूर्य-ग्रह-नक्षत्रोंका गमन, ग्रहण, शकुन आदिके फल आदिका वर्णन करता है। इसमें दो लाखसे गुणित तेरह सौ अर्थात् छब्बीस करोड़ पद हैं। प्राणोंका आवाद—कथन जिसमें है वह प्राणावाद नामक बारहवाँ पूर्व है। वह कायचिकित्सा आदि अष्टांग आयुर्वेद, भूतकर्म, जांगुलि प्रक्रम, ईडा, पिंगला, सुषुम्ना आदि अनेक प्रकारके प्राण-अपानके विभागका तथा दस प्राणोंके उपकारक-अपकारक द्रव्योंका गति आदिके अनुसार वर्णन करता है। इसमें दो लाखसे गुणित छह सौ पचास अर्थात् तेरह करोड़ पद हैं। नृत्य आदि क्रियाओंसे विशाल अर्थात् विस्तीर्ण या शोभमान क्रियाविशाल नामक तेरहवाँ पूर्व है। वह संगीत शास्त्र, छन्द, अलंकार आदि बहत्तर कला, स्त्रियोंके चौसठ गुण, शिल्प आदि विज्ञान, चौरासी गर्भाधान आदि क्रिया,

समायः अथवा सम् समे रागद्वेषाभ्यामनुपहते मध्यस्थे आत्मनि आय उपयोगस्य प्रवृत्तिः समायः स प्रयोजनमस्येति सामायिकं नित्यनैमित्तिकानुष्ठानमुं तत्प्रतिपादकं शास्त्रमुं सामायिकमेंबुदत्थं। रागद्वेष नामस्थापनाद्रव्यक्षेत्रकालभावभेदर्दिदं सामायिकं षड्विधमक्कुमल्लि इष्टानिष्टनामंगळोळ् रागद्वेषनिवृत्तियुं सामायिकाभिधानमुं मेणु नामसामायिकमक्कुं। मनोज्ञामनोज्ञस्त्रीपुरुषाद्याकारकाष्ठलेप्यचित्रादिप्रतिमेगळोळु रागद्वेषनिवृत्तियुं यिदु सामायिकमेंदितु स्थाप्यमानासद्भावस्थापनेयुमप्पक्षतादिपुंज मेणु स्थापनासामायिकमक्कुं। इष्टानिष्टंगळप्प चेतनाचेतनद्रव्यंगळोळ् रागद्वेषनिवृत्तियुं सामायिकशास्त्रानुपयुक्तज्ञायकतच्छरीरादि मेणु द्रव्यसामायिकमक्कुं। ग्रामनगरवनादिक्षेत्रंगळिष्टानिष्टंगळोळु रागद्वेषनिवृत्तिक्षेत्रसामायिकमक्कुं। वसंतादि ऋतुगळोळं शुक्लपक्षकृष्णपक्षंगळोळं दिवसवारनक्षत्रादिगळप्पिष्टानिष्टकालविशेषंगळोळं रागद्वेषनिवृत्तिकालसामायिकमक्कुं। जीवादितत्त्वविषयोपयोगरूपपर्य्यायक्के मिथ्यादर्शनकषायादिसंक्लेशनिवृत्तियुं सामायिकशास्त्रोपयोगयुक्तज्ञायकनुं तत्पर्य्यायपरिणतमप्प सामायिकं मेणु भावसामायिकमक्कुं। पंचमहाकल्याणस्थानसंबंधिगळप्प चतुर्व्विंशतितीर्थंकररुगळ नामस्थापनाद्रव्यभावंगळनाश्रयिसि

अयमहं ज्ञाता द्रष्टा चेति आत्मविषयोपयोग इत्यर्थः, आत्मनः एकस्यैव ज्ञेयज्ञायकत्वसंभवात्। अथवा सं समे रागद्वेषाभ्यामनुपहते मध्यस्थे आत्मनि आयः उपयोगस्य प्रवृत्तिः समायः स प्रयोजनमस्येति सामायिकं नित्यनैमित्तिकानुष्ठानं तत्प्रतिपादकं शास्त्रं वा सामायिकमित्यर्थः। तच्च नामस्थापनाद्रव्यक्षेत्रकालभावभेदात् षड्विधम्। तत्र इष्टानिष्टनामसु रागद्वेषनिवृत्तिः सामायिकमित्यभिधानं वा नाम सामायिकम्। मनोज्ञामनोज्ञासु स्त्रीपुरुषाद्याकारासु काष्ठलेप्यचित्रादिप्रतिमासु रागद्वेषनिवृत्तिः। इदं सामायिकमिति स्थाप्यमानं यत् किञ्चिद्वस्तु वा स्थापनासामायिकम्। इष्टानिष्टेषु चेतनाचेतनद्रव्येषु रागद्वेषनिवृत्तिः सामायिकशास्त्रानुपयुक्तज्ञायकः तच्छरीरादिर्वा द्रव्यसामायिकम्। ग्रामनगरवनादिक्षेत्रेषु इष्टानिष्टेषु रागद्वेषनिवृत्तिः क्षेत्रसामायिकम्। वसन्तादिऋतुषु शुक्लकृष्णपक्षयोर्दिनवारनक्षत्रादिषु च इष्टानिष्टेषु कालविशेषेषु रागद्वेषनिवृत्तिः कालसामायिकम्। भावस्य जीवादितत्त्वविषयोपयोगरूपस्य पर्यायस्य मिथ्यादर्शनकषायादिसंक्लेशनिवृत्तिः सामायिकशास्त्रोपयोगयुक्तज्ञायकः तत्पर्यायपरिणतसामायिकं वा भावसामायिकम्। तत्तत्कालसम्बन्धिनां चतुर्विंशतितीर्थंकराणां

'आय' अर्थात् आगमनको समाय कहते हैं। अर्थात् परद्रव्योंसे निवृत्त होकर आत्मामें प्रवृत्तिका नाम समाय है, यह मैं ज्ञाता-द्रष्टा हूँ इस प्रकारका आत्मविषयमें उपयोग समाय है. क्योंकि आत्मा ही ज्ञेय और वही ज्ञायक होता है। अथवा 'सं' यानी सम—राग-द्वेषसे अबाधित मध्यस्थ आत्मामें 'आय' अर्थात् उपयोगकी प्रवृत्ति समाय है। वह प्रयोजन जिसका है वह सामायिक है। नित्य-नैमित्तिक अनुष्ठान और उनका प्रतिपादक शास्त्र सामायिक है यह इसका अर्थ है। वह सामायिक नाम, स्थापना, द्रव्य, क्षेत्र, काल और भावके भेदसे छह प्रकारकी है। इष्ट-अनिष्ट नामोंमें राग-द्वेषकी निवृत्ति अथवा सामायिक नाम नामसामायिक है। मनोज्ञ और अमनोज्ञ स्त्री-पुरुष आदिके आकारोंमें काष्ठ, लेप्य और चित्र आदिमें अंकित प्रतिमाओंमें राग-द्वेष न करना, अथवा जिस-किसी वस्तुमें 'यह सामायिक है' इस प्रकार स्थापना करना स्थापनासामायिक है। इष्ट-अनिष्ट, चेतन-अचेतन द्रव्योंमें राग-द्वेषकी निवृत्ति अथवा सामायिक शास्त्रका ज्ञाता जो उसमें उपयोगवान् नहीं है, अथवा उसका शरीर आदि द्रव्यसामायिक है। इष्ट-अनिष्ट, ग्राम-नगर आदि क्षेत्रोंमें राग-द्वेष करना क्षेत्रसामायिक है। वसन्त आदि ऋतु, शुक्ल-कृष्ण पक्ष, दिन, वार, नक्षत्रादि इ अनिष्ट काल विशेषोंमें राग-द्वेष न करना कालसामायिक है। भाव अर्थात् जीवादि त विषयक उपयोगरूप पर्यायकी मिथ्यादर्शन कषाय आदि संक्लेशोंसे निवृत्ति, अथवा सा

शास्त्रं मुनिजनंगळाचरण गोचारविधियं पिंडशुद्धिलक्षणमं वर्णिसुगु। उत्तराण्यधीयंते पठ्यन्तेऽस्मिन्नित्युत्तराध्ययनं। ई उत्तराध्ययनशास्त्रं चतुर्व्विधोपसर्गंगळ द्वाविंशतिपरीषहंगळ सहनविधानमं तत्फलमुमं यितु प्रश्नमादोडितुत्तरमें दितुत्तरविधानमं वर्णिसुगुं। कल्प्यं योग्यं व्यवह्रियते अनुष्ठीयतेऽस्मिन्निति अनेनेति वा कल्प्यव्यवहारः। ई कल्प्यव्यवहारशास्त्रं साधुगळ योग्यानुष्ठानविधानमं अयोग्यसेवेयोळु प्रायश्चित्तमुमं वर्णिसुगुं। कल्प्यं चाकल्प्यं च कल्प्याकल्प्यं तद्वर्ण्यतेऽस्मिन्निति कल्प्याकल्प्यं। ई कल्प्याकल्प्यशास्त्रं द्रव्यक्षेत्रकाल भावंगळनाश्रयिसि मुनिगळिगिदु कल्प्यमिदकल्प्यमें दु योग्यायोग्यविभागमं वर्णिसुगुं।

महतां कल्प्यमस्मिन्निति महाकल्प्यं। ई महाकल्प्यशास्त्रं जिनकल्पसाधुगळ्गे उत्कृष्टसंहननादिविशिष्टद्रव्यक्षेत्रकालभाववर्त्तिगळ्गे योग्यमप्प त्रिकालयोगाद्यनुष्ठानमं स्थविरकल्परुगळ दीक्षाशिक्षागणपोषणात्मसंस्कार सल्लेखनोत्तमार्थस्थानगतोत्कृष्टाराधनाविशेषमुमं वर्णिसुगुं। पुंडरीकमें ब शास्त्रं भावनव्यंतरज्योतिष्ककल्पवासिविमानंगळोळुत्पत्तिकारणदानपूजातपश्चरणाकामनिर्ज्जं-

दश वैकालिकानि वर्ण्यन्तेऽस्मिन्निति दशवैकालिकं तच्च मुनिजनानां आचरणगोचरविधिं पिण्डशुद्धिलक्षणं च वर्णयति। उत्तराणि अधीयन्ते पठ्यन्ते अस्मिन्निति उत्तराध्ययनं तच्च चतुर्विधोपसर्गाणां द्वाविंशतिपरीषहाणां च सहनविधानं तत्फलं एवं प्रश्ने एवमुत्तरमित्युत्तरविधानं च वर्णयति। कल्प्यं योग्यं व्यवह्रियते अनुष्ठीयतेऽस्मिन्ननेनेति वा कल्प्यव्यवहारः, स च साधूनां योग्यानुष्ठानविधानं अयोग्यसेवायां प्रायश्चित्तं च वर्णयति। कल्प्यं चाकल्प्यं च कल्प्याकल्प्यं, तद्वर्ण्यते अस्मिन्निति कल्प्याकल्प्यम्। तच्च द्रव्यक्षेत्रकालभावानाश्रित्य मुनीनामिदं कल्प्यं योग्यं इदमकल्प्यं अयोग्यमिति विभागं वर्णयति। महतां कल्प्यमस्मिन्निति महाकल्प्यं शास्त्रं तच्च जिनकल्पसाधूनां उत्कृष्टसंहननादिविशिष्टद्रव्यक्षेत्रकालभाववर्तिनां योग्यं त्रिकालयोगाद्यनुष्ठानं स्थविरकल्पानां दीक्षाशिक्षागणपोषणात्मसंस्कारसल्लेखनोत्तमार्थस्थानगतोत्कृष्टाराधनाविशेषं च वर्णयति। पुण्डरीकं नाम शास्त्रं भावनव्यन्तरज्योतिष्ककल्पवासिविमानेषु उत्पत्तिकारणदानपूजातपश्चरणाकामनिर्जरासम्यक्त्वसंयमादिविधानं तत्तदुपपादस्थानवैभवविशेषं च वर्णयति। महच्च तत्पुण्डरीकं तत्महापुण्डरीकं शास्त्रं

चार सिर नमाना, बारह आवर्त आदि रूप नित्य नैमित्तिक क्रिया विधानका वर्णन होता है। विशिष्ट कालोंको विकाल कहते हैं, उनमें होनेको वैकालिक कहते हैं। जिसमें दस वैकालिकोंका वर्णन हो वह दशवैकालिक है। उसमें मुनियोंका आचार, गोचरीकी विधि और भोजन शुद्धिका लक्षण कहा गया है। जिसमें उत्तरोंका अध्ययन हो वह उत्तराध्ययन है। उसमें चार प्रकारके उपसर्गों और बाईस परीषहोंके सहनेका विधान, उनका फल तथा इस प्रकारके प्रश्नका उत्तर इस प्रकार होता है इसका कथन होता है। जो कल्प्य अर्थात् योग्यके व्यवहारका कथन करता है वह कल्प्यव्यवहार है। उसमें साधुओंके योग्य अनुष्ठानके विधानका और अयोग्यका सेवन होनेके प्रायश्चित्तका कथन होता है। जिसमें कल्प्य और अकल्प्यका कथन हो वह कल्प्याकल्प्य है। वह द्रव्य, क्षेत्र, काल और भावके आश्रयसे यह मुनियोंके योग्य और यह अयोग्य है ऐसा कथन करता है। महान् पुरुषोंका कल्प्य जिसमें हो वह महाकल्प्य शास्त्र है। उसमें जिनकल्पी साधुओंके उत्कृष्ट, संहनन आदि विशिष्ट द्रव्य, क्षेत्र, काल, भावको लेकर त्रिकाल योग आदि अनुष्ठानका तथा स्थविर कल्पी साधुओंकी दीक्षा, शिक्षा, गणका पोषण, आत्मसंस्कार, सल्लेखना, उत्तम स्थानगत उत्कृष्ट आराधना विशेषका कथन होता है। पुण्डरीक नामक शास्त्र भवनवासी, व्यन्तर, ज्योतिषी और कल्पवासी देवोंके विमानोंमें उत्पत्तिके कारण दान, पूजा, तपश्चरण, अकामनिर्जरा, सम्यक्त्व, संयम आदिका विधान तथा उस-उस उपपाद स्थानके वैभव विशेषको कहता है। महान्

त्पन्नं केवलज्ञानं प्रत्यक्षं । समस्तत्वदिंदं विशदं स्पष्टमक्कुं । मूर्त्तामूर्त्तार्थव्यंजनपर्य्यायस्थूलसूक्ष्मांशंगळप्प सर्व्वंगळोळ् प्रवृत्ति संभविसुगुमप्पुदरिदं । साक्षात्करणदिदमुं अक्षमात्मानमेव प्रतिनियतं परानपेक्षं प्रत्यक्षं । उपात्तानुपात्तपरप्रत्ययापेक्षं परोक्षमिति । एंदितु प्रत्यक्षपरोक्षशब्दनिरुक्तिसिद्धलक्षणभेदर्दिदमा श्रुतज्ञानकेवलज्ञानंगळ्गे सादृश्याभावमक्कुमंते समंतभद्रस्वामिगळिंदमुं पेळल्पट्टुदु । "स्याद्वाद केवलज्ञाने सर्व्वतत्त्वप्रकाशने । भेदः साक्षादसाक्षाच्च ह्यवस्त्वन्यतमं भवे" दें दितु । [आप्तमी.]

अनंतरं शास्त्रकारं पंचषष्ठिगाथासूत्रंगळिंदमवधिज्ञानप्ररूपणेयं पेळलुपक्रमिसिदपं ।

अवहीयदित्ति ओही सीमाणाणेत्ति वण्णियं समये ।
भवगुणपच्चयविहियं जमोहिणाणेत्ति णं बेंति ॥३७०॥

अवधीयत इत्यवधिः सीमाज्ञानमिति वर्णितं समये । भवगुणप्रत्ययविहितं यदवधिज्ञानमितीदं ब्रुवंति ।

अवधीयते द्रव्यक्षेत्रकालभावंगळिंदं परिमीयते एंदिनिसल्पट्टुदु मेंदितवधि येंबुदक्कें डोडे मतिश्रुतकेवलंगळंते द्रव्यादिगळिंदमपरिमितविषयत्वाऽभावमप्पुदरिदं सीमाविषयज्ञानमें दु समये परमागमदोळ् भणितं पेळल्पट्टुदु । यत् आवुदों दु तृतीयज्ञानं भवगुणप्रत्ययविहितं भवो नरकादिपर्य्यायः गुणः सम्यग्दर्शनविशुद्धयादिः । भवश्च गुणश्च भवगुणौ तावेव प्रत्ययौ ताभ्यां कारणाभ्यां

स्वविषयेषु अवधिज्ञानादिव साक्षात्करणाभावाच्च । सकलावरणवीर्यान्तरायनिरवशेषक्षयोत्पन्नं केवलज्ञानं प्रत्यक्षं समस्तत्वेन विशदं स्पष्टं भवति । मूर्तामूर्तार्थव्यञ्जनपर्यायस्थूलसूक्ष्मांशेषु सर्वेष्वपि प्रवृत्तिसंभवात् साक्षात्करणाच्च । अक्षं आत्मानमेव प्रतिनियतं परानपेक्षं प्रत्यक्षं, उपात्तानुपात्तपरप्रत्ययापेक्षं परोक्षमिति निरुक्तिसिद्धलक्षणभेदात्तयोः श्रुतज्ञानकेवलज्ञानयोः सादृश्याभावात् । तथा चोक्तं समन्तभद्रस्वामिभिः—

स्याद्वादकेवलज्ञाने सर्वतत्त्वप्रकाशने । भेदः साक्षादसाक्षाच्च ह्यवस्त्वन्यतमं भवेत् ॥— [आप्तमी०]
॥३६९॥ अथ शास्त्रकारः पञ्चषष्टिगाथासूत्रैः अवधिज्ञानप्ररूपणामुपक्रमते—

अवधीयते—द्रव्यक्षेत्रकालभावैः परिमीयते इत्यवधिर्मतिश्रुतकेवलवद्द्रव्यादिभिरपरिमितविषयत्वाभावात् । यत्तृतीयं सीमाविषयं ज्ञानं समये परमागमे वर्णितं तदिदमवधिज्ञानमित्यर्हदादयो ब्रुवन्ति । तत्कृति-

---

स्थूल अंशको अवधिज्ञानकी तरह साक्षात्कार करनेमें असमर्थ है । किन्तु समस्त ज्ञानावरण और वीर्यान्तरायके क्षयसे उत्पन्न केवलज्ञान पूर्ण रूपसे स्पष्ट होता है । मूर्त अमूर्त, अर्थपर्याय, व्यंजनपर्याय, स्थूल अंश, सूक्ष्म अंश सभीमें उसकी प्रवृत्ति है और सभीको साक्षात् जानता है । अक्ष अर्थात् आत्मासे ही जो ज्ञान होता है, परकी अपेक्षा नहीं करता उसे प्रत्यक्ष कहते हैं । उपात्त इन्द्रियादि और अनुपात्त प्रकाशादि परकारणोंकी अपेक्षासे होनेवाला ज्ञान परोक्ष है । इस प्रकार निरुक्तिसे सिद्ध लक्षणोंके भेदसे श्रुतज्ञान और केवलज्ञानमें समानता नहीं है । स्वामी समन्तभद्रने भी अपने आप्तमीमांसामें कहा है—

स्याद्वाद अर्थात् श्रुतज्ञान और केवलज्ञान दोनों ही सर्व तत्त्वोंके प्रकाशक हैं किन्तु भेद यही है कि केवलज्ञान साक्षात् प्रत्यक्ष जानता है और श्रुतज्ञान परोक्ष जानता है । जो इन दोनों ज्ञानोंमें-से एकका भी विषय नहीं है वह अवस्तु है ॥३६९॥

अब शास्त्रकार पैंसठ गाथाओंसे अवधिज्ञानका कथन करते हैं—

'अवधीयते' अर्थात् द्रव्य, क्षेत्र, काल, भावके द्वारा जिसका परिमाण किया जाता है वह अवधि है । अर्थात् जैसे मति, श्रुत और केवलज्ञानका विषय द्रव्यादिकी अपेक्षा

गुणपच्चइगो छद्धा अणुगावट्ठिदपवड्ढमाणिदरा ।
देसोही परमोही सव्वोहित्ति य तिधा ओही ॥३७२॥

गुणप्रत्ययकः षोढा अनुगावस्थितप्रवर्द्धमानेतरे । देशावधिः परमावधिः सर्व्वावधिरिति च त्रिधावधिः ॥

आवुदोंदु गुणप्रत्ययावधिज्ञानमदु अनुगमनुगामियेंदुमवस्थितमेंदु प्रवर्द्धमानमेंदुं मूरुतेरनप्पुवु । इतरंगळु अननुगमननुगामियेंदुमनवस्थितमेंदुं हीयमानमुमेंदितिवु मूरुतेरनप्पुवंतु कूडि अनुगामि अननुगामि अवस्थितमनवस्थित वर्द्धमानहीयमानमेंदितु षड्विधमक्कुमल्लि आवुदोंदवधिज्ञानं तन्न स्वामियप्प जीवनं बळिसल्गुमदनुगामियेंबुदक्कुमदुवुं क्षेत्रानुगामियेंदुं भवानुगामियेंदुं उभयानुगामियेंदितु त्रिविधमक्कुमल्लि आवुदोंदु तां पुट्टिद क्षेत्रदिदमन्यक्षेत्रदोळु विहारिसुव जीवनं बळिसल्गुं । भवांतरदोळु बळिसल्लददु क्षेत्रानुगामियं बुदक्कुमावुदोंदु तां पुट्टिद भवदिदमन्यभवदोळं स्वस्वामियं बळिसल्गुमदु भवानुगामियें बुदक्कुमावुदोंदु तां पुट्टिद क्षेत्रभवंगळेरडरत्तणिंदमन्य भरतैरावतविदेहादिक्षेत्रदोळं देवमनुष्यादिभवंगळोळं वर्त्तमानजीवमं बळिसल्गुमदुभयानुगामियें बुदक्कुमावुदोंदु तन्न स्वामियप्प जीवनं बळिसल्वुदल्लददननुगामियें बुदक्कुमदुवुं क्षेत्राऽननुगामियेंदुं भवाननुगामियेंदुमुभयाननुगामियेंदुं त्रिविधमक्कुं । मल्लि आवुदोंदु क्षेत्रांतरमं बळिसल्वुदल्लदु तां पुट्टिद क्षेत्रदोळे किडुगुं । भवांतरं बळिसलगे मेण्माणगे अदु क्षेत्रा-

---

यद्गुणप्रत्ययावधिज्ञानं तदनुगाम्यननुगाम्यवस्थितमनवस्थितं प्रवर्धमानं हीयमानं चेति षड्विधम् । तत्र यदवधिज्ञानं स्वस्वामिनं जीवमनुगच्छति तदनुगामि । तच्च क्षेत्रानुगामि भवानुगामि उभयानुगामीति त्रिविधम् । यत् स्वोत्पत्तिक्षेत्रात् अन्यक्षेत्रे विहरन्तं जीवमनुगच्छति भवान्तरं नानुगच्छति तत्क्षेत्रानुगामि भवति । यत् उत्पत्तिभवादन्यभवे स्वस्वामिनं अनुगच्छति तद्भवानुगामि भवति । यत्स्वोत्पत्तिक्षेत्रभवाभ्यां अन्यत्र भरतैरावतविदेहादिक्षेत्रे देवमनुष्यादिभवे च वर्तमानं जीवमनुगच्छति तदुभयानुगामि भवति । यदवधिज्ञानं स्वस्वामिनं जीवं नानुगच्छति तदननुगामि । तदपि क्षेत्राननुगामि भवाननुगामि उभयाननुगामीति त्रिविधम् । तत्र यत्क्षेत्रान्तरं न गच्छति स्वोत्पत्तिक्षेत्रे एव विनश्यति भवान्तरं गच्छतु वा मा गच्छतु तत् क्षेत्राननुगामि । यद्भवान्तरं नानुगच्छति स्वोत्पत्तिभव एव विनश्यति, क्षेत्रान्तरं गच्छतु वा मा वा गच्छतु

नहीं होती, केवल सम्यग्दर्शनादि गुणोंके कारण ही अवधिज्ञान प्रकट होता है इसलिए यह गुणप्रत्यय कहा जाता है ॥३७१॥

गुणप्रत्यय अवधिज्ञान, अनुगामी, अननुगामी, अवस्थित, अनवस्थित, वर्धमान, हीयमानके भेदसे छह प्रकारका है। उनमें-से जो अवधिज्ञान अपने स्वामी जीवका अनुगमन करता है वह अनुगामी है। वह तीन प्रकारका है—क्षेत्रानुगामी, भवानुगामी और उभयानुगामी। जो अवधिज्ञान अपने उत्पत्तिक्षेत्रसे अन्य क्षेत्रमें जानेवाले जीवके साथ जाता है, किन्तु भवान्तरमें साथ नहीं जाता वह क्षेत्रानुगामी है। जो उत्पत्तिक्षेत्रसे स्वामीका मरण होनेपर दूसरे भवमें भी साथ जाता है वह भवानुगामी है। जो अपने उत्पत्तिक्षेत्र और भवसे अन्यत्र भरत, ऐरावत, विदेह आदि क्षेत्रमें और देव, मनुष्य आदिके भवमें जीवका अनुगमन करता है वह उभयानुगामी है। जो अवधिज्ञान अपने स्वामी जीवका अनुगमन नहीं करता वह अननुगामी है। वह भी क्षेत्राननुगामी, भवाननुगामी, उभयाननुगामीके भेदसे तीन प्रकारका है। जो अवधि अन्य क्षेत्रमें नहीं जाता अपने उत्पत्तिक्षेत्रमें ही नष्ट हो जाता है,

गुणे दर्शनविशुद्धयादिलक्षणगुणमुंटागुत्तिरलेयक्कुं। मितु गुणप्रत्ययंगळ्मूरुमवधिगळुं संभविसुववुं। भवप्रत्ययं देशावधियेयें दितु निश्चितमाय्तु।

देसोहिस्स य अवरं णरतिरिये होदि संजदम्मि वरं।
परमोही सव्वोही चरमसरीरस्स विरदस्स ॥३७४॥

देशावधिरवरं नरतिर्य्यंक्षु भवति संयते वरं। परमावधिः सर्व्वावधिश्चरमशरीरस्य विरतस्य ॥

देशावधिज्ञानद जघन्यं नररोळं तिर्य्यंचरोळं संयतरोळमसंयतरोळमक्कुं। देवनारकरोळप्पुदु एकेंदोडे देशावधिय सर्व्वोत्कृष्टं नियमदिदं मनुष्यगतिय सकलसंयतरोळेयक्कु–। मितरगतित्रयदोळिल्लेकेंदोडे महाव्रताभावमप्पुदरिदं। परमावधिसर्व्वावधिगळेरडुं जघन्यदिदमुमुत्कृष्टदिंदमुं मनुष्यगतियोळे चरमांगरप्प महाव्रतिगळ्गेये संभविसुववु। चरमं संसारांतवर्त्तितद्भवमोक्षकारणरत्नत्रयाराधकजीवसंबंधिशरीरं वज्रऋषभनाराचसंहननयुक्तं यस्यासौ चरमशरीरः।

पडिवादी देसोही अप्पडिवादी हवंति सेसा ओ।
मिच्छत्तं अविरमणं ण य पडिवज्जंति चरिमदुगे ॥३७५॥

प्रतिपाती देशावधिरप्रतिपातिनौ भवतः शेषौ अहो। मिथ्यात्वमविरमणं न च प्रतिपद्यन्ते चरमद्विके ॥

सम्यक्त्वमुं चारित्रमुमें बी येरडरिदं पळिचे मिथ्यात्वाऽसंयमंगळ्प्राप्ति प्रतिपातमक्कुमदुळ्ळुदं प्रतिपातियक्कुमितप्प प्रतिपाति देशावधियेयक्कुं। शेष परमावधि सर्व्वावधिगळेरडुम-

संयमलक्षणगुणाभावे तयोरभावात्। देशावधिरपि गुणे दर्शनविशुद्धयादिलक्षणे सति भवति। एवं गुणप्रत्ययास्त्रयोऽप्यवधयः संभवन्ति। भवप्रत्ययस्तु देशावधिरेवेति निश्चितं जातम् ॥३७३॥

देशावधेर्ज्ञानस्य जघन्यं नरतिरश्चोरेव संयतासंयतयोः भवति, न देवनारकयोः। देशावधेः सर्वोत्कृष्टं तु नियमेन मनुष्यगतिसकलसंयते एव भवति नेतरगतित्रये तत्र महाव्रताभावात्। परमावधिसर्वावधी द्वावपि जघन्येनोत्कृष्टेन च मनुष्यगतावेव चरमाङ्गस्य महाव्रतिन एव संभवतः। चरमं संसारान्तर्वर्तितद्भवमोक्षकारणरत्नत्रयाराधकजीवसंबन्धि शरीरं वज्रऋषभनाराचसंहननयुतं यस्यासौ चरमशरीरः ॥३७४॥

सम्यक्त्वचारित्राभ्यां प्रच्युत्य मिथ्यात्वासंयमयोः प्राप्तिः प्रतिपातः, तद्युतः प्रतिपाती स तु देशावधिरेव

नियमसे गुणप्रत्यय ही होते हैं। क्योंकि संयमगुणके अभावमें ये दोनों नहीं होते। देशावधि भी दर्शनविशुद्धि आदि गुणोंके होनेपर होता है। इस प्रकार गुणप्रत्यय तो तीनों भी अवधि होते हैं। किन्तु भवप्रत्यय देशावधि ही है यह निश्चित हुआ ॥३७३॥

देशावधिज्ञानका जघन्य भेद संयमी या असंयमी मनुष्यों और तिर्यंचोंके ही होता है, देवों और नारकियोंके नहीं होता। किन्तु देशावधिका सर्वोत्कृष्ट भेद नियमसे सकलसंयमी मनुष्यके ही होता है, शेष तीन गतियोंमें नहीं होता, क्योंकि वहाँ महाव्रत नहीं होते। परमावधि सर्वावधि जघन्य भी और उत्कृष्ट भी मनुष्यगतिमें ही चरमशरीरी महाव्रतीके ही होते हैं। चरम अर्थात् संसारके अन्तमें होनेवाले उसी भवसे मोक्षके कारण रत्नत्रयकी आराधना करनेवाले जीवके होनेवाला वज्रऋषभनाराच संहननसे युक्त शरीर जिसका है उसीके होते हैं। वही चरमशरीरी है ॥३७४॥

सम्यक्त्व और चारित्रसे च्युत होकर मिथ्यात्व और असंयममें आनेको प्रतिपात कहते हैं। और जिसका प्रतिपात होता है वह प्रतिपाती है। देशावधि ही प्रतिपाती है।

देशावधिजघन्यज्ञानं द्रव्यतः द्रव्यदिदं मध्यमयोगार्जितमप्प नोकर्मौदारिकसंचयमं द्व्यर्द्ध-गुणहानिप्रमितसमयप्रबद्धसमूहरूपमं स्वयोग्यविस्रसोपचयपरमाणुसंयुक्तमं लोकदिदं भागिसल्पट्टुदं नियमदिदं तावन्मात्रमने जानाति प्रत्यक्षमागरिगुमदरिदं किरिदनरियल्बेकुदत्थं। जघन्ययोगार्जितमप्प नोकर्मौदारिकसंचयक्कल्पत्वमनरिवडक्कं सूक्ष्मत्वसंभर्वादिदं। तद्ग्रहणदोळ् तज्ज्ञानक्के शक्तिप्रभावमप्पुदरिदं। उत्कृष्टयोगार्जितनोकर्मौदारिकसंचयक्के स्थूलत्वमक्कुं तद्ग्रहणदोळ् प्रतिषेधरहितत्वदिदमदरिदं नियमदिदं मध्यमयोगार्जितमप्प नोकर्मौदारिकसंचयद्रव्यनियमं पेळल्पट्टुदु स ० । १२- । १६ त

सुहुमणिगोदअपज्जत्तयस्स जादस्स तदियसमयम्हि।
अवरोगाहणमाणं जहण्णयं ओहिखेत्तं तु ॥३७८॥

सूक्ष्मनिगोदापर्याप्तकस्य जातस्य तृतीयसमये। अवरावगाहनमानं जघन्यमवधिक्षेत्रं तु ॥

सूक्ष्मनिगोदलब्ध्यपर्याप्तकन पुट्टिद तृतीयसमयदोळादुदोंदु दृष्टोक्तजघन्यावगाहनमानमदु ६।८।२२ तु मत्ते जघन्यदेशावधिज्ञानविषयमप्प क्षेत्रप्रमाणमक्कुं प १९।८९।८।२२।१९

देशावधिजघन्यज्ञानं द्रव्यतः मध्यमयोगार्जितं नोकर्मौदारिकसंचयं द्व्यर्धगुणहानिमितसमयप्रबद्धसमूहरूपं स्वयोग्यविस्रसोपचयपरमाणुसंयुक्तं लोकेन विभक्तं नियमेन तावन्मात्रमेव जानाति–प्रत्यक्षतया अवबुध्यते न ततोऽल्पमित्यर्थः। जघन्ययोगार्जितस्य नोकर्मौदारिकसंचयस्य अल्पत्वं ततोऽस्य सूक्ष्मत्वसंभवात्। तद्ग्रहणे तज्ज्ञानस्य शक्त्यभावात्। उत्कृष्टयोगार्जितनोकर्मौदारिकसंचयस्य स्थूलत्वं भवति तद्ग्रहणे प्रतिषेधाभावात्। तेन नियमान्मध्यमयोगार्जितनोकर्मौदारिकसंचयो द्रव्यनियमः कथितः। स ० १२—१६ त ॥३७७॥

सूक्ष्मनिगोदलब्ध्यपर्याप्तकस्य उत्पत्तितृतीयसमये यज्जघन्यावगाहनं तत् तु–पुनः जघन्यदेशावधि-

मध्यम योगके द्वारा उपार्जित नोकर्म औदारिक शरीरके संचयको, जो डेढ़ गुण हानि प्रमाण समयबद्धोंका समूहरूप है और अपने योग्य विस्रसोपचयके परमाणुओंसे संयुक्त है उसमें लोकराशिसे भाग देनेपर जो एक भाग मात्र द्रव्य होता है उसे जघन्य देशावधि ज्ञान जानता है। उससे कमको नहीं जानता। जघन्य योगके द्वारा उपार्जित नोकर्म औदारिक शरीरका संचय उससे अल्प होनेसे सूक्ष्म होता है। उसको जाननेकी शक्ति इस ज्ञानकी नहीं है। और उत्कृष्ट योगसे उपार्जित नोकर्म औदारिकका संचय स्थूल होता है उसको जाननेका निषेध नहीं है। तथा विस्रसोपचय रहित सूक्ष्म होता है इसलिए उसको जाननेकी शक्ति नहीं है। इस प्रकार उक्त संचयके घनलोकके प्रदेश प्रमाण खण्ड करके उनमें-से एकखण्डरूप अतीन्द्रिय पुद्गल स्कन्धको सबसे जघन्य देशावधिज्ञान प्रत्यक्ष जानता है, इस प्रकार द्रव्यका नियम कहा है ॥३७७॥

सूक्ष्म निगोद लब्ध्यपर्याप्तकके उत्पत्तिके तीसरे समयमें जो जघन्य अवगाहनाका प्रमाण पहले कहा है वह जघन्य देशावधि ज्ञानके विषयभूत क्षेत्रका प्रमाण होता है। इतने

देकभागमात्रभुजकोटिवेधंगळ अन्योन्यगुणकारोत्पन्नघनक्षेत्रं घनांगुलासंख्यातभागमात्रं खलु परमागमदोळु स्फुटं प्रसिद्धमप्पुदु मक्कुं । तत्समानं जघन्यदेशावधिज्ञानक्षेत्रमक्कुमेंदितु तात्पर्य्यं । तन्न्यासमिदु २/a २/a — गुणितिदोडे घनांगुलासंख्यातभागमात्रमक्कुं ६/a घ शास्त्रदिव २/a जघन्यावगाहनमुं जघन्यदेशावधिक्षेत्रमुमोंदुप्रकारमप्पुवेंदितु तात्पुर्णिच-तात्पदुदु ।

अवरं तु ओहिखेत्तं उस्सेहं अंगुलं हवे जम्हा ।
सुहुमोगाहणमाणं उवरि पमाणं तु अंगुलयं ॥३८१॥

जघन्यं स्वयधिक्षेत्रं उत्सेधांगुलं भवेद्यस्मात् । सूक्ष्मावगाहनमानमुपरि प्रमाणं त्वंगुलं ।

तु मते जघन्यदेशावधिज्ञानविषयक्षेत्रमावुदोंदु जघन्यावगाहनसमानं घनांगुलासंख्यात-भागमात्रं पेळल्पट्टुदवुत्सेधांगुलमक्कुं । व्यवहारांगुलमनाश्रयिसि ये पेळल्पट्टुदु । प्रमाणात्मांगुल-मनाश्रयिसि पेळल्पट्टुदिल्लदेकेंदोडे आवुदोंदु कारणदिदं सूक्ष्मनिगोदलब्ध्यपर्याप्तकजघन्यावगाह-

---

सूक्ष्माङ्गुलं असंख्यातेन भक्तम् तदेकभागमात्रभुजकोटिवेधानां अन्योन्यगुणनोत्पन्नघनाङ्गुलासंख्यातभागमात्रं खलु परमागमे स्फुटं प्रसिद्धमागच्छति । तत्समानजघन्यदेशावधिज्ञानक्षेत्रमित्यर्थः २/a । २/a । गुणिते घनाङ्गुला-संख्यातभागमात्रं भवति ६/a ॥३८०॥

तु—पुनः, जघन्यदेशावधिज्ञानविषयक्षेत्रं यज्जघन्यावगाहनसमानं घनाङ्गुलासंख्यातभागमात्रमुक्तं तदुत्सेधाङ्गुलं व्यवहाराङ्गुलमाश्रित्योक्तं भवति न प्रमाणाङ्गुलं नात्माङ्गुलमाश्रित्य । यस्मात्कारणात्

खण्डन विधानके द्वारा भुज, कोटि और वेधका समीकरण करनेपर, उत्सेधांगुलको असंख्यातसे भाजित करके एक भाग प्रमाण भुज कोटि और वेधको परस्परमें गुणा करनेपर घनांगुलके असंख्यातवें भाग प्रमाण क्षेत्रफल होता है। उसीके समान जघन्य देशावधिज्ञान-का क्षेत्र है।

विशेषार्थ—आमने-सामने दो दिशाओंमें-से किसी एक दिशा सम्बन्धी प्रमाणको भुज कहते हैं। शेष दो दिशाओंमें-से किसी एक दिशा सम्बन्धी प्रमाणको कोटि कहते हैं। ऊँचाई-के प्रमाणको वेध कहते हैं। व्यवहारमें इन्हें ऊँचाई, चौड़ाई, लम्बाई कहते हैं। यहाँ जघन्य क्षेत्रकी लम्बाई, चौड़ाई, ऊँचाई एक सी नहीं है कमती-बढ़ती है। किन्तु क्षेत्रखण्डन विधानके द्वारा समीकरण करनेपर ऊँचाई, चौड़ाई, लम्बाईका प्रमाण उत्सेधांगुलके असंख्यातवें भाग मात्र होता है। उनको परस्परमें गुणा करनेपर घनांगुलके असंख्यातवें भाग प्रमाण घनक्षेत्र-फल होता है। इतना ही प्रमाण जघन्य अवगाहनाका है और इतना ही जघन्य देशावधिके क्षेत्रका है ॥३८०॥

जघन्य देशावधिज्ञानका विषय क्षेत्र जो जघन्य अवगाहनाके समान घनांगुलके असंख्यातवें भागमात्र कहा है वह उत्सेधांगुल व्यवहार अंगुलकी अपेक्षा कहा है, प्रमाणांगुल

भुजकोटिवेदिगळु सूच्यंगुलासंख्यातैकभागमात्रंगळरियल्पडुवुवु २ २ ।
ꝺꝺ ꝺꝺ
२
ꝺꝺ

आवलि असंखभागं तीद भविस्सं च कालदो अवरं ।
ओही जाणदि भावे काल असंखेज्जभागं तु ॥३८३॥

आवल्यसंख्यभागं अतीतं भविष्यं तं च कालतोवरावधिर्ज्जानाति भावे कालासंख्येय भागं तु ।

कालदिदं जघन्यावधिज्ञानं अतीत भविष्यत्कालमनावल्यसंख्यातभागमात्रमनरिगुं ८
ꝺ
स्वविषयैकद्रव्यगतव्यंजनपर्य्यायंगळनावल्यसंख्यातैकभागमात्रपूर्व्वोत्तरंगळ नरिगुमें बुदत्थं । एकेंदोडे व्यवहारकालक्क द्रव्यद पर्य्यायस्वरूपमल्लदन्यत् स्वरूपांतराभावमप्पुदरिदं । भावे भावदोळु तु मत्ते कालासंख्येयभागं तज्जघन्यावधिविषयकालावल्यसंख्यातैकभागद असंख्येयभागमात्रमनरिगुं । इंतु जघन्यदेशावधिज्ञानविषयद्रव्यक्षेत्रकालभावंगळगे सीमाविभागमं पेळ्दु तद्देशावधिज्ञानविकल्पंगळं चतुर्व्विधविषयभेददिदं पेळ्दपं ।

भागमात्रमेव भवति । तद्भुजकोटिवेधाः सूच्यङ्गुलासंख्यातैकभागमात्रा ज्ञातव्याः २ २ ॥३८२॥
ꝺꝺ ꝺꝺ
२
ꝺꝺ

कालेन जघन्यावधिज्ञानं अतीतभविष्यत्कालमावल्यसंख्यातभागमात्रं जानाति ८ । स्वविषयैकद्रव्यगत-
ꝺ
व्यञ्जनपर्यायान् पूर्वोत्तरान् तावतो जानातीत्यर्थः । व्यवहारकालस्य द्रव्यस्य पर्यायस्वरूपं विनाऽन्यस्वरूपान्तराभावात् । भावे तज्जघन्यद्रव्यगतवर्तमानपर्याये तु पुनः कालासंख्येयभागं तज्जघन्यावधिविषयकालस्यावल्यसंख्यातैकभागस्य असंख्यातैकभागमात्रं जानाति ८ । एवं जघन्यदेशावधिज्ञानविषयद्रव्यक्षेत्रकालभावानां सी-
ꝺꝺ
माविभागं प्ररूप्येदानीं द्वितीयादीन् देशावधिज्ञानविकल्पान् चतुर्विधविषयभेदानाह—

होता है। तथापि घनांगुलके असंख्यातवें भाग मात्र ही होता है। उसके भुजा, कोटि और वेध सूच्यंगुलके असंख्यातवें भागमात्र हैं ॥३८२॥

कालकी अपेक्षा जघन्य अवधिज्ञान आवलीके असंख्यातवें भागमात्र अतीत और अनागतकालको जानता है। अर्थात् अपने विषयभूत एक द्रव्यकी अतीत और अनागत व्यंजनपर्यायोंको आवलीके असंख्यातवें भागमात्र जानता है क्योंकि व्यवहारकालके और द्रव्यके पर्याय स्वरूपके बिना अन्य स्वरूप सम्भव नहीं है। भावकी अपेक्षा उस जघन्य द्रव्यगत वर्तमान पर्यायोंको कालके असंख्यातवें भाग जानता है अर्थात् जघन्य अवधिका विषय जो आवलीके असंख्यातवें भागमात्र काल है उसके असंख्यातवें भागमात्र अर्थपर्यायोंको जानता है ॥३८३॥

इस प्रकार जघन्य देशावधिज्ञानके विषय द्रव्य, क्षेत्र, काल और भावकी सीमाका विभाग कहकर अब देशावधिज्ञानके द्वितीय आदि विकल्पोंके विषयभूत द्रव्यादिको कहते हैं—

भुजकोटिवेदिगळु सूच्यंगुलासंख्यातैकभागमात्रंगळरियल्पडुवुवु २/ॳॳ २/ॳॳ १/(२/ॳॳ)

आवलि असंखभागं तीद भविस्सं च कालदो अवरं ।
ओही जाणदि भावे काल असंखेज्जभागं तु ॥३८३॥

आवल्यसंख्यभागं अतीतं भविष्यं तं च कालतोवरावधिर्जानाति भावे कालासंख्येय भागं तु ।

कालदिदं जघन्यावधिज्ञानं अतीत भविष्यत्कालमनावल्यसंख्यातभागमात्रमनरियुं ८/ॳ स्वविषयैकद्रव्यगतव्यंजनपर्य्यायंगळनावल्यसंख्यातैकभागमात्रपूर्व्वोत्तरंगळ नरिगुमें बुदर्थं । एकें दोडे व्यवहारकालक द्रव्यद पर्य्यायस्वरूपमल्लदन्यत् स्वरूपांतराभावमप्पुदरिदं । भावे भावदोळु मत्ते कालासंख्येयभागं तज्जघन्यावधिविषयकालावल्यसंख्यातैकभागद असंख्येयभागमात्रमनरियुं । इंतु जघन्यदेशावधिज्ञानविषयद्रव्यक्षेत्रकालभावं गळगे सीमाविभागमं पेळ्दु तद्देशावधिज्ञानविकल्पंगळं चतुर्व्विधविषयभेददिदं पेळ्वपं ।

भागमात्रमेव भवति । तद्भुजकोटिवेधाः सूच्यङ्गुलासंख्यातैकभागमात्रा ज्ञातव्याः २/ॳॳ २/ॳॳ (२/ॳॳ) ॥३८२॥

कालेन जघन्यावधिज्ञानं अतीतभविष्यत्कालमावल्यसंख्यातभागमात्रं जानाति ८/ॳ । स्वविषयैकद्रव्यगतव्यञ्जनपर्यायान् पूर्वोत्तरान् तावतो जानातीत्यर्थः । व्यवहारकालस्य द्रव्यस्य पर्यायस्वरूपं विनाऽन्यस्वरूपान्तराभावात् । भावे तज्जघन्यद्रव्यगतवर्तमानपर्याये तु पुनः कालासंख्येयभागं तज्जघन्यावधिविषयकालस्यावल्यसंख्यातैकभागस्य असंख्यातैकभागमात्रं जानाति ८/ॳॳ । एवं जघन्यदेशावधिज्ञानविषयद्रव्यक्षेत्रकालभावानां सीमाविभागं प्ररूप्येदानीं द्वितीयादीन् देशावधिज्ञानविकल्पान् चतुर्विधविषयभेदानाह—

होता है। तथापि घनांगुलके असंख्यातवें भाग मात्र ही होता है। उसके भुजा, कोटि और वेध सूच्यंगुलके असंख्यातवें भागमात्र हैं ॥३८२॥

कालकी अपेक्षा जघन्य अवधिज्ञान आवलीके असंख्यातवें भागमात्र अतीत और अनागतकालको जानता है। अर्थात् अपने विषयभूत एक द्रव्यकी अतीत और अनागत व्यंजनपर्यायोंको आवलीके असंख्यातवें भागमात्र जानता है क्योंकि व्यवहारकालके और द्रव्यके पर्याय स्वरूपके बिना अन्य स्वरूप सम्भव नहीं है। भावकी अपेक्षा उस जघन्य द्रव्यगत वर्तमान पर्यायोंको कालके असंख्यातवें भाग जानता है अर्थात् जघन्य अवधिका विषय जो आवलीके असंख्यातवें भागमात्र काल है उसके असंख्यातवें भागमात्र अर्थपर्यायोंको जानता है ॥३८३॥

इस प्रकार जघन्य देशावधिज्ञानके विषय द्रव्य, क्षेत्र, काल और भावकी सीमाका विभाग कहकर अब देशावधिज्ञानके द्वितीय आदि विकल्पोंके विषयभूत द्रव्यादिको कहते हैं—

भुजकोटिवेधंगळुं सूच्यंगुलासंख्यातैकभागमात्रंगळरियल्पडुवुवु २ २ ।
aa aa
२
aa

आवलि असंखभागं तीद भविस्सं च कालदो अवरं ।
ओही जाणदि भावे काल असंखेज्जभागं तु ॥३८३॥

आवल्यसंख्यभागं अतीतं भविष्यं तं च कालतोवरावधिर्जानाति भावे कालासंख्येयभागं तु ।

कालदिदं जघन्यावधिज्ञानं अतीत भविष्यत्कालमनावल्यसंख्यातभागमात्रमनरिगुं ८
a
स्वविषयैकद्रव्यगतव्यंजनपर्य्यायंगळनावल्यसंख्यातैकभागमात्रपूर्व्वोत्तरंगळ नरिगुमें बुदर्थं । एकें-दोडे व्यवहारकालक द्रव्यद पर्य्यायस्वरूपमल्लदन्यत् स्वरूपांतराभावमप्पुदरिदं । भावे भावदोळु तु मत्ते कालासंख्येयभागं तज्जघन्यावधिविषयकालावल्यसंख्यातैकभागद असंख्येयभागमात्रमनरिगुं । इंतु जघन्यदेशावधिज्ञानविषयद्रव्यक्षेत्रकालभावंगळगे सीमाविभागमं पेळ्दु सद्देशावधिज्ञानविकल्पंगळ चतुर्व्विधविषयभेदमिदं पेळ्दपं ।

भागमात्रमेव भवति । तद्भुजकोटिवेधाः सूच्यङ्गुलासंख्यातैकभागमात्रा ज्ञातव्याः २ २ ॥३८२॥
aa aa
२
aa

कालेन जघन्यावधिज्ञानं अतीतभविष्यत्कालमावल्यसंख्यातभागमात्रं जानाति ८ । स्वविषयैकद्रव्यगत-
a
व्यञ्जनपर्यायान् पूर्वोत्तरान् तावतो जानातीत्यर्थः । व्यवहारकालस्य द्रव्यस्य पर्यायस्वरूपं विनान्यस्वरूपान्तराभावात् । भावे तज्जघन्यद्रव्यगतवर्तमानपर्याये तु पुनः कालासंख्येयभागं तज्जघन्यावधिविषयकालस्यावल्यसंख्यातैकभागस्य असंख्यातैकभागमात्रं जानाति ८ । एवं जघन्यदेशावधिज्ञानविषयद्रव्यक्षेत्रकालभावानां सी-
aa
माविभागं प्ररूप्येदानीं द्वितीयादीन् देशावधिज्ञानविकल्पान् चतुर्विधविषयभेदानाह—

होता है। तथापि घनांगुलके असंख्यातवें भाग मात्र ही होता है। उसके भुजा, कोटि और वेध सूच्यंगुलके असंख्यातवें भागमात्र हैं ॥३८२॥

कालकी अपेक्षा जघन्य अवधिज्ञान आवलीके असंख्यातवें भागमात्र अतीत और अनागतकालको जानता है। अर्थात् अपने विषयभूत एक द्रव्यकी अतीत और अनागत व्यंजनपर्यायोंको आवलीके असंख्यातवें भागमात्र जानता है क्योंकि व्यवहारकालके और द्रव्यके पर्याय स्वरूपके बिना अन्य स्वरूप सम्भव नहीं है। भावकी अपेक्षा उस जघन्य द्रव्यगत वर्तमान पर्यायोंको कालके असंख्यातवें भाग जानता है अर्थात् जघन्य अवधिका विषय जो आवलीके असंख्यातवें भागमात्र काल है उसके असंख्यातवें भागमात्र अर्थपर्यायोंको जानता है ॥३८३॥

इस प्रकार जघन्य देशावधिज्ञानके विषय द्रव्य, क्षेत्र, काल और भावकी सीमाका विभाग कहकर अब देशावधिज्ञानके द्वितीय आदि विकल्पोंके विषयभूत द्रव्यादिको कहते हैं—

विशेषदिदं ध्रुवहारप्रमाणमं पेळ्दपं :—

मणदव्ववग्गणाण वियप्पाणंतिमसमं खु धुवहारो ।
अवरुक्कस्सविसेसा रूवहिया तव्वियप्पा हु ॥३८६॥

मनोद्रव्यवर्गणानां विकल्पानामनंतैकभागसमः स्फुटं ध्रुवहारः । अवरोत्कृष्टविशेषाः रूपाधिकास्तद्विकल्पाः खलु ॥

ध्रुवहारप्रमाणमरियल्पडुगुमदेंतेंदोडे मनोद्रव्यवर्गणेगळ विकल्पंगळिनितोळवनि $\frac{\overline{ज}\ १}{ख}$ सदनंतैकभागवोडने $\frac{\overline{ज}\ १}{ख\ ख}$ समानमक्कुं । खलु स्फुटमागि । अंतादोडा मनोद्रव्यवर्गणाविकल्पंगळतावेनितप्पुवेंदोडे पेळल्पडुगुं । अवरोत्कृष्टविशेषाः रूपाधिकास्तद्विकल्पाः खलु जघन्यमनोद्रव्यवर्गणेयनुत्कृष्टमनोद्रव्यवर्गणेयोळ्कळेदुळिद शेषदोळेकरूपं कूडुत्तिरला मनोद्रव्यवर्गणाविकल्पंगळप्पुवु । आदी । ज । अन्ते $\frac{ज\ \overline{ख}}{ख}$ सुद्धे $\frac{ज\ १}{ख}$ वड्ढिहिदे $\frac{ज\ १}{ख\ १}$ रूवसंजुदे ठाणा $\frac{\overline{ज}\ ६}{ख}$ स्थानविकल्पंगळनंतैकभागवोडने $\frac{\overline{ज}}{ख\ ख}$ समानं ध्रुवहारप्रमाणमक्कुमेंबुदर्थमंतादोडा जघन्योत्कृष्टमनोद्रव्यवर्गणेगळ प्रमाणमेनितेंदोडे पेळ्दपं :—

अवरं होदि अणंतं अणंतभागेण अहियमुक्कस्सं ।
इदि मणभेदाणंतिमभागो दव्वम्मि धुवहारो ॥३८७॥

अवरो भवत्यनंतोऽनंतभागेनाधिक उत्कृष्ट, इति मनोभेदानामनंतैकभागो द्रव्ये ध्रुवहारः ॥

ज्ञातव्यम् ॥३८५॥ विशेषेण ध्रुवहारप्रमाणमाह—

मनोद्रव्यवर्गणाया यावन्तो विकल्पास्तेषामनन्तैकभागेन समं संख्यया समानं खलु ध्रुवहारप्रमाणं स्यात् । ते च विकल्पाः कति ? मनोवर्गणाजघन्यं ज तदुत्कृष्टे $\frac{\overline{ज}\ ख}{ख}$ विशोध्य शेषे च रूपाधिकेऽकृते एतावन्तः $\frac{\overline{ज}}{ख}$ खलु स्युः ॥३८६॥ ते जघन्योत्कृष्टे प्रमाणयति—

भूत द्रव्य कहा था उसे ही यहाँ समयप्रबद्धके रूपमें स्थापित किया है । इससे ही ध्रुवहारका भाग दे-देकर आगेके विकल्पोंके विषयभूत द्रव्य लायेंगे ॥३८५॥

सामान्य रूपसे ध्रुवहारका प्रमाण सिद्धराशिके अनन्तवें भाग कहा । अब विशेष रूपसे ध्रुवहारका प्रमाण कहते हैं—

मनोद्रव्यवर्गणाके जितने भेद हैं उनके अनन्तवें भागकी संख्याके बराबर ध्रुवहारका प्रमाण है । मनोवर्गणाके जघन्यको मनोवर्गणाके उत्कृष्टमें-से घटाकर जो प्रमाण शेष रहे उसमें एक जोड़नेपर मनोवर्गणाके भेदोंका प्रमाण होता है ॥३८६॥

आगे मनोवर्गणाके जघन्य और उत्कृष्ट भेदका प्रमाण कहते हैं—

[illegible]

[illegible] ग —१ । १ ।

[illegible]

[illegible] ।

[illegible] — [illegible]

[illegible] १ । १ । १

[illegible]

[illegible] भेदका विषय कार्मणवर्गणामें एक बार ध्रुवहारका भाग देनेसे जो प्रमाण आवे उतना है। उसके आगे द्वितीय भेदका विषय कार्मणवर्गणा प्रमाण है। उसके आगे तृतीय भेदका विषय कार्मणवर्गणाको एक बार ध्रुवहारसे गुणा करनेपर जो प्रमाण हो उतना है। उसके आगे चतुर्थ भेदका विषय दो बार ध्रुवहारसे कार्मणवर्गणाको गुणा करनेपर जो प्रमाण हो उतना है। इस प्रकार एक बार अधिक ध्रुवहारसे कार्मणवर्गणाको गुणा करते-करते दो कम देशावधिके भेदप्रमाण ध्रुवहारोंको परस्परमें गुणा करनेसे जो गुणकारका प्रमाण हुआ उससे कार्मणवर्गणाको गुणा करनेपर जो प्रमाण होता है वही जघन्य देशावधिज्ञानके

केकभागमात्रद्रव्यविकल्पंगळु सूच्यंगुलासंख्यातैकभागमात्रंगळु नडेनडेदेकैकप्रदेशक्षेत्रवृद्धियागुत्तं पोगियुत्कृष्टदेशावधिय सर्व्वोत्कृष्टद्रव्यक्षेत्रविकल्पं पुट्टिदापळु तदुत्कृष्टक्षेत्रं संपूर्णलोकमात्रुदत्तु कारणमिदं। आदिक्षेत्रमनंत्यक्षेत्रदोळकळेदु सूच्यंगुलासंख्यातदिदं गुणिसि लब्धदोळोंदु रूपं कूडिदोडे देशावधिज्ञानविकल्पंगळं द्रव्यविकल्पंगळुमप्पुविवक्कंकसंदृष्टिदेशावधियुत्कृष्टद्रव्यक्षेत्रंगळु इल्लि जघन्यक्षेत्रमनुत्कृष्टक्षेत्रदोळकळेदु शेषम ४ अंगुलासंख्यातकांडकमेर-

४	८
२ ४	७
४२	७
४२२	६
४२२२	६
४२२२२	५
४२२२२२	५
४२२२२२२	४
४२२२२२२२	४
द्रव्य	क्षेत्र

डरिदं गुणिसि एकरूपं कूडिदोडे— ४।२ देशावधिसर्व्वद्रव्यविकल्पंगळप्पुवु ।९। 'आदी अंते सुद्धे वड्ढिहिदे रूवसंजुदे ठाणा'। इंदी स्थानविकल्पमं साधिसुव करणसूत्रदके व्याख्यानं विशेषमागि वस्तुमं देनल्वेडेदे वोडिल्लि यथाव्यमनर्थकवचनमप्पुवरिनल्लि किंचिद्विशेषज्ञापनमक्कुमदें-तें वोडे प्रपत्रकारं 'उत्तवियप्पा जहण्णक्खायिसेसं हवे एत्थ' एंदु जघन्योत्कृष्टंगळं शेषेसुत्तिरल्लि क्षेत्रविकल्पंगळें दु पेळ्दोडल्लि कूडुवेकरूपं पेरिरिसि सूच्यंगुलासंख्यातदिंदं गुणिसि लब्धदोळाकरूपं कूडिदोडे द्रव्यविकल्पंगळ प्रमाणमप्पुदें बो विशेषसूचकमक्कुं।

रूपयुतक्षेत्रविकल्पंगळं सूच्यंगुलासंख्यातदिदं गुणिसिदोडे दृष्टेष्टविरोधमक्कुमदें तें वोडे

अंकसंदृष्टियोळु रूपयुतक्षेत्रविकल्पंगळप्पु ४ इवं कांडकमप्पेरडरिदं गुणिसिदोडे पत्तु १०। इवु

एते एव सूच्यङ्गुलासंख्यातेन गुणिताश्च एकरूपयुताः देशावधिसर्वद्रव्यविकल्पाः स्युः ≡–१।२ कुतः? प ० ०

जघन्यद्रव्यं ध्रुवहारेण भक्त्वा भक्त्वा सूच्यङ्गुलासंख्येयभागमात्रद्रव्यविकल्पेषु गतेषु जघन्यक्षेत्रस्योपर्येकप्रदेशो

और वे क्षेत्रकी अपेक्षा विकल्प इस प्रकार हैं—देशावधिके उत्कृष्ट क्षेत्रमें जघन्य क्षेत्रको घटानेपर जो प्रदेशका प्रमाण शेष रहता है उतने क्षेत्रकी अपेक्षा विकल्प हैं। उनको ही सूच्यंगुलके असंख्यातवें भागसे गुणा करके एक जोड़नेपर देशावधिके द्रव्यकी अपेक्षा विकल्प होते हैं। वह कैसे यह कहते हैं—जघन्य द्रव्यको ध्रुवहारसे भाग देते-देते सूच्यंगुलके असंख्यातवें भाग मात्र द्रव्यके भेद बीतनेपर जघन्य क्षेत्रके ऊपर एक प्रदेश बढ़ता है। इसी प्रकार लोकप्रमाण उत्कृष्ट देशावधिक्षेत्र पर्यन्त जानना। इसका आशय यह है कि सूच्यंगुलके असंख्यातवें भागपर्यंत द्रव्यके विकल्प होने तक क्षेत्र वही रहता है जो जघन्य भेदका विषय था। इतने विकल्प बीतनेपर क्षेत्रमें एक प्रदेशकी वृद्धि होती है। पुनः सूच्यंगुलके असंख्यातवें

वग्गणरासिपमाणं सिद्धाणंतिमपमाणमेत्तंपि ।
दुगसहियपरमभेदपमाणवहाराणसंवग्गो ॥३९२॥

वर्गणाराशिप्रमाणं सिद्धानंतैकभागप्रमाणमात्रमपि । द्विकसहितपरमभेदप्रमाणावहाराणां संवर्गः ॥

वर्ग्गणाराशिप्रमाणं इन्ना कार्म्मण वर्ग्गणाराशिप्रमाणं तानें तुटें दोडे सिद्धानंतैकभागप्रमाणमात्रमपि सिद्धराश्यनंतैकभागप्रमाणमप्पुदंतादोडं द्विकसहितपरमभेदप्रमाणावहाराणां संवर्गः द्विरूपयुक्तपरमावधिज्ञानसर्व्वविकल्पंगळेनितु ध्रुवहारंगळ संवर्ग्गसंजनितलब्धप्रमितमक्कुमंतादोडा परमावधिज्ञानविकल्पंगळतावेनितें दोडे पेळदपं :—

परमावहिस्स भेदा सगओगाहणवियप्पहदतेऊ ।
इदि धुवहारं वग्गणगुणगारं वग्गणं जाणे ॥३९३॥

परमावधेर्भेदाः स्वावगाहनविकल्पहततैजसाः । इति ध्रुवहारं वर्गणागुणकारं वर्गणां जानीहि ॥

परमावधेर्भेदाः परमावधिज्ञानविकल्पंगळुं स्वावगाहनविकल्पहततैजसाः मुन्नं जीवसमासाधिकारदोळ्पेळल्पट्ट स्वकीयावगाहनविकल्पंगळिदं गुणिसल्पट्ट तेजस्कायिकजीवंगळ संख्यातराशियु तदवगाहनविकल्पंगळोळु सर्व्वजघन्यावगाहनमिदु ६ । ८ । २२ तदुत्कृष्टा-

प १९ । ७ । ८ । २२ । १९

कार्मणवर्गणाराशिप्रमाणं सिद्धराश्यनन्तैकभागमात्रमपि द्विरूपाधिकपरमावधिसर्वभेदमात्रध्रुवहारसंवर्गमात्रं स्यात् व ॥३९२॥ ते भेदाः कति ? इति चेदाह—

परमावधिज्ञानस्य भेदा तेजस्कायिकावगाहनविकल्पैर्गुणिततेजस्कायिकजीवराशिमात्रा भवन्ति ा । ६ । ा । ते अवगाहनविकल्पाः प्राग्मत्स्यरचनायां तज्जघन्यमिदं ६ । ८ । २२

प १९ । ८ । ७ । ८ । २२ १९ ।

उतनी बार ध्रुवहारोंको परस्परमें गुणा करनेपर जो प्रमाण होता है वही कार्मण वर्गणाका गुणकार होता है ॥३९१॥

अब क्रमानुसार वर्गणाका प्रमाण कहते हैं—

कार्मण वर्गणा राशिका प्रमाण सिद्ध राशिके अनन्तवें भाग है तथापि परमावधिके समस्त भेदोंमें दो मिलानेपर जितना प्रमाण हो उतनी बार ध्रुवहारोंको परस्परमें गुणा करनेपर जो प्रमाण हो उतना है ॥३९२॥

वे परमावधिके भेद कितने हैं, वह कहते हैं—

तैजस्कायिककी अवगाहनाके विकल्पोंसे तैजस्कायिक जीवराशिको गुणा करनेपर जो प्रमाण हो उतने परमावधिके भेद हैं। तथा अग्निकायिककी जघन्य अवगाहनाके प्रमाण-

क्रमदिदमसंख्यातवारंगळरियल्पडुवुवु । इंतसंख्यातवारं ध्रुवहारभक्तैकैकभागंगळागुत्तं पोपुवंतु पोगल्के :—

देसोहिमज्झभेदे सविस्ससोवचयतेजकम्मंगं ।
तेजोभासमणाणं वग्गणयं केवलं जत्थ ॥३९५।

देशावधिमध्यभेदे सविस्रसोपचयतेजः कार्म्मणांगं । तेजोभाषामनसां वर्ग्गणां केवलां यत्र ॥

पस्सदि ओही तत्थ असंखेज्जाओ हवंति दीउवही ।
वासाणि असंखेज्जा होंति असंखेज्जगुणिदकमा ॥३९६॥

पश्यत्यवधिस्तत्रासंख्येया भवंति द्वीपोदधयः । वर्षाण्यसंख्येयानि भवंत्यसंख्येयगुणित-क्रमाणि ॥

देशावधिमध्यभेदे देशावधिज्ञानमध्यमविकल्पदोळु यत्र आवुदानुमोंदेडेयोळु विस्रसोपचय-सहितमप्प तैजसशरीरस्कंधमुमं कार्म्मणशरीरस्कंधमुमं विस्रसोपचयरहित केवलं तैजसवर्गणेयुमं भाषावर्गणेयुमं मनोवर्गणेयुमं पश्यत्यवधिः अवधिज्ञानं प्रत्यक्षमागरिदुमा येडेगळोळु क्षेत्रंगळ-संख्यातद्वीपोदधिगळप्पुवु । कालंगळुमा येडेगळोळु असंख्यातवर्षंगळप्पुवा द्वीपोदधिगळुं वर्षंगळुम-संख्यातंगळागुत्तमुं तैजसशरीरस्कंधस्थानं मोदलागि उत्तरोत्तरंगळसंख्यातगुणितक्रमंगळुमप्पुवु ।

तत्तो कम्मइयस्सिगिसमयपबद्धं विविस्ससोपचयं ।
धुवहारस्स विभज्जं सव्वोही जाव ताव हवे ॥३९७॥

ततः कार्म्मणस्यैकसमयप्रबद्धं विविस्रसोपचयं । ध्रुवहारस्य विभाज्यं सर्व्वावधिर्य्यावत्ता-वद्भवेत् ॥

विषयद्रव्यं भवति—स ० १२–१६ ख । एवं तृतीयादिविकल्पेष्वपि असंख्यातवारपर्यन्तमेष एव क्रमः
≡ ९
कर्तव्यः ॥३९४॥ तथा सति किं स्यादिति चेदाह—

देशावधिज्ञानमध्यमविकल्पेषु यत्र सविस्रसोपचयं तैजसशरीरस्कन्धं तदग्रे यत्र तादृशं कार्मणशरीर-स्कन्धं तदग्रे यत्र केवलां विविस्रोपचयां तैजसवर्गणां तदग्रे यत्र केवलां भाषावर्गणां तदग्रे केवलां मनोवर्गणां च अवधिज्ञानं जानाति । तत्र पञ्चसु स्थानेषु क्षेत्राणि असंख्यातद्वीपोदधयः कालाः असंख्यातवर्षाणि च भवन्ति तथापि उत्तरोत्तरासंख्यातगुणितक्रमाणि ॥३९५–३९६॥

भाग दूसरे भेदके विषयभूत द्रव्यमें देनेपर तीसरे भेदके विषयभूत द्रव्यका प्रमाण आता है। ऐसा ही क्रम असंख्यात बार पर्यन्त करना चाहिए ॥३९४॥

ऐसा करनेसे क्या होता है यह कहते हैं—

देशावधिज्ञानके मध्यम भेदोंमेंसे जहाँ देशावधिज्ञान विस्रसोपचय सहित तैजस-शरीररूप स्कन्धको जानता है, उससे आगे जहाँ विस्रसोपचय सहित कार्मणस्कन्धको जानता है, उससे आगे जहाँ विस्रसोपचय रहित तैजस वर्गणाको जानता है, उससे आगे जहाँ विस्रसोपचय रहित भाषावर्गणाको जानता है, उससे आगे जहाँ विस्रसोपचयरहित मनोवर्गणाको जानता है वहाँ इन पाँचों स्थानोंमें क्षेत्र असंख्यात द्वीप समुद्र और काल असंख्यात वर्ष होता है। तथापि उत्तरोत्तर असंख्यात गुणितक्रम होता है। अर्थात् पहलेसे

[illegible]

संखातीदा समया पढमे पव्वम्मि उभयदो वड्ढी।
खेत्तं कालं अस्सिय पढमादी कंडये वोच्छं ॥४०३॥

संख्यातीताः समयाः प्रथमे पर्वणि उभयतो वृद्धिः। क्षेत्रं कालमाश्रित्य प्रथमादीनि काण्डकानि वक्ष्यामि ॥

प्रथमे पर्वणि [illegible] संख्यातीताः समयाः असंख्यात[illegible] [illegible]

[illegible] ॥४०२॥

[illegible]

घनांगुलके असंख्यातवें भाग और कभी घनांगुलके संख्यातवें भाग प्रदेशोंकी वृद्धि होनेपर कालमें एक समयकी वृद्धि होनेको अध्रुववृद्धि कहते हैं ॥४०२॥

इस प्रकार पहले काण्डकमें ध्रुवरूप और अध्रुवरूपसे एक-एक समय बढ़ते-बढ़ते असंख्यात समयकी वृद्धि होती है। सो प्रथमकाण्डकके उत्कृष्टकालके समयोंमें से जघन्यकालके समयोंको घटानेपर जो शेष रहे उतने असंख्यात समयोंकी वृद्धि प्रथम काण्डकमें होती है। इसी तरह प्रथमकाण्डकके उत्कृष्ट क्षेत्रके प्रदेशोंमेंसे उसके जघन्य क्षेत्रके प्रदेशोंको घटानेपर जो शेष रहे उतने प्रदेशप्रमाण प्रथम काण्डकमें क्षेत्र वृद्धि होती है। इन वृद्धिरूप क्षेत्र और कालको जघन्य क्षेत्र और जघन्य कालमें जोड़नेपर प्रथम [illegible] [illegible]के क्षेत्र और काल होते हैं। अर्थात् वृद्धिरूप प्रदेशोंके परिमाणको जघन्य [illegible] असंख्यातवें भागमें मिलानेपर प्रथम काण्डकके अन्तिम भेदमें [illegible] प्रमाण [illegible] प्रकार वृद्धिरूप समयोंके परिमाणको जघन्य काल आवलीके [illegible] प्रथम काण्डक-

भरहम्मि अद्धमासं साहियमासं च जंबुदीवम्मि ।
वासं च मणुवलोए वासपुधत्तं च रुजगम्हि ॥४०६॥

भरतेर्द्धमासः साधिकमासश्च जंबूद्वीपे। वर्षं च मनुजलोके वर्षपृथक्त्वं च रुचके ॥

अष्टमकांडकदोळु भरतक्षेत्रमुमर्द्धमासमक्कुं। भर। मर्द्धं मा । नवमकांडकदोळु जंबूद्वीपमं साधिकमासमुमक्कुं। जं मा. १। दशमकांडकदोळु मनुष्यलोकमुमेकवर्षमुमक्कुं। म ४५ ल। वर्षं १। एकादशकांडकदोळु रुचकद्वीपमुं च वर्षपृथक्त्वमुमक्कुं। रु। व पृ।

संखेज्जपमे वासे दीवसमुद्दा हवंति संखेज्जा ।
वासम्मि असंखेज्जे दीवसमुद्दा असंखेज्जा ॥४०७॥

संख्येयप्रमे वर्षे द्वीपसमुद्रा भवंति संख्येयाः। वर्षे असंख्येये द्वीपसमुद्रा असंख्येयाः ॥

संख्येयप्रमे वर्षे द्वीपसमुद्रा भवंति संख्येयाः। वर्षे असंख्येये द्वीपसमुद्रा असंख्येयाः। द्वी = स = १ ॥ वर्
द्वादशकांडकदोळु संख्येयमात्र द्वीपसमुद्रंगळु संख्यातवर्षंगळुमप्पुवु। द्वी = स = १ ॥ वर्ष
१। मेले त्रयोदशादि कांडकंगळोळु तेजसशरीरादि द्रव्यविकल्पंगळेडेयोळु मुं पेळ्दसंख्यातद्वीप
समुद्रंगळु तत्कालंगळुमसंख्यातवर्षंगळुमसंख्यातगुणितक्रमंगळप्पुवु। इंतु देशावधिज्ञानविषयंगळ
द्रव्यक्षेत्रकालं भावंगळ एकान्नविंशतिकांडकंगळोळु चरमकांडक चरमद्रव्यक्षेत्रकालभावंगळु
पेळ्द ध्रुवहारेकवारभक्तकार्म्मणवर्गणेयुं व संपूर्णकमुं≡समयोनेकपल्यमुं ॥ प १ ॥ यथा
१
दिदमप्पुवुमाद्यदेशावधिज्ञानविषय द्रव्यक्षेत्रकालभावंगळगे संदृष्टि—

अष्टमकाण्डके क्षेत्रं-भरतक्षेत्र, काल अर्धमासः, भर अर्धमा = । नवमकाण्डके क्षेत्रं जम्बूद्वीप, साधिकमासः, जं = । मा १ । दशमकाण्डके क्षेत्रं मनुष्यलोकः कालः एकवर्षः, ४५ ल वर्ष १ । काण्डके क्षेत्रं रुचकद्वीपः, कालः वर्षपृथक्त्वं रु । व पृ ॥४०६॥

द्वादशे काण्डके क्षेत्रं संख्येयद्वीपसमुद्राः । कालः संख्यातवर्षाणि द्वी = स = १ वर्ष १ । उपरि दिषु काण्डकेषु तैजसशरीरादिद्रव्यविकल्पस्थानेषु क्षेत्राणि असंख्यातद्वीपसमुद्राः कालः असंख्या उभयेऽपि असंख्यातगुणितक्रमेण भवन्ति । चरमकाण्डकचरमे द्रव्यं ध्रुवहारभक्तकार्मणवर्गणा व क्षे
१
लोकः≡कालः समयोनपल्यं प—१ ॥४०७॥

अष्टमकाण्डकमें क्षेत्र भरतक्षेत्र और काल आधामास है। नौवें काण्डकमें क्षे द्वीप काल कुछ अधिक एक मास है। दसवें काण्डकमें क्षेत्र मनुष्य लोक, काल है। ग्यारहवें काण्डकमें क्षेत्र रुचकद्वीप काल वर्षपृथक्त्व है ॥४०६॥

बारहवें काण्डकमें क्षेत्र संख्यात द्वीप-समुद्र और काल संख्यात वर्ष है। आदि काण्डकोंमें जो तैजस शरीर आदि द्रव्यकी अपेक्षा स्थान कहे हैं, उनमें क्षे द्वीप समुद्र है और काल असंख्यात वर्ष है। दोनों ही आगे-आगे क्रमसे अ असंख्यातगुने होते हैं। अन्तके उन्नीसवें काण्डकमें द्रव्य तो कार्मणावर्गणामें भाग देनेसे जो प्रमाण आवे उतना है। क्षेत्र सम्पूर्ण लोक है और काल एक स ... है ॥४०७॥

काल विसेसेणवहिदखेत्तविसेसो धुवा हवे वड्ढो ।
अद्धुववड्ढीवि पुणो अविरुद्धं इट्ठकंडम्मि ॥४०८॥

कालविशेषेणापहृतक्षेत्रविशेषो भवेत् ध्रुवा वृद्धिः । अध्रुववृद्धिरपि पुनरविरुद्धमिष्टकाण्डे ।

कालविशेषेणापहृतः क्षेत्रविशेषो ध्रुवा वृद्धिर्भवेत् । प्रथमकांडकदोळु जघन्यकालमं ८/० तन्नुत्कृष्टकालदोळु ८/१ विशोधिसि ८ ०–१/१ ० बर्दुदिदं भागिसल्पट्ट क्षेत्रविशेषं जघन्यक्षेत्रमं ६/० तन्नुत्कृष्टक्षेत्रदोळु ६/१ शोधिसिदुदनिदं ६ ०–१/१ ० भागिसिद लब्ध ६ ०–१/(१ ० ८ ० १)/१ ० मपवर्तितमिदु ६/८ ध्रुवा भवेत् वृद्धिः । प्रथमकांडकदोळु ध्रुववृद्धिप्रमाणमक्कुं । सूच्यंगुलासंख्यातभागमात्रद्रव्यविकल्पंगळवस्थितरूपदिदं नडदोडे प्रदेशं क्षेत्रदोळु पेर्च्चुगुमी क्रमदिदमोघावलि भक्तघनांगुलप्रमितप्रदेशंगळु जघन्यक्षेत्रदोळु पेर्च्चे कालदोळोंदु समयं जघन्यकालद मेले पेर्च्चुगुमिदु तत्कांडकचरमपर्य्यंतं ध्रुवरूपदिदं जघन्यकालद मेले पेर्च्चिद समयंगळिनितप्पुवु ८ ० १/१ ० इदं जघन्यकालदोळु ८/० समच्छेदं माडि कूडिदोडे प्रथमकांडक चरमदोळु आवलि संख्येयभागमक्कुमें पुदर्थं ८/१ जघन्य क्षेत्रद मेले ६/० पेर्च्चिद प्रदेशंगळुमिनितप्पुवु ६ ० १/१ ६ विदं जघन्यक्षेत्रदोळु कूडिदोडे प्रथमकांडकचरमदोळु घनांगुलसंख्येयभागमात्रमक्कुं ६/१ इंतेल्ला कांडकंगळोळं ध्रुववृद्धियं

विवक्षितकाण्डके जघन्यक्षेत्रं स्वोत्कृष्टक्षेत्रे जघन्यकालं च स्वोत्कृष्टकाले विशोध्य शेषराशी क्षेत्रकालविशेषौ स्याताम् । तत्र प्रथमकाण्डके कालविशेषेण ८ । ०–१/१ । ० क्षेत्रविशेषः ६ । ०–१/१ । ० भक्त्वा ६ ०–१/(१ ० ८ ०–१)/१ ० अपवर्तितः ६/८ ध्रुववृद्धिर्भवेत् । सूच्यङ्गुलासंख्येयभागमात्रद्रव्यविकल्पेषु अवस्थितरूपेण गतेषु एकप्रदेशः क्षेत्रे वर्धते । अनेनक्रमेण आवल्यिभक्तघनाङ्गुलप्रमितप्रदेशाः जघन्यक्षेत्रस्योपरि वर्धन्ते । तदा जघन्यकालस्योपरि एकः समयो वर्धते । एवं तत्काण्डकचरमपर्यन्तं ध्रुवरूपेण जघन्यकालस्योपरि वर्धितसमयप्रमाणमिदम् । ८ ०–१/१ ०

विवक्षित काण्डकके अपने उत्कृष्ट क्षेत्रमें जघन्य क्षेत्रको और अपने उत्कृष्ट कालमें। जघन्य कालको घटानेपर जो शेष राशि रहती है उसको क्षेत्र विशेष और काल विशेष कहते हैं। प्रथम काण्डकके कालविशेषसे क्षेत्रविशेषमें भाग देनेपर ध्रुववृद्धिका प्रमाण होता है। सूच्यंगुलके असंख्यातवें भागमात्र द्रव्यके विकल्पोंके बीतनेपर क्षेत्रमें एक प्रदेश बढ़ता है। इस क्रमसे जघन्य क्षेत्रके ऊपर आवलीसे भाजित घनांगुल प्रमाणप्रदेश जघन्य क्षेत्रके ऊपर बढ़ते हैं। इतने प्रदेश जघन्य क्षेत्रके ऊपर बढ़नेपर जघन्यकालके ऊपर एक समय बढ़ता है। इस प्रकार प्रथम काण्डकके अन्त पर्यन्त ध्रुववृद्धिसे जितने समय बढ़ें उन्हें जघन्यकालमें मिलानेपर आवलीका संख्यातवाँ भाग प्रथम काण्डकका उत्कृष्ट काल होता है। इसी तरह जितने जघन्य क्षेत्रके ऊपर प्रदेश बढ़ें उन्हें जघन्य क्षेत्रमें मिलानेपर घनांगुलका संख्यातवाँ

कार्मणवर्गणेयोळ् ध्रुवहारदिदं भागिसिदोडे देशावधिज्ञानोत्कृष्टद्रव्यमक्कुं च[1] उत्कृष्टं क्षेत्रं मत्ते लोकदोळेंदु षोडशोत्तरदिं संपूर्णलोकमात्रमक्कुं ।

पल्लसमऊणकाले भावेण असंखलोगमेत्ता हु ।

दव्वस्स य पज्जाया वरदेसोहिस्स विसया हु ॥४११॥

पल्ये समयोने काले भावेन असंख्य लोकमात्राः खलु । द्रव्यस्य च पर्यायाः वरदेशावधे-र्विषयाः खलु ॥

कालदोळु देशावधिज्ञानोत्कृष्टं समयोनपल्यमात्रमक्कुं । प १ । भावदिमसंख्यातलोकमात्रंगळु द्रव्यमात्र ... द्रव्यपर्यायंगळु वरदेशावधिज्ञानदके विषयंगळप्पुवु । अप्पुवल्लि ।≡a॥

काले चउण्ह उड्ढी कालो भजिदव्व खेत्तउड्ढी य ।

उड्ढीए दव्वपज्जय भजिदव्वा खेत्तकाला हु ॥४१२॥

काले चतुर्णां वृद्धिः कालो भजनीयः क्षेत्रवृद्धिश्च । द्रव्यपर्याययोर्वृद्धौ भक्तव्यौ क्षेत्रकालौ तु ॥

अवधिज्ञानदोळ् कालवृद्धियागुत्तिरलु द्रव्यक्षेत्रकालभावंगळ्गेल्लक्कं वृद्धियक्कुं । क्षेत्रवृद्धिया-गुत्तं विरलु कालक्के भजनीयमक्कुं । द्रव्यभावंगळ वृद्धियोळु क्षेत्रकालंगळवृद्धियोळु विकल्पनीयं-गळप्पुवेंदु युक्तियुक्तमेयक्कुं ।

कार्मणवर्गणायां एकवारं ध्रुवहारेण भक्तायां देशावधेरुत्कृष्टद्रव्यं भवति च उत्कृष्टक्षेत्रं पुनः संपूर्णलोको भवति ॥४१०॥

काले देशावधेरुत्कृष्टः समयोनपल्यं भवति प—१ । भावेन पुनः असंख्यातलोकमात्रं भवति ≡a । कालभावशब्दाभ्यां द्रव्यस्य पर्यायाः वरदेशावधिज्ञानस्य उत्कृष्टं विषया भवन्ति ॥४११॥

यदा कालवृद्धिस्तदा द्रव्यादीनां चतुर्णां वृद्धयो भवन्ति । यदा क्षेत्रवृद्धिस्तदा कालवृद्धिः स्याद्वा न वेति भजनीया । यदा द्रव्यभाववृद्धी तदा क्षेत्रकालवृद्धी अपि भजनीये इत्येतदपि युक्तियुक्तमेव ॥४१२॥ अथ परमावधिज्ञानस्य व्याख्यामाह—

कार्मणवर्गणाको एक बार ध्रुवहारसे भाजित करनेपर देशावधिका उत्कृष्ट द्रव्य होता है और उत्कृष्ट क्षेत्र सम्पूर्ण लोक है ॥४१०॥

देशावधिका उत्कृष्ट काल एक समयहीन पल्य है और भाव असंख्यात लोकप्रमाण है । काल और भावशब्दसे द्रव्यकी पर्याय उत्कृष्ट देशावधिज्ञानके विषय होती हैं। ऐसा जानना ।

विशेषार्थ—एक समयहीन एक पल्य प्रमाण अतीतकालमें हुई और उतने ही प्रमाण आगामी कालमें होनेवाली द्रव्यकी पर्यायोंको उत्कृष्ट देशावधि जानता है । भावसे असंख्यात लोकप्रमाण पर्यायोंको जानता है ॥४११॥

अवधिज्ञानके विषयमें जब कालकी वृद्धि होती है तब द्रव्य, क्षेत्र, काल, भाव चारोंकी वृद्धि होती है । जब क्षेत्रकी वृद्धि होती है तब कालकी वृद्धि भजनीय है, हो या न हो । जब द्रव्य और भावकी वृद्धि होती है तब क्षेत्र और कालकी वृद्धि भजनीय है । यह सब युक्ति युक्त ही है ॥४१२॥

---

१. तदिन्द्रियसम्पन्नार्थमणीतिरिक्तो भाव इति राजवार्तिके उक्तत्वात् द्रव्यस्य पर्याया एव भावाः । कालभावाभ्यां भूतभावि पर्यायाणां वर्तमानपर्यायाणां च कालभावरूपत्वात् इति टिप्पण ।

मत्तमा परमावधिसर्व्वोत्कृष्टद्रव्यमं ध्रुवहारप्रमितमं । ९ । तु मत्ते ध्रुवहारदिदं भागिसिदोडों दे परमाणवक्कुमा द्रव्यं सर्व्वावधिज्ञानविषयद्रव्यमक्कुमा सर्व्वावधिज्ञानमुं निर्व्विकल्पमेयक्कुमितु देशावधिज्ञानविषयमप्प जघन्यद्रव्यराशियोळु मध्यमयोगार्ज्जितनोकर्म्मौदारिकशरीरसंचयसविस्रसोपचयलोकविभक्तप्रमितद्रव्यस्कंधदोळु देशावधिज्ञानद्वितीयविकल्पं मोदल्गोंडु परमावधिज्ञानसर्व्वोत्कृष्टद्रव्यपर्य्यंतमदमोळ पोन्दु गंगानदीमहाप्रवाहमें तु हिमाचलदोळ्पुट्टि पूर्व्वोदधिपर्य्यंतमविच्छिन्नरूपदिदं परिदु पोगि तदुदधिप्रविष्टमादुदंते ध्रुवहारमुमविच्छिन्नरूपदिदं प्रवेशिसि प्रवेशिसि परमाणुद्रव्यपर्य्यवसानमागि निंदुदेकेंदोडे विषयभूतपरमाणुवुं विषयियप्पसर्व्वावधिज्ञानमुं निर्व्विकल्पकंगळप्पुदरिंद ।

परमोहिदव्वभेदा जेत्तियमेत्ता हु तेत्तिया होंति ।

तस्सेव खेत्तकालवियप्पा विसया असंखगुणिदकमा ॥४१६॥

परमावधिद्रव्यभेदाः यावन्मात्राः खलु तावन्मात्रा भवंति । तस्यैव क्षेत्रकालविकल्पाः विषया असंख्यगुणितक्रमाः ॥

परमावधिज्ञानविषयद्रव्यविकल्पंगळु यावन्मात्रंगळु तावन्मात्रंगळेयप्पुवु । परमावधिज्ञानविषयंगळप्प क्षेत्रविकल्पंगळुं कालविकल्पंगळुं तावन्मात्रविकल्पंगळागुत्तलुं तंतम्म जघन्यविकल्पं मोदल्गोंडु संतम्मुत्कृष्टपर्य्यंतमसंख्यातगुणितक्रमंगळप्पुवेंतप्पऽसंख्यातगुणितक्रमंगळप्पुवें दोडे पेळ्दपं ।

पुनस्तत्परमावधिसर्वोत्कृष्टं द्रव्यं ९ ध्रुवहारेणैकवारं भक्तं एकपरमाणुमात्रं सर्वावधिज्ञानविषयं द्रव्यं भवति । तज्ज्ञानं निर्विकल्पकमेव स्यात् । स च ध्रुवहारः गङ्गामहानद्याः प्रवाहवद्भवति—यथा गङ्गामहानदीप्रवाहः हिमाचलादविच्छिन्नं प्रवह्य पूर्वोदधौ गत्वा स्थितस्तथायं ध्रुवहारोऽपि देशावधिविषयजघन्यद्रव्यात्परमावधिसर्वोत्कृष्टद्रव्यपर्यन्तं प्रवह्य परमाणुपर्यवसाने स्थितः विषयस्य परमाणोः, विषयिणः परमावधेश्च निर्विकल्पकत्वात् ॥४१५॥

परमावधिज्ञानविषयद्रव्यविकल्पा यावन्मात्राः तावन्मात्रा एव भवन्ति तस्य विषयभूतक्षेत्रकालविकल्पाः । तावन्मात्रा अपि स्वस्वजघन्यात् स्वस्वोत्कृष्टपर्यन्तं असंख्यातगुणितक्रमा भवन्ति ॥४१६॥ कीदृगसंख्यातगुणितक्रमाः ? इत्युक्ते प्राह—

उस परमावधिके सर्वोत्कृष्ट द्रव्यको एक बार ध्रुवहारसे भाग देनेपर एक परमाणु मात्र सर्वावधिज्ञानका विषयभूत द्रव्य होता है । यह ज्ञान निर्विकल्प ही होता है इसमें जघन्य-उत्कृष्ट भेद नहीं है । यह ध्रुवहार गंगा महानदीके प्रवाहकी तरह है । जैसे गंगा महानदीका प्रवाह हिमाचलसे अविच्छिन्न निरन्तर बहता हुआ पूर्व समुद्रमें जाकर ठहरता है वैसे ही यह ध्रुवहार भी देशावधिके विषयभूत जघन्य द्रव्यसे सर्वावधिके उत्कृष्ट द्रव्य पर्यन्त बहता हुआ परमाणुपर आकर ठहरता है । सर्वावधिका विषय परमाणु और सर्वावधि ये दोनों ही निर्विकल्प हैं ॥४१५॥

परमावधिज्ञानके विषयभूत द्रव्यकी अपेक्षा जितने भेद कहे हैं उतने ही भेद उसके विषयभूत क्षेत्र और कालकी अपेक्षा होते हैं । फिर भी अपने-अपने जघन्यसे अपने-अपने उत्कृष्ट पर्यन्त क्रमसे असंख्यात गुणित क्षेत्र व काल होते हैं ॥४१६॥

किस प्रकार असंख्यात गुणित होते हैं यह कहते हैं—

दलितेषु दलितेषु गुणकारंगळप्पुवु ४८।१५ ४-१।८।१५ ई प्रकारदिदं चतुर्विशत्यवधि-

कल्पविकल्पंगळोळं नेतव्यमप्पुवु गुणकारंगळु तत्संयोगंगळप्पुवु द्विकादिगुणंगळो गुणकारंगळप्पुवु ई सर्वविकल्पंगळप्पुवु ॥

मत्तो गुणकारंगळुत्पत्तिक्रमवं प्रकारांतरदिदं पेळदपरु :—

गच्छसमा तक्कालियतीदे रूऊणगच्छधणमेत्ता ।

उभये वि य गच्छस्स य धणमेत्ता होंति गुणगारा ॥४१८॥

गच्छसमाः तात्कालिकातीते रूपोनगच्छधनमात्राः । उभयेऽपि गच्छस्य च धनमात्राः भवंति गुणकाराः ॥

अथवा गच्छसमानगुणकाराः विवक्षितगच्छमात्रा गुणकारंगळु तात्कालिकातीते तद्विवक्षित-स्थानांतरदनंतरविकल्पदोळु रूपोनगच्छधनमात्राः तद्विवक्षितरूपोनगच्छधनमात्रंगळु उभय-मिल्लि मिलिते ई रूपोनगच्छधनमात्रंगळु विवक्षितगच्छमात्रंगळुं कूडुत्तिरलु गच्छस्य च धनमात्रा भवंति मुं पेळ्दंते विवक्षितगच्छधनमात्रंगळप्पुवु । अदेंतेंदोडे विवक्षितचतुर्थविकल्पदोळु गुण-काराः गुणकारंगळु गच्छमात्राः विवक्षितगच्छमात्रंगळु ४ तात्कालिकातीते तद्विवक्षितस्थानांत-

रानंतरविकल्पदोळु रूपोनगच्छधनमात्राः तद्विवक्षितरूपोनगच्छधन $\frac{4 \cdot 4}{2 \cdot 1}$ मात्रंगळु ६ उभ-

यमिल्लिमिलितेऽपि च ई रूपोनगच्छधनमात्रंगळुं विवक्षितगच्छमात्रंगळुं ४ कूडुत्तिरलु गच्छस्य धनमात्रा भवंति मुं पेळ्दंते विवक्षितगच्छधनमात्रंगळु पत्तु गुणकारंगळप्पुवु ४८।१०।४-१।८।१०

अंतु पंचमविकल्पदोळु गुणकाराः गुणकारंगळु गच्छमात्राः विवक्षितगच्छमात्रंगळु ५ तात्कालिका-तीते तद्विवक्षितस्थानांतरानंतरविकल्पदोळु रूपोनगच्छधनमात्राः तद्विवक्षितरूपोनगच्छधन

$\frac{5 \cdot 4}{2 \cdot 1}$ मात्रंगळु १० । उभयमिल्लिमिलितेऽपि च ई रूपोनगच्छधनमात्रंगळु १० । विवक्षितगच्छ-

मात्रंगळुं ५ कूडुत्तिरलु गच्छस्य च धनमात्रा भवंति मुं पेळ्दंते विवक्षितगच्छधनमात्रंगळु पदिनैदु

चतुर्थस्थानकालस्य प्रमाणं भवति ॥४१७॥ पुनः प्रकारान्तरेण तानेव गुणकारान् दर्शयति—

गच्छसमाः—गच्छमात्रा यथा चतुर्थविकल्पे चत्वारः, तात्कालिकातीते च तृतीयविकल्पे रूपोनगच्छ-

---

प्रमाण आवे उतना परमावधिके पाँचवें भेदके विषयभूत क्षेत्रका परिमाण होता है । तथा इसी गुणकारसे देशावधिके विषयभूत उत्कृष्ट काल एक समय हीन एक कल्पको गुणा करनेपर पाँचवें भेदमें कालका परिमाण होता है । इसी तरह सब भेदोंमें जानना ॥४१७॥

पुनः प्रकारान्तरसे उन्हीं गुणकारोंको कहते हैं—

गच्छके समान धन और गच्छसे तत्काल अतीत जो विवक्षित भेदसे पहला भेद, सो विवक्षित गच्छसे एक कम गच्छका जो संकलित धन, इन दोनोंको मिलानेसे गच्छका संकलित धन प्रमाण गुणकार होता है । उदाहरण कहते हैं—जिसमेंका भेद विवक्षित हो

देसदछप्पण्णंगळं संवर्ग माडिद लब्धं तृतीयपदवोळु परमावधिक्षेत्रकालंगळ्गे गुणकारप्रमाणमक्कु = ६५। ≡ २५६। प—१। ६५ = २५६। मिते चरमवोळं देयमावल्यसंख्यातभागमक्कु ८ / a मी राशिगळर्द्धच्छेदंगळेनितप्पुवेंदोडे संख्यातरूपहीनावलिच्छेदमात्रंगळप्पुवु १६—४ यदेंतेंदोडे—

विरलिज्जमाणरासी दिण्णस्सद्धच्छिदीहि संगुणिदे।
अद्धच्छेदसलागा होंति समुप्पण्णरासिस्स।

एंदितावलियें पुदु परिमितासंख्यातजघन्यराशियं विरळिसि प्रतिरूपमा राशियने कोट्टु वर्गितसंवर्गं माडे संजनितराशियप्पुदरिदमा परिमितासंख्यातजघन्यराश्यर्द्धच्छेदंगळु संख्यातरूपंगळिदं गुणिसल्पट्ट परीतासंख्यातजघन्यराशिप्रमाणमावलियर्द्धच्छेदंगळप्पुवु । १६।—७। गुणिसिदोडे सव्वधाराविं तद्योग्यधारिगळोळु परीतासंख्यातमध्यपतितासंख्यातराशियक्कुमदके संदृष्टि पदिनारु १६ इदरोळु हारभूतासंख्यातार्द्धच्छेदंगळु संख्यातरूपंगळप्पुवुवं ४ कळेदोडे देयमावल्यसंख्यातराशिगळर्द्धच्छेदंगळप्पुवु १६-४। इंतु त्रैराशिकं माडल्पडुगुं प्र वि छे ८ वि छे / a / १। १६-४ छे १। फ≡। इ ≡a ६ a / प २ / a ८ ≡a ६ a / a पा१ / a ई त्रैराशिकमं कटाक्षिसि पेळ्दपं। देयच्छेदे-

पल्लब्धं तस्मात् १ वेसदछप्पण्णाना गुणने परस्परसंवर्गसंजनितराशिः तृतीयपदे परमावधिक्षेत्रकालयोर्गुणकारप्रमाणं भवति≡ ६५ = २५६। प-१। ६५ = २५६ एवं चरमेऽपि देयमावल्यसंख्येयभागः तस्य अर्धच्छेदाः भागहारार्धच्छेदन्यूनभाज्यार्धच्छेदमात्रत्वात् संख्यातरूपन्यूनपरीतासंख्यातमध्यमभेदमात्राः संदृष्टया एतावन्तः १६-४ एभिः देयार्धच्छेदैर्भक्तेन लोकार्धच्छेदराशिना पदधने—परमावधिज्ञानचरमविकल्पसंकलितसर्वधने भक्ते सति यल्लब्धं तन्मात्रलोकानां परस्परगुणने परमावधिचरमगुणकारो भवति। यथैतावतां देयरूपावल्यसंख्येयभागानां दे ८ / a परस्परगुणने लोक उत्पद्यते फ ≡ तदा एतावतां देयरूपावल्यसंख्येय-
प्र। वि छे छे १
१६—४

उससे विवक्षित पदके संकलित धनमें भाग दें। उससे जो प्रमाण आवे उतनी जगह लोकराशिको रखकर परस्परमें गुणा करनेपर जो प्रमाण आवे वह विवक्षित पद सम्बन्धी क्षेत्र या कालका गुणकार होता है। इसी प्रकार परमावधिके अन्तिम भेदमें गुणकार जानना। जैसे देयराशि चौंसठका चौथा भाग अर्थात् सोलह, उसके अर्धच्छेद चार, उसका भाग दो सौ छप्पनके अर्धच्छेद आठमें देनेपर दो लब्ध आया। उसका भाग विवक्षित पद तीनके संकलित धन छहमें देनेसे तीन आया। सो तीन जगह दो सौ छप्पन रखकर परस्परमें गुणा करनेसे जो प्रमाण होता है वही तीसरे स्थानमें गुणकार जानना। इसी तरह यथार्थमें देयराशि आवलीका असंख्यातवाँ भाग, उसके अर्धच्छेद आवलीके अर्धच्छेदोंमें-से भाजक असंख्यातके अर्धच्छेदोंको घटानेपर जो प्रमाण रहे, उतने हैं। सो वे संख्यातहीन परीतासंख्यातके मध्यमभेद प्रमाण होते हैं। इनका भाग लोकराशिके अर्धच्छेदोंमें देनेपर जो प्रमाण आवे, उसका भाग परमावधिके विवक्षित भेदके संकलित धनमें देनेसे जो प्रमाण

देशावधिज्ञानविषयजघन्यकालमं नोडलु ८/a मसंख्यातगुणहीनमात्रंगळप्पुवु ८/aa स्

सव्वोहित्ति य कमसो आवलियसंखभागगुणिदकमा ।
दव्वाणं भावाणं पदसंखा सरिसगा होंति ॥४२३॥

सर्व्वावधिज्ञानपर्य्यंतं क्रमशः आवल्यसंख्यभागगुणितक्रमाः । द्रव्याणां भावा
सदृशाः भवंति ॥

देशावधिज्ञानविषयजघन्यद्रव्यदपर्य्यायंगळप्प भावंगळु जघन्यदेशावधिज्ञान
सर्व्वावधिज्ञानपर्य्यंतं क्रमदिदं आवल्यसंख्यातगुणितक्रमंगळप्पुववु कारणमागि द्रव्यंग
स्यानसंख्येगळु समानंगळेयप्पुवु ।

अनंतरं नरकगतियोळ् नारकगंवधिविषयक्षेत्रमं पेळ्दपरु—

सत्तमखिदिम्मि कोसं कोसस्सद्धं पवड्ढदे ताव ।
जाव य पढमे णिरये जोयणमेक्कं हवे पुण्णं ॥४२४॥

सप्तमक्षितौ क्रोशः क्रोशस्यार्द्धं प्रवर्द्धते तावत् । यावत्प्रथमे नरके योजनमेकं भवेत्पू

सप्तमक्षितिमाघवियोळु नारकगंवधिविषयमप्प क्षेत्रमेकक्रोशमात्रमक्कुं । षष्ठ
क्रोशार्द्धं पेर्च्चुगुं । पंचमक्षितियोळु मत्तमदं नोडे क्रोशार्द्धं पेर्च्चुगुं । चतुर्थक्षितियोळ
क्रोशार्द्धं पेर्च्चुगुं । तृतीयक्षेत्रदोळदर मेले क्रोशार्द्धं पेर्च्चुगुं । द्वितीयपृथ्वियोळमंते
पेर्च्चुगुं । प्रथमक्षितियोळु क्रोशार्द्धं पेर्च्चि संपूर्ण योजनप्रमाणमक्कुं । मा क्रोश १ ।
म ३/२ । भ । क्रोश २ । अं क्रोश ५/२ । मे क्रोश ३ । वं क्रो ७/२ । घ क्रो ४ ।

थसंख्यातगुणहीनभावाः स्फुटं भवन्ति ८/aa ॥४२२॥

देशावधिजघन्यद्रव्यस्य पर्यायरूपभावाः जघन्यदेशावधितः सर्वावधिज्ञानपर्यन्तं क्रमेण आवल्यसंख्य
गुणितक्रमाः स्युः । तेन द्रव्याणां भावानां च स्थानसंख्या समाना एव ॥४२३॥ अथ नरकगतावधिविष
क्षेत्रमाह—

सप्तमक्षितौ अवधिविषयक्षेत्रं एकक्रोशः । तत उपरि प्रतिपृथ्वि तावत् क्रोशस्यार्धार्धं प्रवर्धते यावत्प्रथ

है । तथापि उसके विषयभूत जघन्य कालसे असंख्यातगुणा हीन हैं ॥४२२॥

देशावधिके विषयभूत द्रव्यके पर्यायरूप भाव जघन्य देशावधिसे सर्वावधिज्ञान पर्यन्त
क्रमसे आवलीके असंख्यातवें भाग प्रमाणसे गुणित हैं । अर्थात् देशावधिके विषयभूत द्रव्य-
की अपेक्षा जहाँ जघन्य भेद है वहाँ ही द्रव्यके पर्यायरूप भावकी अपेक्षा आवलीके
असंख्यातवें भाग प्रमाण भावको जाननेरूप जघन्य भेद है । जहाँ द्रव्यकी अपेक्षा दूसरा
भेद है वही भावकी अपेक्षा उस प्रथम भेदको आवलीके असंख्यातवें भागसे गुणा करनेपर
जो प्रमाण आवे उस प्रमाण भावको जानने रूप दूसरा भेद है । इसी प्रकार सर्वावधिपर्यन्त
जानना । इस तरह अवधिज्ञानके जितने भेद द्रव्यकी अपेक्षा हैं उतने ही भावकी अपेक्षा हैं ।
अतः द्रव्य और भावकी अपेक्षा स्थान संख्या समान है ॥४२३॥

अब नरकगतिमें अवधिज्ञानका विषयक्षेत्र कहते हैं—

सातवीं पृथ्वीमें अवधिज्ञानका विषयभूत क्षेत्र एक कोस है । उससे ऊपर

अमुराणमसंखेज्जा कोडीओ सेसजोइसंताणं ।
संखातीदसहस्सा उक्कस्सोहीण विसओ दु ॥४२७॥

असुराणामसंख्येया कोटयः शेषज्योतिष्कांतानां । संख्यातीतसहस्रमुत्कृष्टावधीनां विषयस्तु ॥

असुररुगळिगुत्कृष्टक्षेत्रमसंख्यातकोटियोजनमक्कुं । शेषनवविधभावनदेवर्क्कळं व्यंतरज्योतिष्कदेवर्कळुमसंख्यातसहस्रमुत्कृष्टावधिज्ञानविषयमक्कुं ।

असुराणमसंखेज्जा वरिसा पुण सेसजोइसंताणं ।
तस्संखेज्जदिभागं कालेण य होदि णियमेण ॥४२८॥

असुराणामसंख्येयानि वर्षाणि पुनः शेषज्योतिष्कांतानां । तत्संख्येयभागः कालेन च भवति नियमेन ॥

असुरकुलद भवनामररिगुत्कृष्टकालमसंख्येयवर्षंगळप्पुवु । तु मत्ते शेषनवविधभावनदेवर्क्कळं व्यंतरज्योतिष्कदेवर्क्कळ्गं असुरकुलसंभूतर्गे पेळ्दकालमं नोडलु संख्यातैकभागमक्कुमुत्कृष्टकालं । व a ।
१

भवणतियाणमधोधो थोवं तिरिएण होदि बहुगं तु ।
उड्ढेण भवणवासी सुरगिरिसिहरोत्ति पस्संति ॥४२९॥

भवनत्रयाणामधोधः स्तोकं तिर्य्यग्बहुकं भवति तु ऊर्ध्वतो भवनवासिनः सुरगिरिशिखरपर्य्यंतं पश्यंति ॥

भवनत्रयामरर्गेल्लं केळगे केळगे अवधिविषयक्षेत्रं स्तोकस्तोकमक्कुं । तिर्य्यक्कागि बहुक्षेत्रं विषयमक्कुं । तु मत्ते भवनवासिदेवर्क्कळु तम्मिर्द्देडेयिंदवि मेगे सुरगिरिशिखरपर्य्यंतम-

---

असुराणां उत्कृष्टविषयक्षेत्रं असंख्यातकोटियोजनमात्रम् । शेषनवविधभावनव्यन्तरज्योतिष्काणां च असंख्यातसहस्रयोजनानि ॥४२७॥

असुरकुलस्योत्कृष्टकालः असंख्येयवर्षाणि पुनः शेषनवविधभावनव्यन्तरज्योतिष्काणां तस्य संख्यातैकभागः व a ॥४२८॥
१

भवनत्रयामराणामधोधोऽवधिविषयक्षेत्रं स्तोकं भवति । तिर्यग्रूपेण बहुकं भवति । तु—पुनः, भवनवासिनः

असुरकुमार जातिके भवनवासी देवोंके अवधिज्ञानका उत्कृष्ट विषयक्षेत्र असंख्यात कोटि योजन प्रमाण है। शेष नौ प्रकारके भवनवासी, व्यन्तर और ज्योतिषीदेवोंके असंख्यात हजार योजन है ॥४२७॥

असुरकुमारोंका उत्कृष्ट काल असंख्यात वर्ष है। शेष नौ प्रकारके भवनवासी व्यन्तर और ज्योतिषी देवोंके उत्कृष्ट अवधिज्ञानका काल उक्त कालके संख्यातवें भाग है ॥४२८॥

भवनवासी, व्यन्तरों और ज्योतिषी देवोंके नीचेकी ओर अवधिज्ञानका विषयक्षेत्र थोड़ा है किन्तु तिर्यक् रूपसे बहुत है। भवनवासी अपने निवासस्थानसे ऊपर मेरुपर्वतके

वधिदर्शनदिदं काण्बरं ।

जघन्य	जघन्य	उ	उ
भवनव्यंतर	जोयिसि	असुर	भ ९ । ७ं । जो
यो २९	२५३	को ७	१००० । ७
दि १	बहुकाल	व ७	व ७ १

सक्कीसाणा पढमं बिदियं तु सणक्कुमारमाहिंदा ।
तदियं तु बम्ह लांतव सुक्कसहस्सारया तुरियं ॥४३०॥

शक्रेशानौ प्रथमां द्वितीयां तु सनत्कुमारमाहेंद्रौ । तृतीयां तु ब्रह्मलांतवौ शुक्रसहस्रारजौ तुर्य्यां ॥

सौधर्म्मैशानकल्पजरुगळु प्रथमपृथ्वीपर्य्यंतं काण्बरु । सनत्कुमारमाहेंद्रकल्पसंभूतरु तु मत्ते द्वितीयपृथ्वीपर्य्यंतं काण्बरु । ब्रह्मलांतवकल्पजरु तृतीयपृथ्वीपर्य्यंतं काण्बरु । शुक्रशतारकल्पजरु चतुर्त्थपृथ्वीपर्य्यंतं काण्बरु ।

आणदपाणदवासी आरण तह अच्चुदा य पस्संति ।
पंचमखिदिपेरंतं छट्ठिं गेवेज्जगा देवा ॥४३१॥

आनतप्राणतवासिनः आरणास्तथाऽच्युताश्च पश्यंति पंचमक्षितिपर्य्यंतं षष्ठिं ग्रैवेयका देवाः ।

आनतप्राणतवासिगळु आरणाच्युतकल्पजरुमंते पंचमक्षितिपर्य्यंतं काण्बरु । नवग्रैवेयकज[illegible] मिंद्ररु षष्ठपृथ्वीपर्यंतं काण्बरु ।

सव्वं च लोयनालिं पस्संति अणुत्तरेसु जे देवा ।
सक्खेत्ते य सकम्मे रूवगदमणंतभागं च ॥४३२॥

सर्वां च लोकनाडीं पश्यंत्यनुत्तरेषु ये देवाः । स्वक्षेत्रे स्वकर्म्मणि रूपगतमनंतभागं ।

स्वकीयावस्थितस्थानादुपरि सुरगिरिशिखरपर्यन्तं अवधिदर्शनेन पश्यन्ति ॥४२९॥

सौधर्मैशानजाः प्रथमपृथ्वीपर्यन्तं पश्यन्ति । सनत्कुमारमाहेन्द्रजाः पुनर्द्वितीयपृथ्वीपर्यन्तं ब्रह्मलान्तवजास्तृतीयपृथ्वीपर्यन्तं पश्यन्ति । शुक्रशतारजाः चतुर्थपृथ्वीपर्यन्तं पश्यन्ति ॥४३०॥

आनतप्राणतवासिनः तथा आरणाच्युतवासिनश्च पञ्चमपृथ्वीपर्यन्तं पश्यन्ति, नवग्रै[illegible] षष्ठपृथ्वीपर्यन्तं पश्यन्ति ॥४३१॥

शिखरपर्यन्त अवधिदर्शनके द्वारा देखते हैं ॥४२९॥

सौधर्म और ऐशान स्वर्गके देव अवधि[illegible]

कप्पसुराणं सगसग ओहीखेत्तं विविस्ससोवचयं ।
ओहीदव्वपमाणं संठाविय धुवहारेण हरे ॥४३३॥
सगसगखेत्तपदेससलायपमाणं समप्पदे जाव ।
तत्थतणचरिमखंडं तत्थतणोहिस्स दव्वं तु ॥४३४॥

कल्पसुराणां स्वकस्वकावधिक्षेत्रं विविस्रसोपचय—मवधिद्रव्यप्रमाणं संस्थाप्य ध्रुवहारेण हरेत् ॥

स्वस्वक्षेत्रप्रदेशशलाकाप्रमाणं समाप्यते यावत् । तत्रतनचरमखंडं तत्रतनावधेर्द्रव्यं तु ।

कल्पजरप्प देवर्क्कळ स्वस्वावधिक्षेत्रमुमं विगतविस्रसोपचयावधिज्ञानावरणद्रव्यमुमं स्थापिसि—

≡१०२२	≡८०२२	≡११	≡६	≡१५	≡१८	≡१९	≡१०	≡११	≡१३	≡१४-
१४३१२	३४३१	३४३७	३४३	३४३१२	३४३१	३४३१२	३४३	३४३	३४३	३४३
स०१२	स०१-२	स०१-२	स०१-२	स०१-२	स०१-२	स०१-२	स०१-२	स०१-२	स०१-२	स०१-२
७१४	७१४	७१४	७१४	७१४	७१४	७१४	७१४	७१४	७१४	७१४
द्रव्य	द्रव्य									

अमुमेवार्थं विवृणोति—

कल्पवासिनां स्वस्वावधिक्षेत्रं विगतविस्रसोपचयावधिज्ञानावरणद्रव्यं च संस्थाप्य—

≡१	≡८	≡११	≡६	≡१५	≡८	≡१९	≡१०	≡११	≡१३	≡१४-
१४३१२	३४३१	३४३१२	३४३१	३४३१२	३४३१	३४३१२	३४३	३४३१	३४३	३४३
स०१२-	स०१२-	स०१२-	स०१२-	स०१२-	स०१२-	स०१२-	स०१२-	स०१२-	स०१२-	स०१२-
७१४	७१४	७१४	७१४	७१४	७१४	७१४	७१४	७१४	७१४	७१४

इसी बातको आगे स्पष्ट करते हैं—

कल्पवासी देवोंके अपने-अपने अवधिज्ञानके क्षेत्रको और अपने-अपने विस्रसोपचय-रहित अवधिज्ञानावरण द्रव्यको स्थापित करके क्षेत्रमें से एक प्रदेश कम करना और द्रव्यमें एक बार ध्रुवहारका भाग देना। ऐसा तबतक करना चाहिए जबतक अपने-अपने अवधिक्षेत्रके प्रदेशोंकी शलाकाओंका परिमाण समाप्त हो। ऐसा करनेसे जो अवधिज्ञानावरण कर्मद्रव्यका अन्तिम खण्ड शेष रहता है उतना ही उस अवधिज्ञानके विषयभूत द्रव्यका परिमाण होता है।

विशेषार्थ—जैसे सौधर्म ऐशान स्वर्गवालोंका क्षेत्र प्रथम नरक पृथ्वीपर्यन्त कहा है। सो मध्यलोकसे पहला दूसरा स्वर्ग डेढ़ राजू ऊंचा है। अतः अवधिज्ञानका क्षेत्र उनका एक राजू लम्बा-चौड़ा और डेढ़ राजू ऊंचा हुआ। इस घनरूप डेढ़ राजू क्षेत्रके जितने प्रदेश हों उतने एक जगह स्थापित करें। और जिस देवका जानना हो उस देवके अवधिज्ञानावरण कर्मद्रव्यको एक जगह स्थापित करें। इसमें विस्रसोपचयके परमाणु नहीं लेना। इस अवधिज्ञानावरण कर्मद्रव्यके परमाणुओंमें एक बार ध्रुवहारका भाग दें और क्षेत्रमें से एक कम करें। भाग देनेसे जो प्रमाण आया उसमें दुबारा ध्रुवहारका भाग दें

जोइसियंताणोही खेत्ता उत्ता ण होंति घणपदरा ।
कप्पसुराणं च पुणो विसरित्थं आयदं होदि ॥४३७॥

ज्योतिष्कांतानामवधिक्षेत्राण्युक्तानि न भवंति घनप्रतराणि । कल्पसुराणां च पुनर्विसदृशमायतं भवति ॥

ज्योतिषिकांतानामुक्तान्यवधिक्षेत्राणि भावनव्यंतरज्योतिष्करिगेल्लगं पेरगे पेळल्पट्टवधिविषयक्षेत्रंगळु समचतुरस्र घनक्षेत्रंगळल्तु एकेंदोडे अवर्गळवधिविषयक्षेत्रंगळ्गे सूत्रदोळु विसदृसत्वकथनमुंटप्पुदरिं । इदरिं पारिशेष्यदिं तद्योग्यस्थानदोळु नारकतिर्य्यंचरुगळवधिविषयक्षेत्रमे समघनक्षेत्रमें बुदत्थं । कल्पामरर्गेल्लं पुनः मत्ते तंतम्मवधिज्ञानविषयक्षेत्रं विसदृशमायतमक्कुं । आयतचतुरस्रक्षेत्रमें बुदत्थंमवधिज्ञानं समाप्तमाप्तु ।

चिंतियमचिंतियं वा अद्धं चिंतियमणेयभेयगयं ।
मणपज्जवं ति उच्चइ जं जाणइ तं खु णरलोए ॥४३८॥

चिंतितमचिंतितं वा अर्द्धं चिंतितमनेकभेदगतं । मनःपर्य्ययं इत्युच्यते यत् जानाति तत्खलु नरलोके ।

चिंतितं पेरदिदं चिंतिसल्पट्टुदं । अचिंतितं वा मुंदे चिंतिसल्पडुवुदं । मेणु अर्द्धचिंतितं चिंताविषयमं संपूर्णमागि चिंतिसदे अर्द्धं चिंतिसल्पडुत्तुमं । अनेकभेदगतं इंतनेकप्रकारदिंदं पेरर मनदोळिद्दुदं यत् आवुदोंदु ज्ञानं जानाति अरिगुमा ज्ञानं खलु स्फुटमागि मनःपर्य्ययज्ञानमें बुदु

जानां यथायोग्यं पल्यासंख्यातभागः प तत उपरि लान्तवादिसर्वार्थसिद्धपर्यन्तानां यथायोग्यं किंचिदूनपल्यं
a

प-॥४३५-४३६॥

ज्योतिष्कान्तत्रिविधदेवानां उक्तावधिविषयक्षेत्राणि समचतुरस्रघनरूपाणि न भवन्ति, सूत्रे तेषां विसदृशत्वकथनात् । अनेन पारिशेष्यात् तद्योग्यस्थाने नरनारकतिर्यगवधिविषयक्षेत्रमेव समघनमित्यर्थः । कल्पामराणां पुनर्विसदृशमायातं आयतचतुरस्रमित्यर्थः ॥४३७॥

चिन्तितं—चिन्ताविषयीकृतं, अचिन्तितं—चिन्तयिष्यमाणं, अर्धचिन्तितं—असंपूर्णचिन्तितं वा इत्यनेकभेदगतं अर्थं परमनस्यवस्थितं यज्ज्ञानं जानाति तत् खलु मनःपर्यय इत्युच्यते । तस्योत्पत्तिप्रवृत्ती नरलोके

देवोंके अवधिज्ञानका विषयभूत काल यथायोग्य पल्यके असंख्यातवें भाग है। उनसे ऊपर लान्तव स्वर्गसे लेकर सर्वार्थसिद्धिपर्यन्त देवोंके यथायोग्य कुछ कम पल्य प्रमाण है ॥४३५-४३६॥

ज्योतिषी देव पर्यन्त तीन प्रकारके देवोंके अर्थात् भवनवासी व्यन्तर और ज्योतिष्क देवोंके जो अवधिज्ञानका विषयभूत क्षेत्र कहा है वह समचतुरस्र अर्थात् बराबर चौकोर घनरूप नहीं है क्योंकि आगममें उसकी लम्बाई चौड़ाई ऊँचाई बराबर एक समान नहीं कही है। इससे शेष रहे जो मनुष्य नारक, तिर्यंच उनके अवधिज्ञानका विषयभूत क्षेत्र समान चौकोर घनरूप है यह अर्थ निकलता है। कल्पवासी देवोंके अवधिज्ञानका विषयक्षेत्र विसदृश आयत है अर्थात् लम्बा बहुत और चौड़ा कम है ॥४३७॥

॥ अवधिज्ञान प्ररूपणा समाप्त ॥

चिन्तित—जिसका पूर्वमें चिन्तन किया था। अचिन्तित—जिसका आगामी कालमें चिन्तन करेगा, अर्धचिन्तित—जिसका पूर्णरूपसे चिन्तन नहीं किया, इत्यादि अनेक प्रकार-

दिवं त्रिविधमक्कुं ।

विउलमदीवि य छद्धा उजुगाणुजुवयणकायचित्तगयं ।
अत्थं जाणदि जम्हा सद्दत्थगया हु ताणत्था ॥४४०॥

विपुलमतिरपि च षड्धा ऋज्वनृजुवचनकायचित्तगतमर्थं जानाति यस्मात् शब्दार्थगताः खलु तयोरर्थाः ।

विपुलमतिमनःपर्य्ययमुं षट्प्रकारमप्पुदवें तें दोडे ऋजुमनोगतार्थविषयमनःपर्य्ययमें दुं ऋजुवचनगतार्थविषयमनःपर्य्ययमें दुं ऋजुकायगतार्थविषयमनःपर्य्ययमें दितु । अनृजुमनोगतार्थविषयमनःपर्य्ययमें दुं अनृजुवचनगतार्थविषयमनःपर्य्ययमें दुं अनृजुकायगतार्थविषयमनःपर्य्ययमें दितिल्लि । यस्मात् ऋज्वनृजुमनोवचनकायगतार्थविषयत्वात्कारणात् । तयोरर्थाः आवुदों दु ऋज्वनृजुमनोवचनकायगतार्थविषयत्वकारणवत्तणिवमा ऋजुविपुलमतिमनःपर्य्ययंगळ अर्थाः विषयंगळु शब्दगतार्थंगळें दुं खलु स्फुटमागि द्विप्रकारंगळप्पुवु । अदें तें दोडे ऋजुमतिमनःपर्य्ययज्ञानं पोर्थ्दे ऋजुमनदिवं निर्व्वर्त्तितमागि निष्पन्नमागि त्रिकालविषयंगळप्प पदार्त्थंगळं चिंतितिदं । ऋजुवचनदिवं निष्पन्नमागि त्रिकालविषयंगळप्पर्त्थंगळं नुडिदं । ऋजुभूतकायदिवं निष्पन्नमागि त्रिकालविषयार्त्थंगळं कायव्यापारदिवं माडिदनवंमरेदु । कालांतरदिवं नेनेयलारदे बंदु बेसगों डोडे बेसगोळदिद्दोडमरिगुं एंदितु शब्दगतार्थंगळुमर्थगतार्थंगळु में दु द्विप्रकारंगळप्पुवु । विपुलमतिमनःपर्य्ययदक्कमिते ऋज्वनृजुमनोवचनकायंगळिंदं निर्व्वर्त्तितमागि निष्पन्नमागि त्रिकालविषयपदार्थंगळं चिंतिसिदुवं नुडिदुवं माडिदुवं मरेदु कालांतरदिवं नेनेयलारदे बंदु बेसगों-

---

दिविध: ॥४३९॥

विपुलमतिमनःपर्ययोऽपि यस्मात् ऋज्वनृजुमनोवचनकायगतार्थं जानाति तस्मात्कारणात् ऋजुमनोगतार्थविषयः ऋजुवचनगतार्थविषयः ऋजुकायगतार्थविषयः अनृजुमनोगतार्थविषयः अनृजुवचनगतार्थविषयः अनृजुकायगतार्थविषयश्चेति षोढा । तयोः ऋजुविपुलमतिमनःपर्यययोः अर्थाः—विषयाः शब्दगता अर्थगताश्च स्फुटं भवन्ति । तद्यथा—कश्चिज्जीवः ऋजुमनसा निर्वर्तितः—निष्पन्नः त्रिकालविषयपदार्थान् चिन्तितवान् ऋजुवचनेन निर्वर्तितस्तानुक्तवान् ऋजुकायेन निष्पन्नस्तान् कृतवान्, विस्मृत्य कालान्तरेण स्मर्तुमशक्तः, आगत्य पृच्छति वा तूष्णीं तिष्ठति तदा ऋजुमतिमनःपर्ययज्ञानं जानाति । तथा ऋज्वनृजुमनोवचनकायैर्निर्वर्तितः

अर्थको जाननेवाला, सरल वचनके द्वारा कहे गये मनोगत अर्थको जाननेवाला और सरलकायसे किये गये मनोगत अर्थको जाननेवाला ॥४३९॥

विपुलमति मनःपर्यय छह प्रकारका है—क्योंकि वह सरल और कुटिल मन-वचन-कायसे किये गये मनोगत अर्थको जानता है। अतः ऋजु मनोगत अर्थको विषय करनेवाला, ऋजु वचनगत अर्थको विषय करनेवाला, ऋजुकायगत अर्थको विषय करनेवाला तथा कुटिल मनोगत अर्थको विषय करनेवाला, कुटिल वचनगत अर्थको विषय करनेवाला, कुटिल कायगत अर्थको विषय करनेवाला इस तरह छह प्रकारका है। उन ऋजुमति और विपुलमति मनःपर्ययके विषय शब्दगत और अर्थगत होते हैं। यथा—किसी सरलमनसे निष्पन्न व्यक्तिने त्रिकालवर्ती पदार्थोंके विषयमें चिन्तन किया, सरल वचनसे निष्पन्न होते हुए उन पदार्थोंका कथन किया और सरलकायसे निष्पन्न होकर उनको किया। फिर भूल गया, कालान्तरमें उन्हें स्मरण नहीं कर सका। आ करके पूछता है अथवा चुप बैठता है। तब ऋजुमति मनःपर्ययज्ञान जान लेता है। तथा सरल या कुटिल मन-वचन-

अंगोपांगोदयात्कारणात् अंगोपांगनामकर्म्मोदयकारणदिंदं मनोवर्गणास्कंधंगळिदं विक-सिताष्टच्छदारविंददंते द्रव्यमनं हृदयदोळप्पुदु स्फुटमागि ।

णोइंदियत्ति सण्णा तस्स हवे सेसइंदियाणं वा ।
वत्तत्ताभावादो मण मणपज्जं च तत्थ हवे ॥४४४॥

नो इंद्रियमिति संज्ञा तस्य भवेत् शेषेंद्रियाणामिव व्यक्तत्वाभावात् मनो मनःपर्य्ययश्च तत्र भवेत् ॥

मनः आ द्रव्यमनं शेषेंद्रियाणामिव स्पर्शनादींद्रियंगळ्गे तु संस्थाननिर्द्देशंगळ्गे व्यक्तत्व-मुंटंते । तस्य आ द्रव्यमनक्के व्यक्तत्वाभावात् कर्णनासिकानयनादियत् व्यक्तत्वाभावदिंदं नोइंद्रिय-मिति संज्ञा भवेत् । ईषदिंद्रियं नोइंद्रियमेंदितन्वर्थसंज्ञेयुमक्कुं । तत्र आ द्रव्यमनदोळु मनः भावमनो-ज्ञानमुं मनःपर्य्ययश्च भवेत् मनःपर्य्ययज्ञानं पुट्टुगुं ।

मणपज्जवं च णाणं सत्तसु विरदेसु सत्तइड्ढीणं ।
एगादिजुदेसु हवे वड्ढंतविसिट्ठचरणेसु ॥४४५॥

मनःपर्य्ययज्ञानं सप्तसु विरतेषु सप्तर्द्धीनामेकादियुतेषु भवेत् वर्द्धमानविशिष्टाचरणेषु ॥

सप्तसु विरतेषु प्रमत्तसंयतादिक्षीणकषायांतमाद सप्तगुणस्थानवर्त्तिगळप्प विरतरोळु सप्तर्द्धीनामेकादियुतेषु बुद्धितपोवैकुर्व्वणौषधरसबलाक्षीणमेंब सप्तर्द्धिगळोळेक द्व्यादियुतरोळु वर्द्धमानविशिष्टाचरणेषु पेर्च्चुत्तिप्पं विशिष्टाचारमनुळ्ळ महामुनिगळोळु मनःपर्य्ययश्च ज्ञानं भवेत् मनःपर्य्ययज्ञानं पुट्टुवेंबुदु तात्पर्य्यं ।

इंदियणोइंदियजोगादि पेक्खित्तु उजुमदी होदि ।
णिरवेक्खिय विउलमदी ओहिं वा होदि णियमेण ॥४४६॥

इंद्रियनोइंद्रिययोगादीनपेक्ष्य तु ऋजुमतिर्भवति । निरपेक्ष्य च विपुलमतिरवधिवद्भवति नियमेन ॥

अङ्गोपाङ्गनामकर्मोदयकारणात् मनोवर्गणास्कन्धैर्विकसिताष्टच्छदारविन्दसदृशं द्रव्यमनो हृदये उत्पद्यते स्फुटम् ॥४४३॥

तस्य द्रव्यमनसः शेषस्पर्शनादीन्द्रियाणामिव स्थाननिर्देशाभ्यां व्यक्तत्वाभावात् ईषदिन्द्रियत्वेन नोइन्द्रियमित्यन्वर्थनाम भवेत् । तत्र द्रव्यमनसि भावमनो मनःपर्ययश्चोत्पद्यते ॥४४४॥

प्रमत्तादिसप्तगुणस्थानेषु बुद्धितपोविकुर्वाणौषधरसबलाक्षीणनामसप्तर्धिमध्ये एकद्व्यादियुतेष्वेव वर्धमानविशिष्टाचरणेषु मनःपर्ययज्ञानं भवति, नान्यत्र ॥४४५॥

अंगोपांग नामकर्मके उदयसे मनोवर्गणारूप स्कन्धोंके द्वारा हृदयस्थानमें मनकी उत्पत्ति होती है। वह खिले हुए आठ पाँखुड़ीके कमलके समान होता है ॥४४३॥

उस द्रव्यमनका नो इन्द्रिय नाम सार्थक है क्योंकि जैसे स्पर्शन आदि इन्द्रियोंका स्थान और विषय प्रकट है वैसा मनका नहीं है। इसलिए ईषत् अर्थात् किंचित् इन्द्रिय होनेसे उसका नाम नोइन्द्रिय है। उस द्रव्यमनमें भावमन और मनःपर्ययज्ञान उत्पन्न होते हैं ॥४४४॥

प्रमत्तसंयतसे क्षीणकषाय पर्यन्त सात गुणस्थानोंमें, बुद्धि-तप-विक्रिया-औषध-रस-बल और अक्षीण नामक सात ऋद्धियोंमें-से एक-दो-तीन आदि ऋद्धियोंके धारी तथा जिनका विशिष्ट चारित्र वर्धमान होता है उन महामुनियोंमें ही मनःपर्ययज्ञान होता है, अन्यत्र नहीं ॥४४५॥

पेरर मनदोळिर्द्दर्त्थमं ऋजुस्थितं ऋजु यथा भवति तथा स्थितं इहामदिणा ईहामतिज्ञानदिदं मुन्नं लब्ध्वा पडेदु पश्चात् बळिकं ऋजुमतिना ऋजुमतिमनःपर्य्ययज्ञानदिदं प्रत्यक्षेण च प्रत्यक्षमागि मनःपर्य्ययज्ञानी जानीते अरिगुं नियमात् नियमदिदं ।

चिंतियमचिंतियं वा अद्धं चिंतियमणेयभेयगयं ।
ओहिं वा विउलमदी लहिऊण विजाणए पच्छा ॥४४९॥

चिंतितमचिंतितं वा अर्द्धचिंतितमनेकभेदगतं । अवधिवद्विपुलमतिर्लब्ध्वा विजानाति पश्चात् ॥

चिंतितमुमचिंतितमुमं मेणर्द्धचिंतितमुमनितनेकभेदवोळिर्द्द परकीयमनोगतार्त्थमं मुन्नं पडदु बळिकं विपुलमतिमनःपर्य्ययज्ञानमवधिज्ञानमंतंत प्रत्यक्षमागरिगुं ।

दव्वं खेत्तं कालं भावं पडि जीवलक्खियं रूविं ।
उजुविउलमदी जाणदि अवरवरं मज्झिमं च तहा ॥४५०॥

द्रव्यं क्षेत्रं कालं भावं प्रति जीवलक्षितं रूपिणं । ऋजु-विपुलमती जानीतः अवरवरं मध्यमं च तथा ॥

द्रव्यं प्रति क्षेत्रं प्रति कालं प्रति भावं प्रति प्रत्येकं जीवलक्षितं जीवनिंद चिंतिसल्पट्टुदं रूपिणं पुद्गलं पुद्गलद्रव्यमं तत्संबंधिजीवद्रव्यमं । अवरवरं जघन्यमुमनुत्कृष्टमुमं । तथा अंते मध्यमं च मध्यममुमं ऋजुविपुलमतो ऋजुविपुलमतिमनःपर्य्ययंगळेरडुं जानीतःअरिववु ।

परस्य मनसि ऋजुतया स्थितमर्थं ईहामतिज्ञानेन पूर्वं लब्ध्वा पश्चात् ऋजुमतिज्ञानेन प्रत्यक्षतया मनःपर्ययज्ञानी जानीते नियमात् ॥४४८॥

चिन्तितं अचिन्तितं अथवा अर्धचिन्तितं इत्यनेकभेदगतं परमनोगतार्थं पूर्वं लब्ध्वा पश्चाद्विपुलमतिमनःपर्ययः अवधिरिव प्रत्यक्षं जानाति ॥४४९॥

द्रव्यं प्रति क्षेत्रं प्रति कालं प्रति भावं प्रति प्रत्येकं जीवलक्षितं—जीवचिन्तितं, रूपि—पुद्गलद्रव्यं तत्संबन्धिजीवद्रव्यं च जघन्यं उत्कृष्टं तथा मध्यमं च ऋजुविपुलमतिमनःपर्ययौ जानीतः ॥४५०॥

आत्माकी निर्मलता रूप विशुद्धिसे उत्पन्न होता है। किन्तु विपुलमतिमनःपर्यय अतिशय विशुद्ध होता है ॥४४७॥

दूसरेके मनमें सरलता रूपसे विचार किया गया जो अर्थ स्थित है उसे पहले ईहामतिज्ञानके द्वारा प्राप्त करके पीछे ऋजुमतिज्ञानसे मनःपर्ययज्ञानी नियमसे प्रत्यक्ष जानता है ॥४४८॥

चिन्तित, अचिन्तित, अथवा अर्धचिन्तित इत्यादि अनेक भेद रूप दूसरेके मनोगत अर्थको पहले प्राप्त करके पीछे विपुल मति मनःपर्यय अवधिज्ञानकी तरह प्रत्यक्ष जानता है ॥४४९॥

द्रव्य, क्षेत्र, काल, भावको लेकर जीवके द्वारा चिन्तित पुद्गल द्रव्य और उससे सम्बद्ध जीवद्रव्यको जघन्य मध्यम उत्कृष्ट भेदको लिए हुए ऋजुमति और विपुलमति मनःपर्यय जानते हैं ॥४५०॥

पेरर मनदोळिर्द्दर्त्थमं ऋजुस्थितं ऋजु यथा भवति तथा स्थितं इहामदिणा ईहामतिज्ञानदिदं मुन्नं लब्ध्वा पडेदु पश्चात् बळिकं ऋजुमतिना ऋजुमतिमनःपर्य्ययज्ञानदिदं प्रत्यक्षेण च प्रत्यक्षमागि मनःपर्य्ययज्ञानी जानीते अरिगुं नियमात् नियमदिदं ।

चिंतियमचिंतियं वा अद्धं चिंतियमणेयमेयगयं ।
ओहिं वा विउलमदी लहिऊण विजाणए पच्छा ॥४४९॥

चिंतितमचिंतितं वा अर्द्धचिंतितमनेकभेदगतं । अवधिवद्विपुलमतिर्लब्ध्वा विजानाति पश्चात् ॥

चिंतितमुमचिंतितमुमं मेणर्द्धचिंतितमुमन्तितनेकभेददोळिर्द्द परकीयमनोगतार्त्थमं मुन्नं पडेदु बळिक विपुलमतिमनःपर्य्ययज्ञानमवधिज्ञानमेंतंत प्रत्यक्षमागरिगुं ।

दव्वं खेत्तं कालं भावं पडि जीवलक्खियं रूविं ।
उजुविउलमदी जाणदि अवरवरं मज्झिमं च तहा ॥४५०॥

द्रव्यं क्षेत्रं कालं भावं प्रति जीवलक्षितं रूपिणं । ऋजु-विपुलमती जानीतः अवरवरं मध्यमं च तथा ॥

द्रव्यं प्रति क्षेत्रं प्रति कालं प्रति भावं प्रति प्रत्येकं जीवलक्षितं जीवनिदं चिंतिसल्पट्टुदं रूपिणं पुद्गलं पुद्गलद्रव्यमं तत्संबंधिजीवद्रव्यमं । अवरवरं जघन्यमुमनुत्कृष्टमुमं । तथा अंते मध्यमं च मध्यममुमं ऋजुविपुलमती ऋजुविपुलमतिमनःपर्य्ययंगळेरडुं जानीतःअरिवुवु ।

परस्य मनसि ऋजुतया स्थितमर्थं ईहामतिज्ञानेन पूर्वं लब्ध्वा पश्चात् ऋजुमतिज्ञानेन प्रत्यक्षतया मनःपर्ययज्ञानी जानीते नियमात् ॥४४८॥

चिन्तितं अचिन्तितं अथवा अर्धचिन्तितं इत्यनेकभेदगतं परमनोगतार्थं पूर्वं लब्ध्वा पश्चाद्विपुलमतिमनःपर्ययः अवधिरिव प्रत्यक्षं जानाति ॥४४९॥

द्रव्यं प्रति क्षेत्रं प्रति कालं प्रति भावं प्रति प्रत्येकं जीवलक्षितं–जीवचिन्तितं, रूपि–पुद्गलद्रव्यं तत्संबन्धिजीवद्रव्यं च जघन्यं उत्कृष्टं तथा मध्यमं च ऋजुविपुलमतिमनःपर्ययौ जानीतः ॥४५०॥

आत्माकी निर्मलता रूप विशुद्धिसे उत्पन्न होता है। किन्तु विपुलमतिमनःपर्यय अतिशय विशुद्ध होता है ॥४४७॥

दूसरेके मनमें सरलता रूपसे विचार किया गया जो अर्थ स्थित है उसे पहले ईहामतिज्ञानके द्वारा प्राप्त करके पीछे ऋजुमतिज्ञानसे मनःपर्ययज्ञानी नियमसे प्रत्यक्ष जानता है ॥४४८॥

चिन्तित, अचिन्तित, अथवा अर्धचिन्तित इत्यादि अनेक भेद रूप दूसरेके मनोगत अर्थको पहले प्राप्त करके पीछे विपुल मति मनःपर्यय अवधिज्ञानकी तरह प्रत्यक्ष जानता है ॥४४९॥

द्रव्य, क्षेत्र, काल, भावको लेकर जीवके द्वारा चिन्तित पुद्गल द्रव्य और उससे सम्बद्ध जीवद्रव्यको जघन्य मध्यम उत्कृष्ट भेदको लिए हुए ऋजुमति और विपुलमति मनःपर्यय जानते हैं ॥४५०॥

पेरर मनदोळिर्द्दर्थमं ऋजुस्थितं ऋजु यथा भवति तथा स्थितं इहामदिणा ईहामतिज्ञान-दिदं मुन्नं लब्ध्वा पडेदु पश्चात् बळिकं ऋजुमतिना ऋजुमतिमनःपर्य्ययज्ञानदिदं प्रत्यक्षेण च प्रत्यक्षमागि मनःपर्य्ययज्ञानी जानीते अरिगुं नियमात् नियमदिदं।

चिंतियमचिंतियं वा अद्धं चिंतियमणेयमेयगयं।
ओहिं वा विउलमदी लहिऊण विजाणए पच्छा ॥४४९॥

चिंतितमचिंतितं वा अर्द्धचिंतितमनेकभेदगतं। अवधिवद्विपुलमतिर्लब्ध्वा विजानाति पश्चात्॥

चिंतितमुमचिंतितमुमं भेगर्द्धचिंतितमुमेंतितनेकभेदवोळिर्द्द परकीयमनोगतार्थमं मुन्नं पडदु बळिकं विपुलमतिमनःपर्य्ययज्ञानमवधिज्ञानमंतंत प्रत्यक्षमागरिगुं।

दव्वं खेत्तं कालं भावं पडि जीवलक्खियं रूविं।
उजुविउलमदी जाणदि अवरवरं मज्झिमं च तहा ॥४५०॥

द्रव्यं क्षेत्रं कालं भावं प्रति जीवलक्षितं रूपिणं। ऋजु-विपुलमती जानीतः अवरवरं मध्यमं च तथा॥

द्रव्यं प्रति क्षेत्रं प्रति कालं प्रति भावं प्रति प्रत्येकं जीवलक्षितं जीवनिदं चिंतितरूपद्दुदं रूपियं पुद्गलं पुद्गलद्रव्यमं तत्संबंधिजीवद्रव्यमं। अवरवरं जघन्यमुमनुत्कृष्टमुमं। तथा अंते मध्यमं च मध्यममुमं ऋजुविपुलमतो ऋजुविपुलमतिमनःपर्य्ययंगळेरडुं जानीतःअरिवुवु।

परस्य मनसि ऋजुतया स्थितमर्थं ईहामतिज्ञानेन पूर्वं लब्ध्वा पश्चात् ऋजुमतिज्ञानेन प्रत्यक्षतया मनःपर्ययज्ञानी जानीते नियमात् ॥४४८॥

चिन्तितं अचिन्तितं अथवा अर्धचिन्तितं इत्यनेकभेदगतं परमनोगतार्थं पूर्वं लब्ध्वा पश्चाद्विपुलमतिमनःपर्ययः अवधिरिव प्रत्यक्षं जानाति ॥४४९॥

द्रव्यं प्रति क्षेत्रं प्रति कालं प्रति भावं प्रति प्रत्येकं जीवलक्षितं–जीवचिन्तितं, रूपि–पुद्गलद्रव्यं तत्संबन्धिजीवद्रव्यं च अवरं उत्कृष्टं तथा मध्यमं च ऋजुविपुलमतिमनःपर्ययौ जानीतः ॥४५०॥

भावनाकी विशेषता रूप विशुद्धिसे उत्पन्न होता है। किन्तु विपुलमतिमनःपर्यय अतिशय विशुद्ध होता है ॥४४७॥

दूसरेके मनमें सरलता रूपसे विचार किया गया जो अर्थ स्थित है उसे पहले ईहामतिज्ञानके द्वारा ग्रहण करके पीछे ऋजुमतिज्ञानसे मनःपर्ययज्ञानी नियमसे प्रत्यक्ष जानता है ॥४४८॥

चिन्तित, अचिन्तित, अथवा अर्धचिन्तित इत्यादि अनेक भेद रूप दूसरेके मनोगत अर्थको पहले ग्रहण करके पीछे विपुलमति मनःपर्यय अवधिज्ञानकी तरह प्रत्यक्ष जानता है ॥४४९॥

द्रव्य, क्षेत्र, काल, भावको लेकर जीवके द्वारा चिन्तित पुद्गल द्रव्य और उससे सम्बद्ध जीव द्रव्यको जघन्य मध्यम उत्कृष्ट भेदको लिए हुए ऋजुमति और विपुलमति मनःपर्यय जानते हैं ॥४५०॥

पेरर मनवोळिर्दुदर्थमं ऋजुस्थितं ऋजु यथा भवति तथा स्थितं ईहामदिणा ईहामतिज्ञानदिदं मुन्नं लब्ध्वा पडेदु पश्चात् बळिकं ऋजुमदिणा ऋजुमतिमनःपर्य्ययज्ञानदिदं प्रत्यक्षेण च प्रत्यक्षमागि मनःपर्य्ययज्ञानी जानीते अरिगुं नियमात् नियमदिदं ।

चिंतियमचिंतियं वा अद्धं चिंतियमणेयभेयगयं ।
ओहिं वा विउलमदी लहिऊण विजाणए पच्छा ॥४४९॥

चिंतितमचिंतितं वा अर्द्धचिंतितमनेकभेदगतं । अवधिवद्विपुलमतिर्लब्ध्वा विजानाति पश्चात् ॥

चिंतितमुमचिंतितमुमं मेणर्द्धचिंतितमुमनितनेकभेदवोळिर्द्दं परकीयमनोगतार्थमं मुन्नं पडेदु बळिक्कं विपुलमतिमनःपर्य्ययज्ञानमवधिज्ञानमें तंते प्रत्यक्षमागरिगुं ।

दव्वं खेत्तं कालं भावं पडि जीवलक्खियं रूविं ।
उजुविउलमदी जाणदि अवरवरं मज्झिमं च तहा ॥४५०॥

द्रव्यं क्षेत्रं कालं भावं प्रति जीवलक्षितं रूपिणं । ऋजु-विपुलमती जानीतः अवरवरं मध्यमं च तथा ॥

द्रव्यं प्रति क्षेत्रं प्रति कालं प्रति भावं प्रति प्रत्येकं जीवलक्षितं जीवनिदं चिंतितरूपद्दुदं रूपिणं पुद्गलं पुद्गलद्रव्यमं तत्संबंधिजीवद्रव्यमं । अवरवरं जघन्यमुमनुत्कृष्टमुमं । तथा अंते मध्यमं च मध्यममुमं ऋजुविपुलमती ऋजुविपुलमतिमनःपर्य्ययंगळेरडुं जानीतःअरिवुवु ।

परके मनमें ऋजुरूपसे स्थित अर्थको ईहामतिज्ञानेन पूर्वं लब्ध्वा पश्चात् ऋजुमतिज्ञानेन प्रत्यक्षतया मनःपर्ययज्ञानी जानीते नियमात् ॥४४८॥

चिन्तित अचिन्तित अथवा अर्धचिन्तितं इत्यनेकभेदगतं परमनोगतार्थं पूर्वं लब्ध्वा पश्चाद्विपुलमतिमनःपर्ययः अवधिरिव प्रत्यक्षं जानाति ॥४४९॥

द्रव्यं प्रति क्षेत्रं प्रति कालं प्रति भावं प्रति प्रत्येकं जीवलक्षितं–जीवचिन्तितं, रूपि–पुद्गलद्रव्यं तत्सम्बन्धिजीवद्रव्यं च जघन्यं उत्कृष्टं तथा मध्यमं च ऋजुविपुलमतिमनःपर्ययौ जानीतः ॥४५०॥

ऋजुमतिकी निर्मलता कम विशुद्धिसे उत्पन्न होता है। किन्तु विपुलमतिमनःपर्यय अतिशय विशुद्ध होता है ॥४४७॥

दूसरेके मनमें सरलता रूपसे विचार किया गया जो अर्थ स्थित है उसे पहले ईहामतिज्ञानके द्वारा ग्रहण करके पीछे ऋजुमतिज्ञानसे मनःपर्ययज्ञानी नियमसे प्रत्यक्ष जानता है ॥४४८॥

चिन्तित, अचिन्तित, अथवा अर्धचिन्तित इत्यादि अनेक भेद रूप दूसरेके मनोगत अर्थको पहले ग्रहण करके पीछे विपुलमति मनःपर्यय अवधिज्ञानकी तरह प्रत्यक्ष जानता है ॥४४९॥

द्रव्य, क्षेत्र, काल, भावको लेकर जीवके द्वारा चिन्तित पुद्गल द्रव्य और उससे सम्बद्ध जीवद्रव्यको जघन्य मध्यम उत्कृष्ट भेदको लिए हुए ऋजुमति और विपुलमति मनःपर्यय जानते हैं ॥४५०॥

पेरर मनदोळिर्द्दर्त्थमं ऋजुस्थितं ऋजु यथा भवति तथा स्थितं ईहामदिणा ईहामतिज्ञानदिदं मुन्नं लब्ध्वा पडेदु पश्चात् बळिकं ऋजुमतिना ऋजुमतिमनःपर्य्ययज्ञानदिदं प्रत्यक्षेण च प्रत्यक्षमागि मनःपर्य्ययज्ञानी जानीते अरिगुं नियमात् नियमदिदं ।

चिंतियमचिंतियं वा अद्धं चिंतियमणेयभेयगयं ।
ओहिं वा विउलमदी लहिऊण विजाणए पच्छा ॥४४९॥

चिंतितमचिंतितं वा अर्धचिंतितमनेकभेदगतं । अवधिवद्विपुलमतिर्लब्ध्वा विजानाति पश्चात् ॥

चिंतितमुमचिंतितमुमं मेणर्द्धचिंतितमुमनितनेकभेदवोळिर्द्द परकीयमनोगतार्त्थमं मुन्नं पडेदु बळिक्कं विपुलमतिमनःपर्य्ययज्ञानमवधिज्ञानमें तंते प्रत्यक्षमागरिगुं ।

दव्वं खेत्तं कालं भावं पडि जीवलक्खियं रूविं ।
उजुविउलमदी जाणदि अवरवरं मज्झिमं च तहा ॥४५०॥

द्रव्यं क्षेत्रं कालं भावं प्रति जीवलक्षितं रूपिणं । ऋजु-विपुलमती जानीतः अवरवरं मध्यमं च तथा ॥

द्रव्यं प्रति क्षेत्रं प्रति कालं प्रति भावं प्रति प्रत्येकं जीवलक्षितं जीवनिदं चिंतितरूपद्दुदं रूपिनं पुद्गलं पुद्गलद्रव्यमं तत्संबंधिजीवद्रव्यमं । अवरवरं जघन्यमुमनुत्कृष्टमुमं । तथा मध्यमं च मध्यममुमं ऋजुविपुलमती ऋजुविपुलमतिमनःपर्य्ययंगळेरडुं जानीतःअरिवुवु ।

परकीय मनसि ऋजुतया स्थितमर्थं ईहामतिज्ञानेन पूर्वं लब्ध्वा पश्चात् ऋजुमतिज्ञानेन प्रत्यक्षतया मनःपर्ययज्ञानी जानाति नियमात् ॥४४८॥

चिन्तितं अचिन्तितं अथवा अर्धचिन्तितं इत्यनेकभेदगतं परमनोगतार्थं पूर्वं लब्ध्वा पश्चाद्विपुलमतिमनःपर्ययः अवधिरिव प्रत्यक्षं जानाति ॥४४९॥

द्रव्यं प्रति क्षेत्रं प्रति कालं प्रति भावं प्रति प्रत्येकं जीवलक्षितं–जीवचिन्तितं, रूपि–पुद्गलद्रव्यं जघन्यमनुत्कृष्टं च [illegible] उत्कृष्टं तथा मध्यमं च ऋजुविपुलमतिमनःपर्ययौ जानीतः ॥४५०॥

ऋजुमति निर्मलता रूप विशुद्धिसे उत्पन्न होता है। किन्तु विपुलमतिमनःपर्यय अतिशय विशुद्ध होता है ॥४४७॥

दूसरेके मनमें सरलता रूपसे विचार किया गया जो अर्थ स्थित है उसे पहले ईहामतिज्ञानके द्वारा ग्रहण करके पीछे ऋजुमतिज्ञानसे मनःपर्ययज्ञानी नियमसे प्रत्यक्ष जानता है ॥४४८॥

चिन्तित, अचिन्तित, अथवा अर्धचिन्तित इत्यादि अनेक भेद रूप दूसरेके मनोगत अर्थको पहले ग्रहण करके पीछे विपुलमति मनःपर्यय अवधिज्ञानकी तरह प्रत्यक्ष जानता है ॥४४९॥

द्रव्य, क्षेत्र, काल, भावको लेकर जीवके द्वारा चिन्तित पुद्गल द्रव्य और उसके जघन्य, मध्यम तथा उत्कृष्ट भेदको लिए हुए ऋजुमति और विपुलमति मनःपर्यय जानते हैं ॥४५०॥

मणदव्ववग्गणाणमणंतिमभागेण उजुगउक्कस्सं ।
खंडिदमेत्तं होदि हु विउलमदिस्सावरं दव्वं ॥४५२॥

मनोद्रव्यवर्गणानामनंतैकभागेन ऋजुमतेरुत्कृष्टं । खंडितमात्रं भवति खलु विपुलमतेरवरं द्रव्यं ॥

मनोद्रव्यवर्गणेगळनंतैकभागं ध्रुवहारप्रमाणमक्कु ज १ / ख ख मो ध्रुवहार भागिसिदं ऋजुमतिपर्य्ययज्ञानविषयोत्कृष्टद्रव्यमं खंडिसुत्तिरलावुदोंदेकखंडं तावन्मात्रं खलु स्फुटमागि विपुलमतिमनःपर्य्ययज्ञानविषयजघन्यद्रव्यमक्कुं स ० १६ ख ६ ९

६ । १ । ९ १ १ ९ ० ९
० ०

अट्ठण्हं कम्माणं समयपबद्धं विविस्ससोवचयं ।
धुवहारेणिगिवारं भजिदे विदियं हवे दव्वं ॥४५३॥

अष्टानां कर्म्मणां समयप्रबद्धो विविस्रसोपचयो । ध्रुवहारेणैकवारं भाजिते द्वितीयं भवेद्द्रव्यं।

ज्ञानावरणाद्यष्टविधकर्म्मसामान्यसमयप्रबद्धं विगतविस्रसोपचयमवेकवारं ध्रुवहारदिदं भागिसल्पडुतिरलेकखंडमात्रं विपुलमतिमनःपर्य्ययज्ञानविषयद्वितीयद्रव्यविकल्पमक्कुं स ०–ख ख / ९ ० ०

मनोद्रव्यवर्गणाविकल्पानामनन्तैकभागेन ध्रुवहारेण ज १ / ख ख ऋजुमतिविषयोत्कृष्टद्रव्ये खण्डिते यावन्मात्रं तत्स्फुटं विपुलमतिविषयजघन्यद्रव्यं भवति स ० १६ ख । ६ ९ / ० ॥४५२॥

६ १ ९ १ १ ९ । ९
० ०

अष्टकर्मसामान्यसमयप्रबद्धे विस्रसोपचये ध्रुवहारेण एकवारं भक्ते यदेकखण्डं तद्विपुलमतिविषयद्वितीयद्रव्यं भवति— स ० ० ० ख ख / ९ ॥४५३॥

मनोद्रव्य वर्गणाके विकल्पोंके अनन्तवें भागरूप ध्रुवहारसे ऋजुमतिके विषय उत्कृष्ट द्रव्यमें भाग देनेपर जो प्रमाण आता है उतना विपुलमतिके विषयभूत जघन्यद्रव्यका परिमाण होता है ॥४५२॥

आठों कर्मोंके विस्रसोपचय रहित सामान्य समय प्रबद्धमें ध्रुवहारसे एक बार भाग देनेपर जो एक खण्ड आता है वह विपुलमतिका विषय द्वितीयद्रव्य होता है ॥४५३॥

मणदव्ववग्गणाणमणंतिमभागेण उजुगउक्कस्सं ।
खंडिदमेत्तं होदि हु विउलमदिस्सावरं दव्वं ॥४५२॥

मनोद्रव्यवर्गणानामनंतैकभागेन ऋजुमतेरुत्कृष्टं । खंडितमात्रं भवति खलु विपुलमतेरवरं द्रव्यं ॥

मनोद्रव्यवर्गणेगळनंतैकभागं ध्रुवहारप्रमाणमक्कु ज १ / ख ख मी ध्रुवहार भागदिदं ऋजुमतिपर्य्ययज्ञानविषयोत्कृष्टद्रव्यमं खंडिसुत्तिरलावुदो देकखंडं तावन्मात्रं खलु स्फुटमागि विपुलमतिमनःपर्य्ययज्ञानविषयजघन्यद्रव्यमक्कुं स ० १६ ख ६ प

६ । १ । ५ १ १ प ० ९
० ०

अट्ठण्हं कम्माणं समयपबद्धं विविस्ससोवचयं ।
धुवहारेणिगिवारं भजिदे विदियं हवे दव्वं ॥४५३॥

अष्टानां कर्म्मणां समयप्रबद्धो विविस्रसोपचयो । ध्रुवहारेणैकवारं भाजिते द्वितीयं भवेद्द्रव्यं ।

ज्ञानावरणाद्यष्टविधकर्म्मसामान्यसमयप्रबद्धं विगतविस्रसोपचयमदेकवारं ध्रुवहारदिदं भागिसल्पडुतिरलेकखंडमात्रं विपुलमतिमनःपर्य्ययज्ञानविषयद्वितीयद्रव्यविकल्पमक्कुं स ० ० ख ख / ९ ० ०

मनोद्रव्यवर्गणाविकल्पानामनन्तैकभागेन ध्रुवहारेण ज १ / ख ख ऋजुमतिविषयोत्कृष्टद्रव्ये खण्डिते यावन्मात्रं तत्स्फुटं विपुलमतिविषयजघन्यद्रव्यं भवति स ० १६ ख । ६ प / ० ॥४५२॥

६ १ प १ १ प । ९
० ०

अष्टकर्मसामान्यसमयप्रबद्धे विविस्रसोपचये ध्रुवहारेण एकवारं भक्ते यदेकखण्डं तद्विपुलमतिविषयद्वितीयद्रव्यं भवति— स ० ० ० ख ख / ९ ॥४५३॥

मनोद्रव्य वर्गणाके विकल्पोंके अनन्तवें भागरूप ध्रुवहारसे ऋजुमतिके विषय उत्कृष्ट द्रव्यमें भाग देनेपर जो प्रमाण आता है उतना विपुलमतिके विषयभूत जघन्यद्रव्यका परिमाण होता है ॥४५२॥

आठों कर्मोके विस्रसोपचय रहित सामान्य समय प्रबद्धमें ध्रुवहारसे एक बार भाग देनेपर जो एक खण्ड आता है वह विपुलमतिका विषय द्वितीयद्रव्य होता है ॥४५३॥

मणदव्ववग्गणाणमणंतिमभागेण उजुगउक्कस्सं ।
खंडिदमेत्तं होदि हु विउलमदिस्सावरं दव्वं ॥४५२॥

मनोद्रव्यवर्गणानामनंतैकभागेन ऋजुमतेरुत्कृष्टं । खंडितमात्रं भवति खलु विपुलमतेरवरं द्रव्यं ॥

मनोद्रव्यवर्गणेगळनंतैकभागं ध्रुवहारप्रमाणमक्कु ज १ / ख ख मो ध्रुवहार भागदिवं ऋजुमतिपर्य्यंयज्ञानविषयोत्कृष्टद्रव्यमं खंडिसुत्तिरलावुदो देकखंडं तावन्मात्रं खलु स्फुटमागि विपुलमतिमनःपर्य्ययज्ञानविषयजघन्यद्रव्यमक्कुं ॥ ० १६ ख ६ प

६ । १ । प १ १ प ० ९
० ०

अट्ठण्हं कम्माणं समयपबद्धं विविस्ससोवचयं ।
धुवहारेणिगिवारं भजिदे विदियं हवे दव्वं ॥४५३॥

अष्टानां कर्म्मणां समयप्रबद्धो विविस्रसोपचयो। ध्रुवहारेणैकवारं भाजिते द्वितीयं भवेद्द्रव्यं।

ज्ञानावरणाद्यष्टविधकर्म्मसामान्यसमयप्रबद्धं विगतविस्रसोपचयमदेकवारं ध्रुवहारदिदं भागिसल्पडुत्तिरलेकखंडमात्रं विपुलमतिमनःपर्य्ययज्ञानविषयद्वितोयद्रव्यविकल्पमक्कुं स ०-ख ख / ९ ० ०

मनोद्रव्यवर्गणाविकल्पानामनन्तैकभागेन ध्रुवहारेण ज १ / ख ख ऋजुमतिविषयोत्कृष्टद्रव्ये खण्डिते यावन्मात्रं तावत्स्फुटं विपुलमतिविषयजघन्यद्रव्यं भवति स ० १६ ख । ६ प ॥४५२॥
०

६ १ प १ १ प । ९
० ०

अष्टकर्मसामान्यसमयप्रबद्धे विस्रसोपचये ध्रुवहारेण एकवारं भक्ते यदेकखण्डं तद्विपुलमतिविषयद्वितीयद्रव्यं भवति— स ० ० ० ख ख ॥४५३॥
९

मनोद्रव्य वर्गणाके विकल्पोंके अनन्तवें भागरूप ध्रुवहारसे ऋजुमतिके विषय उत्कृष्ट द्रव्यमें भाग देनेपर जो प्रमाण आता है उतना विपुलमतिके विषयभूत जघन्यद्रव्यका परिमाण होता है ॥४५२॥

आठों कर्मोंके विस्रसोपचय रहित सामान्य समय प्रबद्धमें ध्रुवहारसे एक बार भाग देनेपर जो एक खण्ड आता है वह विपुलमतिका विषय द्वितीयद्रव्य होता है ॥४५३॥

मणदव्ववग्गणाणमणंतिमभागेण उजुगउक्कस्सं ।
खंडिदमेत्तं होदि हु विउलमदिस्सावरं दव्वं ॥४५२॥

मनोद्रव्यवर्गणानामनंतैकभागेन ऋजुमत्युत्कृष्टं । खंडितमात्रं भवति खलु विपुलमतेरवरं द्रव्यं ॥

मनोद्रव्यवर्गणेगळनंतैकभागं ध्रुवहारप्रमाणमक्कु ज १ मी ध्रुवहार भागहारं ऋजुमति-
ख ख
पर्य्ययज्ञानविषयोत्कृष्टद्रव्यमं खंडिसुत्तिरलागुत्तो देकखंडं तावन्मात्रं खलु स्फुटमागि विपुलमतिमनः-
पर्य्ययज्ञानविषयजघन्यद्रव्यमक्कुं स ० १६ ख ६ प

६ । १ । ५ १ १ प ० ९
० ०

अट्ठण्हं कम्माणं समयपबद्धं विविस्ससोवचयं ।
धुवहारेणिगिवारं भजिदे विदियं हवे दव्वं ॥४५३॥

अष्टानां कर्म्मणां समयप्रबद्धो विविस्रसोपचयो । ध्रुवहारेणैकवारं भाजिते द्वितीयं भवेद्द्रव्यं ।

ज्ञानावरणाद्यष्टविधकर्म्मसामान्यसमयप्रबद्धं विगतविस्रसोपचयमदेकवारं ध्रुवहारदिदं भागिसल्पडुत्तिरलेकखंडमात्रं विपुलमतिमनःपर्य्ययज्ञानविषयद्वितीयद्रव्यविकल्पमक्कुं स ०-ख ख
९ ० ०

मनोद्रव्यवर्गणाविकल्पानामनन्तैकभागेन ध्रुवहारेण ज १ ऋजुमतिविषयोत्कृष्टद्रव्ये खण्डिते यावन्मात्रं
ख ख
तत्स्फुटं विपुलमतिविषयजघन्यद्रव्यं भवति स ० १६ ख । ६ प ॥४५२॥
०

६ १ प १ १ प । ९
० ०

अष्टकर्मसामान्यसमयप्रबद्धे विविस्रसोपचये ध्रुवहारेण एकवारं भक्ते यदेकखण्डं तद्विपुलमतिविषय-द्वितीयद्रव्यं भवति— स ० ० ० ख ख ॥४५३॥
९

मनोद्रव्य वर्गणाके विकल्पोंके अनन्तवें भागरूप ध्रुवहारसे ऋजुमतिके विषय उत्कृष्ट द्रव्यमें भाग देनेपर जो प्रमाण आता है उतना विपुलमतिके विषयभूत जघन्यद्रव्यका परिमाण होता है ॥४५२॥

आठों कर्मोंके विस्रसोपचय रहित सामान्य समय प्रबद्धमें ध्रुवहारसे एक बार भाग देनेपर जो एक खण्ड आता है वह विपुलमतिका विषय द्वितीयद्रव्य होता है ॥४५३॥

मनुष्यक्षेत्रव समचतुरस्रघनप्रतरप्रमितं विपुलमतिमनःपर्य्ययज्ञानविषयसर्व्वोत्कृष्टक्षेत्रप्रमाणमें वु समुद्दिष्टं अनादिनिधनार्षदोळु पेळल्पट्टुदप्पुदे कारणमागि मानुषोत्तरपर्व्वताभ्यंतरविष्कंभ नाल्वत्तय्दुलक्षयोजनप्रमाणमवर समचतुरस्रक्षेत्रघनप्रतरप्रमाणं कैकोळल्पडुवुदेके दोडे आ मानुषोत्तरपर्व्वतदिदं पोरगण नाल्कुं कोणंगळोळिर्द्द तिर्य्यंचरुममरक्कं चिंतिसिदुवं विपुलमतिमनःपर्य्ययज्ञानमरियुमप्पुदे कारणमागि।




दुगतिगभवा हु अवरं सत्तट्ठभवा हवंति उक्कस्सं।
अडणवभवा हु अवरमसंखेज्जं विउलउक्कस्सं ॥४५७॥

द्वित्रिभवाः खलु जघन्यं समाष्ट भवा भवंति उत्कृष्टं। अष्टनवभवाः खलु जघन्यमसंख्यातं विपुलोत्कृष्टं॥

कालं प्रति ऋजुमतिमनःपर्य्ययज्ञानविषयजघन्यं द्वित्रिभवंगळु खलु स्फुटमागि अप्पुवु उत्कृष्टदिदं सप्ताष्टभवंगळप्पुवु। विपुलमतिमनःपर्य्ययक्के जघन्यमष्टनवभवंगळु विषयमप्पुवु उत्कृष्टमसंख्यातसमयमप्पुवुमावोडं पल्यासंख्यातैकभागमात्रमक्कुं प/a

भवति न तु वृत्तस्य। कुतः ? यतस्तत्पञ्चचत्वारिंशल्लक्षयोजनप्रमाणं समचतुरस्रघनप्रतरं मनःपर्ययविषयोत्कृष्टक्षेत्रं समुद्दिष्टं ततः कारणात् तदपि कुतः ? मानुषोत्तराद्बहिश्चतुःकोणस्थिततिर्यगमराणां परचिन्तितानां उत्कृष्टविपुलमतेः परिज्ञानात् ॥४५६॥



कालं प्रति ऋजुमतेर्विषयजघन्यं द्वित्रिभवाः स्युः। उत्कृष्टं सप्ताष्टभवाः स्युः। विपुलमतेर्विषयजघन्यं अष्टनवभवाः स्युः। उत्कृष्टं पल्यासंख्यातैकभागः स्यात् प/a ॥४५७॥

मनुष्यलोकके विष्कम्भका निश्चायक है गोलाईका नहीं। अर्थात् मनुष्यलोक तो गोलाकार है। यह नहीं लेना चाहिए। क्योंकि पैंतालीस लाख योजन प्रमाण समचतुरस्र घनप्रतर अर्थात् समान चौकोर घनप्रतर रूप मनःपर्ययका उत्कृष्ट विषयक्षेत्र कहा है। अर्थात् पैंतालीस लाख योजन लम्बा उतना ही चौड़ा लेना। क्योंकि मानुषोत्तर पर्वतके बाहर चारों कोनोंमें स्थित देवों और तिर्यंचोंके द्वारा चिन्तित अर्थको भी उत्कृष्ट विपुलमति जानता है ॥४५६॥

कालकी अपेक्षा ऋजुमतिका जघन्य विषय दो तीन भव होते हैं। और उत्कृष्ट सात-आठ भव होते हैं। विपुलमतिका जघन्य विषय आठ-नौ भव होते हैं और उत्कृष्ट पल्यका असंख्यातवाँ भाग है ॥४५७॥

द्रव्य	क्षेत्र	काल	भाव	
स ७ ९ रू ७ ९ । ० ० ० ० ० ० स ७ स स ९ ९ ० ० ० ० स स	४५००००० ० ० ० ०	प ० ७ ० ० ० ०	भा ७ ७ ७ ७ ७	उत्कृष्ट विपुलमति
स ७ १६ स ६ प ७ ६ । ३ । प ३३ । प ९ ७ ७	जोयण । ८ । ९	भव । ८ । ९	८ ७ ७ ७ ७ ७	जघन्य
स ७ १६ स ६ प ७ ६ । १ । प । ११ प ७ ० ७ ० ०	जोयण । ७ । ८ ० ० ० ० ० ०	भव । ७ । ८ ० ० ० ० ० ०	८ ७ ७ ७ ७ ० ० ० ० ८	उत्कृष्ट ऋजुमति
स ७ १६ स	गाउय । २ । ३	भव २ । ३	७ ७ ७	जघन्य ॥ ०
द्रव्य	क्षेत्र	काल	भाव	॥ ० ॥ ० ॥

संपुण्णं तु समग्गं केवलमसवत्त सव्वभावगयं।
लोयालोयवितिमिरं केवलणाणं मुणेदव्वं ॥४६०॥

संपूर्णं तु समग्रं केवलमसपत्नसर्वभावगतं। लोकालोकवितिमिरं केवलज्ञानं मंतव्यं ॥

जीवद्रव्यद शक्तिगतज्ञानाविभागप्रतिच्छेदंगळेनितोळवनितुं व्यक्तिगे बंदु (धु) दप्पुदे कारणमागि संपूर्णमुं मोहनीयवीर्य्यांतरायनिरवशेषक्षयदिदमप्रतिहतशक्तियुक्तत्वदिदमुं निश्चलत्वदिदमुं समग्रमुं इंद्रियसहायनिरपेक्षमप्पुदरिदं केवलमुं। सपत्नंगळप्प घातिचतुष्टयप्रक्षयदिदं क्रमकरणव्यवधानरहितमागि सकलपदार्थगतमप्पुदु कारणदिदमसपत्नमुं लोकालोकंगळोळ्विगततिमिरमुमितप्पुदु केवलज्ञानमेंदु मंतव्यं वगेयल्पडुवुदु।

जीवद्रव्यस्य शक्तिगतसर्वज्ञानाविभागप्रतिच्छेदाना व्यक्तिगतत्वात्संपूर्णम्। मोहनीयवीर्यान्तरायनिरवशेषक्षयादप्रतिहतशक्तियुक्तत्वात् निश्चलत्वाच्च समग्रम्। इन्द्रियसहायनिरपेक्षत्वात् केवलम्। घातिचतुष्टयप्रक्षयात् क्रमकरणव्यवधानरहितत्वेन सकलपदार्थगतत्वात् असपत्नम्। लोकालोकयोर्विगततिमिरं तदिदं केवलज्ञानं

जीवद्रव्यके शक्तिरूप जो सब ज्ञानके अविभाग प्रतिच्छेद हैं वे सब व्यक्त हो जानेसे केवलज्ञान सम्पूर्ण है। मोहनीय और वीर्यान्तरायका सम्पूर्ण क्षय होनेसे केवलज्ञानकी शक्ति बेरोक और निश्चल है इसलिए वह समग्र है। इन्द्रियोंकी सहायता न लेनेसे केवल है। चार घातिया कर्मोंका अत्यन्त क्षय हो जानेसे तथा क्रम और इन्द्रियोंके व्यवधानसे रहित होनेके कारण समस्त पदार्थोंको जाननेसे असपत्न है। लोक और अलोकको प्रकाशित करनेवाला ऐसा यह केवलज्ञान जानना ॥४६०॥

पल्लासंखघणंगुलहदसेढितिरिक्खगदिविभंगजुदा ।
णरसहिदा किंचूणा चदुगदीवेभंगपरिमाणं ॥४६३॥

पल्यासंख्यातघनांगुलहतश्रेणितिर्य्यग्गति विभंगयुताः । नरसहिता किंचिदूना चतुर्गतिविभंगज्ञानिपरिमाणं ॥

पल्यासंख्यातघनांगुलगुणित १ जगच्छ्रेणिमात्रं तिर्य्यंचविभंगज्ञानिगळप्पर -६ प नरसहिता ई तिर्य्यंचविभंगज्ञानिगळोळु मनुष्यविभंगज्ञानिगळु संख्यातप्रमितरप्प १ रयागंळ संख्येयं साधिकं माडि - १ प दी राशियमं सम्यग्दृष्टिगळिवं किंचिदूनघनांगुलद्वितीयमूलगुणितजगच्छ्रेणिप्रमितसामान्यनारकर संख्येयमं ।-२-। सम्यग्दृष्टिगळिवं किंचिदून ज्योतिष्कर संख्येयं नोडि साधिकयुप्प देवगतिजर संख्येयुमनितुं नाल्कुं गतिगळ विभंगज्ञानिगळ संख्येयं कूडिदोडे चतुर्गतिसमस्तविभंगज्ञानिगळ संख्येयवक्कुं = १ / ४ । ६५-१

सण्णाणरासिपंचयपरिहीणो सव्वजीवरासी हु ।
मदिसुद अण्णाणीणं पत्तेयं होदि परिमाणं ॥४६४॥

सद्ज्ञानराशिपंचकपरिहीनः सर्व्वजीवराशिः खलु । मतिश्रुताज्ञानिनो प्रत्येकं भवति परिमाणं ॥

पल्यासंख्यातघनाङ्गुलहतजगच्छ्रेणिमात्रतिर्यञ्चः-६ प संख्यातमनुष्याः १ सम्यग्दृष्टयूनघनाङ्गुलद्वितीयमूलगुणितजगच्छ्रेणिमात्रनारकाः—२—सम्यग्दृष्टयूनज्योतिष्कसंख्यासाधिकदेवाः १— / = १- / ४ । ६५ = १ मिलित्वा चतुर्गतिविभङ्गज्ञानिसंख्या भवति १— / = १— / ४ । ६५ = १ ॥४६३॥

पल्यके असंख्यातवें भागसे गुणित घनांगुलसे जगतश्रेणिको गुणा करनेपर जितना प्रमाण हो उतने तिर्यंच, संख्यात मनुष्य तथा घनांगुलके द्वितीय मूलसे जगतश्रेणिको गुणा करनेपर जितना प्रमाण हो उतने नारकियोंके प्रमाणमें-से सम्यग्दृष्टी नारकियोंका प्रमाण घटानेसे जो शेष रहे उतने नारकी तथा ज्योतिषी देवोंके परिमाणमें भवनवासी, व्यन्तर और वैमानिक देवोंका प्रमाण मिलानेपर जो सामान्यदेव राशिका प्रमाण होता है उसमें सम्यक्दृष्टि देवोंका परिमाण घटानेपर जो शेष रहे उतने देव। इन सब तिर्यंच, मनुष्य, नारकी और देवोंके प्रमाणको जोड़नेपर चारों गतिके विभंगज्ञानियोंकी संख्या होती है ॥४६३॥

---

१. ब°न साधिकज्योतिष्कसंख्यदेवाः ।

गंभीररचनेगळ परिरंभणेयं विडिसि निरिसिदुवनेंदुव प्रा–१ रंभिसि गोम्मटवृत्ति सुधांभोळियिनोडिगे मोहवज्राचलमं ॥

इत्याचार्यश्रीनेमिचन्द्रविरचितायां गोम्मटसारापरनामपञ्चसंग्रहवृत्तौ जीवतत्त्वप्रदीपिकाख्यायां जीवकाण्डे विंशतिप्ररूपणासु ज्ञानमार्गणाप्ररूपणानाम द्वादशोऽधिकारः ॥१२॥

इस प्रकार आचार्य श्री नेमिचन्द्र विरचित गोम्मटसार अपर नाम पंचसंग्रहकी भगवान् अर्हन्त देव परमेश्वरके सुन्दर चरणकमलोंकी वन्दनासे प्राप्त पुण्यके पुंजस्वरूप राजगुरु मण्डलाचार्य महावादी श्री अभयनन्दी सिद्धान्त चक्रवर्तीके चरणकमलोंकी धूलिसे शोभित ललाटवाले श्री केशववर्णीके द्वारा रचित गोम्मटसार कर्णाटवृत्ति जीवतत्त्व प्रदीपिकाकी अनुसारिणी संस्कृतटीका तथा उसकी अनुसारिणी पं. टोडरमलरचित सम्यग्ज्ञानचन्द्रिका नामक भाषाटीकाकी अनुसारिणी हिन्दी भाषा टीकामें जीवकाण्डकी बीस प्ररूपणाओंमें-से ज्ञानमार्गणा प्ररूपणा नामक बारहवाँ अधिकार सम्पूर्ण हुआ ॥१२॥

प्रमत्ताप्रमत्तरोळु संज्वलनकषायंगळो सर्वघातिस्पर्द्धकंगळुदयाभावलक्षणक्षयमुं उप[illegible] निषेकद उपरितननिषेकंगळुदयाभावलक्षणमुपशममुमितु चारित्रमोहनीयक्षयोपशममुं बादरसं[illegible] [illegible]स्पर्द्धककके संयमाविरोधदिदमुदयदोळं सामायिकछेदोपस्थापनसंयमंगळप्पुवुमा गु[illegible] [illegible]दोळे परिहारशुद्धिसंयममुमक्कुं। सूक्ष्मकृष्टिकरणानिवृत्तिपर्य्यंतं बादरसंज्वलनोदयदि[illegible] [illegible]निवृत्तिकरणदोळं सामायिकछेदोपस्थापनसंयमंगळप्पुवु। सूक्ष्मकृष्टिरूपविनिर्द्द संज्वल[illegible] [illegible] सूक्ष्मसांपरायसंयममक्कुं। चारित्रमोहनीयसर्व्वोपशमदिदमुं यथाख्यातसंयममक्कुं [illegible]निरवशेषक्षयदिदं यथाख्यातसंयमं क्षीणकषायादिगुणस्थानत्रयदोळं नियमदिदमक्कु [illegible] निर्म्मलमप्पुदें युदर्थमीयर्थमने मुंवणगाथासूत्रद्वयदिदं विशदं माडिदप[illegible]

बादरसंजलणुदए बादरसंजमतियं खु परिहारो।

पमदिदरे सुहुमुदए सुहुमो संजमगुणो होदि ॥४६७॥

बादरसंज्वलनोदये बादरसंयमत्रयं खलु परिहारः। प्रमत्तेतरयोः सूक्ष्मोदये सूक्ष्मः संयम[illegible] [illegible] ॥

बादरसंज्वलन[illegible]स्पर्द्धकोदयदोळु बादरंगळप्प सामायिकछेदोप[illegible] [illegible] संयमत्रयमक्कुमल्लि परिहारविशुद्धिसंयमं प्रमत्ताप्रमत्तरोळेयक्कु[illegible] [illegible]। सूक्ष्मकृष्टिरूपसंज्वलनलोभोदयमागुत्तिरलु सूक्ष्मसांपरायसंयम[illegible]

[illegible] सर्वघातिस्पर्द्धकानामुदयाभावलक्षणे क्षये उदयनिषेकादुपरितननिषेकाणां उदय[illegible] [illegible] सर्वघातिस्पर्द्धकस्य संयमाविरोधेनोदये सति सामायिकछेदोपस्थापनपरिहार[illegible] [illegible] सूक्ष्मकृष्टिकरणानिवृत्तिपर्यन्तं बादरसंज्वलनोदयेनानिवृत्तिकरणेऽपि सामायिकछेदो[illegible] [illegible] सूक्ष्मसाम्परायसंयमः चारित्रमोहनीयसर्वोपशमेन [illegible] [illegible] भवतीत्यर्थः, इत्येतद्विवरणेऽदिदृम् ॥४६६॥ [illegible]—

[illegible] बादर सामायिकछेदोपस्थापनपरिहारविशुद्धिसंयमा [illegible] अनिवृत्तिपर्यन्तं भवन्ति। सूक्ष्म[illegible]

[illegible]—प्रमत्त और अप्रमत्त गुणस्थानमें संज्वलन कषायोंके सर्वघाती [illegible] निषेकोंसे ऊपरके निषेकोंका [illegible] [illegible] संयमका विरोध न करते हुए [illegible] और परिहारविशुद्धि संयम होते हैं। किन्तु सूक्ष्म[illegible] [illegible] बादर संज्वलन कषायका उदय होनेसे [illegible] सामायिक और छेदोपस्थापना संयम होते हैं। सूक्ष्म[illegible] [illegible] होनेसे सूक्ष्म साम्पराय संयम होता है। सम्पूर्ण चारित्र[illegible] [illegible] और क्षय होनेपर [illegible] [illegible] ॥४६६॥

[illegible] कहते हैं—

[illegible] और [illegible] संयम होते हैं। [illegible] [illegible] और अप्रमत्त गुणस्थानमें [illegible] होता है। [illegible] अनिवृत्तिकरण

[illegible]

[illegible] ॥२३१॥

[illegible]

[illegible] ॥२३२॥

[illegible]

[illegible] है और [illegible] है [illegible]

[illegible]

निर्गिर्गनिल्लनुदं दुगम्यं दुःखेन महता कष्टेन गम्यं प्राप्यं एवंविधमप्प सामायिकमं सनुद्दहुत्तु जीवः केळंगु नडनुवंतप्पासन्नभव्यजीवं सामायिकसंयमो भवति। सामायिकः संयमोऽस्यास्मिन्वा [illegible]सामायिकसंयमः सामायिकसंयममनुळ्ळ सामायिकसंयमनेंबनक्कुं।

छेत्तूण य परियायं पोराणं जो ठवेइ अप्पाणं।
पंचजमे धम्मे सो छेदोवट्ठावगो जीवो ॥४७१॥

छित्वा च पर्यायं पुराणं यः स्थापयति आत्मानं। पंचयमे धर्मे स छेदोपस्थापको जीवः॥

छित्वा पुराणं पर्य्यायं सामायिकसंयतनागिर्दुं बळिचि सावद्यव्यापारंगळोळे संचिरंतप्पजीवं [illegible]र्य्यायमं प्रायश्चित्तंगळिदं छित्वा च्छेदिसि यः आवनोव्वं आत्मानं तन्नं पंचयमे धर्मे [illegible]स्थापयति नेलेगोलिसुगुं सः जीवः आ जीवं छेदोप[illegible]नक्कुं। छेदेनोपस्थापनं छेदोपस्थापनं। प्रायश्चित्ताचरणेनोप[illegible] स छेदोपस्थापकः एंदितु निरुक्तिलक्षणसिद्धमक्कुं। अथवा प्रायश्चित्तं[illegible] तपमनाचरिसुत्तं छेदिसि [illegible] स्थापिसुवातनुं छेदोपस्थापनसंयतनक्कुं। स्वतपसि छेदे सति [illegible] छेदोपस्थापकः एंदितिल्लि अधिकरणव्युत्पत्तियक्कुं।

[illegible] परिहरइ सदा वि जो हु सावज्जं।
[illegible] परिहारयसंजदो सो हु ॥४७२॥

[illegible] परिहरति सदापि यः खलु सावद्यं। पंचैकयमः पुरुषः परिहारसंयतः

[illegible] अनुत्तर—अनुत्तम, अनुत्तर, दुरवगम्य—दुःखेन प्राप्यं तत्सामायिकं समुद्वहन् जीवः [illegible] भवति ॥४७०॥

[illegible] पुराणं पर्यायमं [illegible] यो जीवः पुराणं [illegible] स्थापयति स छेदोपस्थापनसंयतः [illegible] इति निरुक्तिः। अथवा प्रायश्चित्तेन [illegible] स्थापयति स छेदोपस्थापकसंयतः, [illegible] ॥४७१॥

[illegible] निरुत्कृष्ट है। यह अनुत्तर है अर्थात् [illegible] है और दुरवगम्य है अर्थात् बड़े कष्टसे यह प्राप्त होता है। [illegible] संयमी होता है ॥४७०॥

[illegible] इससे च्युत होकर सावद्य क्रियामें [illegible] द्वारा छेदन करके अपनेको [illegible] स्थापन करता है वह छेदोपस्थापना संयमी [illegible] उपस्थापन होता है वह [illegible] किये हुए दोषोंको [illegible] संयममें [illegible] छेदोपस्थापना [illegible] है ॥४७१॥

मनोंभत्तनेय पूर्व्वंमं पठियिसि मत्ते परिहारविशुद्धिसंयममं पोर्द्दिवंगे तदुत्कृष्टकालं संभविसुगुमप्पुर्वरिदं। 'परिहारर्द्धिसमेतः षड्जीवनिकायसंकुले विहरन्। पयसेव पद्मपत्रं न लिप्यते पापनिवहेन'।

अणुलोहं वेदंतो जीवो उवसामगो व खवगो वा।
सो सुहुमसंपराओ जहखाएणूणओ किंचि ॥४७४॥

अणुलोभं वेदयमानो जीवः उपशमको वा क्षपको वा। स सूक्ष्मसांपरायो यथाख्यातेनोनः किंचित् ॥

सूक्ष्मलोभकृष्टिगतानुभागमनावनोर्व्वनन् भविसुत्तं जीवन् उपशमकनागलि मेणु क्षपकनागलि मेणु सः आ जीवं सूक्ष्मसांपरायनें बनक्कुं। सूक्ष्मः सांपरायः कषायो यस्य स सूक्ष्मसांपरायः एंदी यन्वर्थनामविशिष्टमहामुनि यथाख्यातसंयमिपलोडने किंचिदूननक्कुं।

उवसंते खीणे वा असुहे कम्मम्मि मोहणीयम्मि।
छदुमट्ठो व जिणो वा जहखादो संजदो सो दु ॥४७५॥

उपशांते क्षीणे वा अशुभे कर्म्मणि मोहनीये छद्मस्थो वा जिनो वा यथाख्यातसंयतः स तु ॥

अशुभमप्प मोहनीयकर्म्ममुपशांतमागुत्तिरलु मेणु क्षीणमागुत्तं विरलावनोर्व्वं छद्मस्थं उपशांतकषायनागलि मेणु क्षीणकषायछद्मस्थनागलि मेणु जिनो वा सयोगकेवलियुमयोगकेवलियुमेणागलि सः आ जीवं तु मत्ते यथाख्यातसंयतनें बनक्कुं। मोहस्य निरवशेषस्योपशमात्क्षयाद्वा·

दिवसादारभ्य त्रिंशद्वर्षाणि सर्वदा सुखेन नीत्वा संयमं प्राप्य वर्षपृथक्त्वं तीर्थंकरपादमूले प्रत्याख्यानं पठितस्य तदङ्गीकरणात् ॥

उक्तं च–

परिहारर्धिसमेतः षड्जीवनिकायसंकुले विहरन्।
पयसेव पद्मपत्रं न लिप्यते पापनिवहेन ॥४७३॥

सूक्ष्मलोभकृष्टिगतानुभागमनुभवन् यः उपशमकः क्षपको वा स जीवः सूक्ष्मसांपरायः स्यात्। सूक्ष्मः सांपरायः कषायो यस्येत्यन्वर्थनामा महामुनिः यथाख्यातसंयमिभ्यः किंचिन्न्यूनो भवति ॥४७४॥

अशुभमोहनीयकर्मणि उपशान्ते क्षीणे वा य. उपशान्तक्षीणकषायछद्मस्थः सयोगायोगिजिनो वा, स:, तु–पुनः, यथाख्यातसंयतो भवति। मोहस्य निरवशेषस्य उपशमात् क्षयाद्वा आत्मस्वभावावस्थापेक्षालक्षणं

सदा सुखसे बिताकर संयम धारण करके वर्षपृथक्त्व तक तीर्थंकरके पादमूलमें प्रत्याख्यान पढ़नेके पश्चात् परिहारविशुद्धि संयम स्वीकार करना होता है। कहा है—'परिहारविशुद्धि ऋद्धिसे संयुक्त जीव छह कायके जीवोंसे भरे स्थानमें विहार करते हुए भी पाप समूहसे वैसे ही लिप्त नहीं होता जैसे कमलका पत्ता पानीमें रहते हुए भी पानीसे लिप्त नहीं होता' ॥४७३॥

सूक्ष्म कृष्टिको प्राप्त लोभ कषायके अनुभागको अनुभव करनेवाला उपशमक या क्षपक जीव सूक्ष्म साम्पराय होता है। सूक्ष्म साम्पराय अर्थात् कषाय जिसकी है वह सार्थक नामवाला महामुनि यथाख्यात संयमियोंसे किंचित् ही हीन होता है ॥४७४॥

अशुभ मोहनीय कर्मके उपशान्त या क्षय हो जानेपर उपशान्त कषाय और क्षीण कषाय गुणस्थानवर्ती छद्मस्थ अथवा सयोगी और अयोगी जिन यथाख्यात संयमी होते हैं।

---

१. क 'वर्तिदं हिं'।

इत्यादिलक्षणंगळु देशविरतरुगळगे पर्यंतरवोळरियल्पडुवुवु ।

जीवा चोद्दसभेया इंदियविसया तहट्ठवीसं तु ।
जे तेसु णेव विरया असंजदा ते मुणेयव्वा ॥४७८॥

जीवाश्चतुर्दशभेदाः इंद्रियविषयास्तथाष्टाविंशतिः तु । ये तेषु नैव विरताः असंयतास्ते मंतव्याः ॥

पदिनाल्कुं जीवभेदंगळोळं तु मत्तें इंद्रियविषयंगळिप्पतें दुभेदं गळोळमारोळंवरु विरतरल्लदवर्गळु असंयतरे दरियल्पडुवरु ।

पंचरस पंचवण्णा दो गंधा अट्ठफाससत्तसरा ।
मणसहिदट्ठावीसा इंदियविसया मुणेदव्वा ॥४७९॥

पंचरसाः पंचवर्णाः द्वौ गंधौ अष्टस्पर्शाः सप्तस्वराः । मनः सहिताष्टाविंशतिरिंद्रियविषया मंतव्याः ॥

तिक्तकटुकषायाम्लमधुरमें व पंचरसंगळुं श्वेतपीतहरितारुणकृष्णमें व पंचवर्णंगळुं सुगंधदुर्गंधमें बरडु गंधमुं मृदुकर्कशगुरुलघुशीतोष्णस्निग्धरूक्षमें व अष्टस्पर्शंगळुं षड्जऋषभगांधार मध्यम-पंचमधैवतनिषादमें व सरिगमपध निगळप्पसप्तस्वरंगळुं कूडिविंतिंद्रियविषयंगळिप्पत्तेळु मनोविषयमों दितु इंद्रियनोइंद्रियविषयंगळष्टाविंशतिप्रमितंगळें दु मंतव्यंगळप्पुवु ।

अनंतरं संयममार्ग्गणेयोळु जीवसंख्येयं पेळ्दपं :—

पमदादिचउण्हजुदी सामाइयदुगं कमेण सेसतियं ।
सत्तसहस्सा णवसय णवलक्खा तीहि परिहीणा ॥४८०॥

प्रमत्तादिचतुर्णां युतिः सामायिकद्विकं क्रमेण शेषत्रयं । सप्तसहस्रं नवशतं नवलक्षं त्रिभिः परिहीनानि ॥

चतुर्दशजीवभेदाः, तु—पुनः इन्द्रियविषयाः अष्टाविंशतिः तेषु ये नैव विरतास्ते असंयता इति मन्तव्याः ॥४७८॥

रसाः—तिक्तकटुककषायाम्लमधुराः पञ्च । वर्णाः—श्वेतपीतहरितारुणकृष्णाः पञ्च । गन्धौ सुगन्धदुर्गन्धौ द्वौ । स्पर्शाः मृदुकर्कशगुरुलघु-शीतोष्णस्निग्धरूक्षाः अष्टौ । स्वराः—षड्ज-ऋषभ-गान्धार-मध्यम-पञ्चम-धैवत-निषादाः सरिगमपधनिरूपाः सप्त एते इन्द्रियविषयाः सप्तविंशतिः । मनोविषय एकः, एवमष्टाविंशतिर्मन्तव्याः ॥४७९॥ अथ संयममार्गणायां जीवसंख्यामाह—

चौदह प्रकारके जीव और अठाईस इन्द्रियोंके विषय, इनमें जो विरत नहीं हैं वे असंयमी जानना ॥४७८॥

तीता, कटुक, कसैला, खट्टा, मीठा ये पाँच रस हैं। श्वेत, पीला, हरा, लाल, काला ये पाँच वर्ण हैं। सुगन्ध, दुर्गन्ध ये दो गन्ध हैं। कोमल, कठोर, भारी, हल्का, शीत, उष्ण, चिकना, रूखा ये आठ स्पर्श हैं। षड्ज, ऋषभ, गान्धार, मध्यम, पंचम, धैवत, निषाद ये सा रे ग म प ध नि रूप सात स्वर हैं। ये सत्ताईस इन्द्रियविषय हैं और एक मनका विषय है। इस प्रकार अठाईस विषय जानना ॥४७९॥

अब संयम मार्गणामें जीवोंकी संख्या कहते हैं—

संसारिराशिअविरतप्रमाणमक्कु :—

सामायिक	छेदोपस्थापन	परिहार	सूक्ष्म	यथाख्यात	देशसंय =	संय =
८९०९९१०३	८२०९९१०३	६९९७	८९७	८९९९९७	प ३ ३ ४ ३	१३ –

इंतु भगवदर्हत्परमेश्वरचारुचरणारविंदद्वंद्ववंदनानंदित पुण्यपुंजायमानश्रीमद्रायराजगुरु मंडलाचार्य्यमहावादवादीश्वररायवादिपितामह सकलविद्वज्जनचक्रवर्त्ति श्रीमदभयसूरिसिद्धांतचक्रवर्त्तिश्रीपादपंकजरजोरंजितललाटपट्टं श्रीमत्केशवण्णविरचितमप्प गोम्मटसारकर्णाटवृत्तिजीवतत्वप्रदीपिकेयोळ् जीवकांडविंशतिप्ररूपणंगळोळ् त्रयोदशं संयममार्ग्गणाधिकारं निगदितमाय्तु ॥

अविरतानां प्रमाणं भवति । १३–॥४८१॥

इत्याचार्यश्रीनेमिचन्द्रविरचितायां गोम्मटसारापरनामपञ्चसंग्रहवृत्तौ तत्त्वप्रदीपिकाख्यायां जीवकाण्डे विंशतिप्ररूपणासु संयममार्गणाप्ररूपणा नाम त्रयोदशोऽधिकारः ॥१३॥

संसारी जीवोंकी राशिमें भाग देनेपर जो शेष रहे उतना ही असंयमियोंका प्रमाण होता है ॥४८१॥

इस प्रकार आचार्य श्री नेमिचन्द्र विरचित गोम्मटसार अपर नाम पंचसंग्रहकी भगवान् अर्हन्त देव परमेश्वरके सुन्दर चरणकमलोंकी वन्दनासे प्राप्त पुण्यके पुंजस्वरूप राजगुरु मण्डलाचार्य महावादी श्री अभयनन्दी सिद्धान्त चक्रवर्तीके चरणकमलोंकी धूलिसे शोभित ललाटवाले श्री केशववर्णीके द्वारा रचित गोम्मटसार कर्णाटवृत्ति जीवतत्त्व प्रदीपिकाकी अनुसारिणी संस्कृतटीका तथा उसकी अनुसारिणी पं. टोडरमल रचित सम्यग्ज्ञानचन्द्रिका नामक भाषाटीकाकी अनुसारिणी हिन्दी भाषा टीकामें जीवकाण्डकी बीस प्ररूपणाओंमें-से संयममार्गणा प्ररूपणा नामक तेरहवाँ अधिकार सम्पूर्ण हुआ ॥१३॥

१. म प्रतौ संदृष्टिर्नास्ति ।

भावसाधनं दर्शनमरियल्पडुवुदु ।

अनंतरं चक्षुर्दर्शन अचक्षुदर्शनंगळ स्वरूपमं पेळ्वपं :—

चक्खूण जं पयासइ दिस्सइ तं चक्खुदंसणं वेंति ।
सेसिंदियप्पयासो णायव्वो सो अचक्खु त्ति ॥४८४॥

चक्षुषा यत्प्रकाशते दृश्यते तच्चक्षुर्दर्शनं ब्रुवंति । यः शेषेंद्रियप्रकाशो ज्ञातव्यः सोऽचक्षुर्दर्शनमिति ॥

नयनंगळावुदों दु प्रतिभासिसुत्तमिर्द्दपुदु काणल्पडुत्तिर्द्दपुदु तद्विषयप्रकाशनमे चक्षुर्द्दर्शनमें दितु गणधरदेवादिदिव्यज्ञानिगळु पेळ्वरु । शेषेंद्रियंगळावुदों दु तोर्पत्तिर्द्दपुददु अचक्षुदर्शनमें दितु ज्ञातव्यमक्कुं ।

परमाणु आदियाइं अंतिमखंधंति मुत्तिदव्वाइं ।
तं ओहिदंसणं पुण जं पस्सइ ताइ पच्चक्खं ॥४८५॥

परमाण्वादिकान्यंतिमस्कंधपर्य्यंतानि मूर्त्तद्रव्याणि । तदवधिदर्शनं पुनर्यत्पश्यति तानि प्रत्यक्षं ॥

परमाणुवादियागि महास्कंधपर्य्यंतमप्प मूर्त्तद्रव्यंगळवेनितनितुमनावुदों दु दर्शनं मत्ते प्रत्यक्षमागि काणुमदवधिदर्शनमें बुदक्कुं ।

बहुविहबहुप्पयारा उज्जोवा परिमियम्मि खेत्तम्मि ।
लोगालोगवितिमिरो जो केवलदंसणुज्जोओ ॥४८६॥

बहुविधबहुप्रकारा उद्योताः परिमिते क्षेत्रे । लोकालोकवितिमिरो यः केवलदर्शनोद्योतः ॥

सत्तावभासनं तद्दर्शनं भवति । पश्यति दृश्यते अनेन दर्शनमात्रं वा दर्शनम् ॥४८३॥ अथ चक्षुरचक्षुर्दर्शने लक्षयति—

चक्षुषोः—नयनयोः संबन्धि यत्सामान्यग्रहणं प्रकाशते पश्यति तद्वा दृश्यते जीवेनानेन कृत्वा तद्वा तद्विषयप्रकाशनमेव तद्वा चक्षुर्दर्शनमिति गणधरदेवादयो ब्रुवन्ति । यश्च शेषेन्द्रियप्रकाशः स अचक्षुर्दर्शनमिति ॥४८४॥

परमाणोरारभ्य महास्कन्धपर्यन्तं मूर्तद्रव्याणि पुनः यद्दर्शनं प्रत्यक्षं पश्यति तदवधिदर्शनं भवति ॥४८५॥

मात्र दर्शन है ॥४८३॥

अथ चक्षुदर्शन और अचक्षुदर्शनके लक्षण कहते हैं—

दोनों नेत्र सम्बन्धी सामान्य ग्रहणको जो देखता है अथवा इस जीवके द्वारा देखा जाता है अथवा सामान्य मात्रका प्रकाशन दर्शन है, यह गणधरदेव आदि कहते हैं। शेष इन्द्रियोंका जो प्रकाश है वह अचक्षु दर्शन है ॥४८४॥

परमाणुसे लेकर महास्कन्ध पर्यन्त सब मूर्तिक द्रव्योंको जो प्रत्यक्ष देखता है वह अवधिदर्शन है ॥४८५॥

त्रैराशिकं माडि प्र ४। प = इ। २ वंदलब्धदोळु पर्य्याप्तकरं किंचिदूनं माडिदोडदु शक्तिगतचक्षु-
४
२ a
a

र्द्दर्शनिगळ संख्येयक्कु = । २— मिते व्यक्तिगतचक्षुर्द्दर्शनिगलं त्रैराशिकमं माल्पागळोंदु
४ ।
२ ४
≡

विशेषमुंटदावुदेंदोडे फलराशित्रसपर्य्याप्तराशियक्कु प्र =४ प= इ। २। मी वंद लब्धं व्यक्ति-
४
५

गतचक्षुर्द्दर्शनिगळ संख्येयक्कु = । २ अवधिदर्शनिगळ संख्येयवधिज्ञानिगळ प्रमाणमेनितनिते-
४ । ४
५

यक्कुं प a केवलदर्शनिगळसंख्ये केवलज्ञानिगळसंख्येयेनितनितेयक्कुं १।
e a ३

कियत्? इति त्रैराशिके कृते प्र ४। फ =। इ २ लब्धं पर्याप्तकसंख्यया किंचिदूनं शक्तिगतचक्षुर्दर्शनिसंख्या
४
२
a

भवति =। २ = द्वितीयत्रैराशिके फलराशिः त्रसपर्याप्तकराशिः प्र ४। फ =। इ २ लब्धं व्यक्तिगतचक्षुर्दर्शनिसंख्या
४ । ४ ४
२ ५
a

भवति = २-अवधिदर्शनराशिरवधिज्ञानराशिवत् प a—१ केवलदर्शनिसंख्या केवलज्ञानिसंख्यावत् १ ॥४८३॥
४ । ४ a a १
५

पंचेन्द्रियका कितना परिमाण है ऐसा त्रैराशिक करनेपर प्रमाण राशि चार, फलराशि त्रसजीवोंका प्रमाण, इच्छाराशि दो। सो इच्छाराशिको फलराशिसे गुणा करके प्रमाणराशि से भाग देनेपर जो प्रमाण आवे उतने चौइन्द्रिय, पंचेन्द्रिय जीवराशि है। उसमेंसे पर्याप्त जीवोंके प्रमाणको घटानेपर जो प्रमाण आवे उसमें-से कुछ घटानेपर, क्योंकि दोइन्द्रिय आदि क्रमसे घटते हुए शक्तिगत चक्षुदर्शनवालोंका प्रमाण जानना। इसी तरह त्रसपर्याप्त जीवोंके प्रमाणको चारसे भाग देकर दोसे गुणा करनेपर जो प्रमाण आवे उसमें-से कुछ कम करनेपर व्यक्तिरूप चक्षुदर्शनवालोंका प्रमाण होता है। अवधिदर्शनी जीवोंका प्रमाण अवधिज्ञानियोंके प्रमाणके समान जानना। और केवल दर्शनी जीवोंका प्रमाण केवलज्ञानी जीवोंके परिमाणके समान जानना ॥४८३॥

लेश्या-मार्गणा ॥१५॥

दर्शनमार्गणानंतरं लेश्यामार्गणेयं पेळलुपक्रमिसि निरुक्तिपूर्व्वकं लेश्येये लक्षणमं पेळ्दपं—

> लिंपइ अप्पीकीरइ एदीए णियअपुण्णपुण्णं च ।
> जीवोत्ति होदि लेस्सा लेस्सागुणजाणयक्खादा ॥४८९॥

लिंपत्यात्मीकरोत्येतया निजाऽपुण्यं पुण्यं च जीव इति भवति लेश्या लेश्यागुणज्ञायका-ख्याता ।

द्रव्यलेश्येयेंदुं भावलेश्येयेंदुं लेश्ये द्विप्रकारमप्पुवल्लि । भावलेश्यापेक्षेयिदं लिंपत्यात्मीकरोति निजापुण्यं पुण्यं च जीव एतयेति लेश्या । लेश्यागुणज्ञायकाऽऽख्याता भवति । जीवं निजपापमुमं पुण्यमुमं लिंपति तन्नं पोरेगुं आत्मीकरोति तन्नदागि माळ्पनिदरिंदमेंदितु लेश्या लेश्येंदु लेश्या-गुणमनरिद श्रुतज्ञानिगळप्प गणधरदेवादिगळिंदं पेळल्पट्टुदक्कुं । अनया कर्म्मभिरात्मानं लिंपतीति लेश्या । कषायोदयानुरंजिता योगप्रवृत्तिर्वा लेश्या । कषायाणामुदयेनानुरंजिता कमप्यतिशयांतरमु-पनीता भवतीत्यर्थः । ई यर्थमने विशदमागि माडिदपरु ।

> यः सद्धर्मसुधावर्षैर्भव्यसस्यानि प्रीणयन् ।
> नीतवान् स्वेष्टसिद्धिं तं धर्मनाथघनं भजे ॥१५॥

अथ लेश्यामार्गणां वक्तुमना निरुक्तिपूर्वकं लेश्यालक्षणमाह—

लेश्या द्रव्यभावभेदाद् द्वेधा । तत्र भावलेश्यां लक्षयितुं इदं सूत्रम् । लिम्पति—आत्मीकरोति निजमपुण्यं पुण्यं च जीव एतयेति लेश्या लेश्यागुणज्ञायकैर्गणधरदेवादिभिराख्याता । अनया कर्मभिरात्मानं लिम्पतीति लेश्या । कषायोदयानुरञ्जिता योगप्रवृत्तिर्वा लेश्या कषायाणामुदयेन अनुरञ्जिता कमप्यतिशयान्तरमुपनीता योगप्रवृत्तिर्वा लेश्या ॥४८९॥ अमुमेवार्थं स्पष्टयति—

लेश्या मार्गणाको कहनेकी भावनासे निरुक्तिपूर्वक लेश्याका लक्षण कहते हैं—

लेश्या द्रव्य और भावके भेदसे दो प्रकारकी है। उनमें-से भावलेश्याका लक्षण कहनेके लिए यह सूत्र है। 'लिम्पति' अर्थात् इसके द्वारा जीव अपने पुण्य-पापको अपनाता है, लेश्या-का यह लक्षण लेश्याके गुणोंके ज्ञाता गणधर देव आदिने कहा है। जिसके द्वारा जीव आत्माको कर्मोंसे लिप्त करता है वह लेश्या है। कषायके उदयसे अनुरंजित मन वचन कायकी प्रवृत्ति लेश्या है। अथवा कषायोंके उदयसे अनुरंजित अर्थात् किसी भी अतिशया-न्तरको प्राप्त योग प्रवृत्ति लेश्या है ॥४८९॥

इसीको स्पष्ट करते हैं—

नारप्पुवेकें दोडे लेश्यानां साधनार्त्थं लेश्येगळ भेदप्रभेदंगळं साधिससल्वेडि अवुकारणमागि तेरधिकारेः आपदिनारुमधिकारंगळिवं यथाक्रमं क्रममनतिक्रमिसदे लेश्येयं वक्ष्यामि पेळ्वें ॥

किण्हा णीला काऊ तेऊ पम्मा य सुक्कलेस्सा य ।
लेस्साणं णिद्देसा छच्चेव हवंति णियमेण ॥४९३॥

कृष्णा नीला कापोती तेजः पद्मा च शुक्ललेश्या च । लेश्यानां निर्द्देशाः षट् चैव भवंति नियमेन ॥

कृष्णलेश्येयेंदु नीललेश्येयेंदुं कपोतलेश्येयेंदुं तेजोलेश्येयेंदुं पद्मलेश्येयेंदुं शुक्ललेश्येयेंदुमितु लेश्येगळ निर्द्देशंगळारेयप्पुवु । नियमदिदं । इल्लि षट्चैव एंदितु नैगमनयाभिप्रायदिदं पेळल्पट्टुदु । पर्य्यायवृत्तियिदं मत्तमसंख्येयलोकमात्रंगळु लेश्येगळप्पुवेंदितु नियमशब्ददिदं सूचिसल्पट्टुदु । निर्द्देशं निगदितमाय्तु ॥

वण्णोदयेण जणिदो सरीरवण्णो दु दव्वदो लेस्सा ।
सा सोढा किण्हादी अणेयभेया सभेयेण ॥४९४॥

वर्णोदयेन जनितः शरीरवर्णस्तु द्रव्यतो लेश्या । सा षोढा कृष्णादयोऽनेकभेदाः स्वभेदेन ॥

वर्णनामकर्म्मोदयदिदं जनितः पुट्टल्पट्ट शरीरवर्णस्तु शरीरदवर्ण्णं द्रव्यतो लेश्या द्रव्यदिदं लेश्येयक्कुमा द्रव्यलेश्येयुं षोढा षट्प्रकारमक्कुमा षट्प्रकारंगळुं कृष्णादयः कृष्णादिगळक्कुं । अनेकभेदाः स्वभेदेन स्वस्वभेदाः स्वभेदाः तैः स्वभेदैरनेकभेदाः स्युः तंतम्म भेददिदमनेकभेदंगळप्पुवेंतेंदोडे ॥

अन्तरं भावः अल्पबहुत्वं चेति षोडशाधिकाराः लेश्याभेदप्रभेदसाधनार्थं भवन्तीति तैर्यथाक्रमं लेश्या वक्ष्यामि ॥४९१–४९२॥

कृष्णलेश्या नीललेश्या कपोतलेश्या तेजोलेश्या पद्मलेश्या शुक्ललेश्या चेति लेश्यानिर्देशाः–लेश्यानामानि षडेव भवन्ति नियमेन । अत्र एवकारेणैव नियमस्य अवगमात् पुनरनर्थकं नियमशब्दोपादानं नैगमनयेन लेश्या षोढा पर्यायार्थिकनयेन असंख्यातलोकभेदेत्याचार्यस्य अभिप्रायं ज्ञापयति ॥४९३॥ इति निर्देशाधिकारः ।

वर्णनामकर्मोदयजनितशरीरवर्णस्तु द्रव्यलेश्या भवति । सा च षोढा–षट्प्रकाराः । ते च प्रकाराः कृष्णादयः स्वस्वभेदैरनेकभेदाः स्युः ॥४९४॥ तथाहि–

काल, अन्तर, भाव, अल्पबहुत्व ये सोलह अधिकार लेश्याके भेद-प्रभेदोंके साधनके लिए हैं । उनके द्वारा क्रमानुसार लेश्याको कहूँगा ॥४९१–९२॥

कृष्णलेश्या, नीललेश्या, कपोतलेश्या, तेजोलेश्या, पद्मलेश्या, शुक्ललेश्या ये छह ही लेश्याओंके नाम नियमित हैं । यहाँ एवकार (ही) से ही नियमका ज्ञान हो जानेसे पुनः नियम शब्दका ग्रहण निरर्थक ही है । अतः वह नैगम नयसे लेश्या छह हैं और पर्यायार्थिक नयसे असंख्यातलोक हैं, इस आचार्यके अभिप्रायको सूचित करता है ॥४९३॥ निर्देशाधिकार समाप्त हुआ ।

वर्णनाम कर्मके उदयसे उत्पन्न शरीरका वर्ण तो द्रव्य लेश्या है । उसके भी छह भेद हैं । वे कृष्ण आदि भेद अपने-अपने अवान्तर भेदोंसे अनेक भेद वाले हैं ॥४९४॥

वादरआऊतेऊ सुक्कातेऊ य वाउकायाणं ।
गोम्मुत्तमुग्गवण्णा कमसो अव्वत्तवण्णा य ॥४९७॥

वादराप्कायिकतेजस्कायिकाः शुक्लास्तेजसश्च वातकायानां । गोमूत्रमुद्गवर्णौ क्रमशोऽव्यक्तवर्णाश्च ॥

वादराप्कायिकतेजस्कायिकंगळुं यथाक्रमदिदं शुक्लाः शुक्लवर्णंगळु तेजसश्च पीतवर्णंगळुमप्पुवु । वातकायंगळ शरीरवर्णंगळु घनोदधिघनानिलंगळ्गे गोमूत्रमुद्गवर्णंगळु यथाक्रमदिदमप्पुवु । तनुवातकायिकंगळ शरीरवर्णमव्यक्तवर्णमक्कुं ॥

सव्वेसिं सुहुमाणं कावोदा सव्वविग्गहे सुक्का ।
सव्वो मिस्सो देहो कवोदवण्णो हवे णियमा ॥४९८॥

सर्व्वेषां सूक्ष्माणां कापोताः सर्व्वविग्रहे शुक्लाः । सर्व्वो मिश्रो देहः कपोतवर्णो भवेन्नियमात् ॥

सर्वसूक्ष्मजीवंगळ देहंगळु कपोतवर्णदेहंगळेयप्पुवु सर्वजीवंगळु विग्रहगतियोळु शुक्लवर्णंगळेयप्पुवु । सर्वजीवंगळु शरीरपर्य्याप्तियनेरिवन्नेवरं कपोतवर्णंगळेयप्पव नियमदिदं ॥ वर्णाधिकारं द्वितीयं ॥ अनंतरं लेश्यापरिणामाधिकारमं गाथापंचकदिदं पेळ्दपं:—

लोगाणमसंखेज्जा उदयट्ठाणा कसायगा होंति ।
तत्थ किलिट्ठा असुहा सुहा विसुद्धा तदालावा ॥४९९॥

लोकानामसंख्येयान्युदयस्थानानि कषायगाणि भवंति । तत्र क्लिष्टान्यशुभानि शुभानि विशुद्धानि तदालापानि ।

बादरास्तेजस्कायिको क्रमेण शुक्लपीतवर्णावेव, वातकायिकेषु घनोदधिवातघनवाततनुवातशरीराणि क्रमेण गोमूत्रमुद्गवर्णानि तनुवातशरीराणि अव्यक्तवर्णानि ॥४९७॥

सर्वसूक्ष्मजीवदेहाः कपोतवर्णा एव । सर्वे जीवा विग्रहगतौ शुक्लवर्णा एव । सर्वे जीवाः स्वस्वपर्याप्तिप्रारम्भप्रथमसमयाच्छरीरपर्याप्तिनिष्पत्तिपर्यन्तं कपोतवर्णा एव नियमेन ॥४९८॥ इति वर्णाधिकारः । अथ परिणामाधिकारं गाथापञ्चकेनाह—

भोगभूमिके मनुष्य और तिर्यंच क्रमसे सूर्यके समान, चन्द्रमाके समान तथा हरित वर्णवाले होते हैं ॥४९६॥

बादर तैजस्कायिक और बादर जलकायिक क्रमसे पीतवर्ण और शुक्लवर्ण ही होते हैं। बादरवायुकायिकोंमें घनोदधि वातका शरीर गोमूत्रके समान वर्णवाला है। घनवातका शरीर मूँग के समान वर्णवाला है और तनुवातके शरीरका वर्ण अव्यक्त है ॥४९७॥

सब सूक्ष्मजीवोंका शरीर कपोतके समान वर्णवाला ही होता है। सब जीवोंका विग्रहगतिमें शुक्लवर्ण ही होता है। सब जीव अपनी-अपनी पर्याप्तिके प्रारम्भ होनेके प्रथम समयसे लेकर शरीरपर्याप्तिको पूर्णता पर्यन्त कपोतवर्ण ही नियमसे होते हैं ॥४९८॥

वर्णाधिकार समाप्त हुआ। आगे पाँच गाथाओंसे परिणामाधिकार कहते हैं—

मंदसंक्लेशस्थानंगळु तदसंख्यातलोकभक्तबहुभागमात्रंगळप्पुवु ≡a ८ / ९ ९ पद्मलेश्याविशुद्धिस्थानंगळु मंदतरसंक्लेशस्थानंगळु तदेकभागबहुभागमात्रंगळप्पुवु ≡ a ८ / ९ ९ ९ शुक्ललेश्याविशुद्धिस्थानंगळु मंदतमसंक्लेशस्थानंगळु शेषैकभागमात्रंगळप्पुवु ≡ a १ / ९ ९ ९ ई कृष्णलेश्याविषयारुं स्थानंगळोळु प्रत्येकमशुभंगळोळुत्कृष्टदिदं जघन्यपर्य्यंतं शुभंगळोळं जघन्यदिदमुत्कृष्टपर्य्यंतमसंख्यातलोकमात्रषट्स्थानपतितहानिवृद्धियुक्तस्थानंगळप्पुवु खलु नियमदिदं ।

असुहाणं वरमज्झिमअवरंसे किण्हणीलकाउतिए ।
परिणमदि कमेणप्पा परिहाणीदो किलेसस्स ॥५०१॥

अशुभानां वरमध्यमावरांशे कृष्णनीलकपोतत्रये परिणमति क्रमेणात्मा परिहानितः संक्लेशस्य ।

कृष्णनीलकपोतत्रिस्थानंगळ अशुभंगळप्पुत्कृष्टमध्यमजघन्यांशंगळोळु जीवं संक्लेशहानियिदं क्रमदिदं परिणमिसुगुं ।

लोकभक्तैकभागमात्रेषु ≡ a । १ / ९ तेजोलेश्यामन्दसंक्लेशस्थानानि तदसंख्यातलोकभक्तबहुभागमात्राणि ≡ a । ८ / ९ । ९ पद्मलेश्याविशुद्धिस्थानानि मन्दतरसंक्लेशस्थानानि तदेकभागबहुभागमात्राणि ≡ a । ८ / ९ । ९ । ९ शुक्ललेश्याविशुद्धिस्थानानि मन्दतमसंक्लेशस्थानानि शेषैकभागमात्राणि ≡ a । १ / ९ । ९ । ९ । एतेषु कृष्णलेश्यादिषट्स्थानेषु प्रत्येकमशुभेषु उत्कृष्टाज्जघन्यपर्यन्तं शुभेषु च जघन्यादुत्कृष्टपर्यन्तं असंख्यातलोकमात्रषट्स्थानपतितहानिवृद्धिस्थानानि भवन्ति खलु-नियमेन ॥५००॥

कृष्णनीलकपोतत्रिस्थानेषु अशुभेषूत्कृष्टमध्यमजघन्यांशेषु जीवः संक्लेशहानितः क्रमेण परिणमति ॥५०१॥

नीललेश्या सम्बन्धी तीव्रतर संक्लेश स्थान हैं। शेष रहे एक भाग प्रमाण कपोतलेश्या सम्बन्धी तीव्र संक्लेश स्थान हैं। पहले कषायोंके उदय स्थानोंमें असंख्यात लोकसे भाग देकर जो एक भाग प्रमाण शुभ लेश्या सम्बन्धी स्थान कहे थे वे तेज, पद्म और शुक्लके भेदसे तीन प्रकारके हैं। उनमें असंख्यात लोकसे भाग देकर बहुभाग प्रमाण तेजोलेश्या सम्बन्धी मन्द संक्लेश स्थान हैं। शेष बचे एक भागमें पुनः असंख्यात लोकसे भाग देकर बहुभाग प्रमाण पद्मलेश्या सम्बन्धी मन्दतर संक्लेशस्थान है। शेष रहे एक भाग प्रमाण शुक्ल लेश्या सम्बन्धी मन्दतम संक्लेश स्थान हैं। इन कृष्णलेश्या आदि सम्बन्धी छह स्थानोंमें-से प्रत्येकमें अशुभमें तो उत्कृष्टसे जघन्य पर्यन्त और शुभ लेश्याओंमें जघन्यसे उत्कृष्ट पर्यन्त असंख्यात लोकमात्र षट्स्थान पतित हानि-वृद्धि स्थान नियमसे होते हैं ॥५००॥

यदि जीवके संक्लेश परिणामोंमें हानि होती है तो वह अशुभ कृष्ण नील और कपोत लेश्याओंके उत्कृष्ट, मध्यम और जघन्य अंशोंमें क्रमसे परिणमन करता है अर्थात् उस लेश्याके उत्कृष्ट अंशसे मध्यममें और मध्यमसे जघन्यरूप परिणमन करता है ॥५०१॥

भागमसंख्यातभागं संख्यातभागं संख्यातगुणमसंख्यातगुणमनंतगुणमेंब हानिवृद्धिगळ नामंगळु मुत्कृष्टसंख्यातमुमसंख्यातलोकमुं सर्व्वजीवराशियुमेंब प्रमाणंगळु भागक्रमदोळं गुणितक्रमदोळमियेयप्पुवेंबु श्रुतज्ञानमार्ग्गणेयोळु पेळ्द क्रममिल्लिपुमरियल्पडुगुमेंबुदु तात्पर्य्यं ॥ नाल्कनेय संक्रमनाधिकारंतिद्दुदु ॥ अनंतरं कर्म्माधिकारमं गाथाद्वयदिदं पेळ्दपं :—

श्रुतज्ञानमार्गणायां उक्तक्रमेणैव भवन्ति। तत्र अनन्तभागः असंख्यातभागः संख्यातभागः संख्यातगुणः असंख्यातगुणः अनन्तगुणश्चेति नामानि। उत्कृष्टसंख्यातमसंख्यातलोकः सर्वजीवराशिश्चेति भागक्रमे गुणितक्रमे च प्रमाणानि भवन्ति ॥५०६॥ इति संक्रमणाधिकारश्चतुर्थः ॥ अथ कर्माधिकारं गाथाद्वयेनाह—

नाम और उनका प्रमाण पहले श्रुतज्ञानमार्गणामें जैसा कहा है वैसा ही जानना। उनके नाम अनन्तभाग, असंख्यात भाग, संख्यात भाग, संख्यात गुण, असंख्यात गुण और अनन्त गुण हैं। उनका प्रमाण जीवराशि, असंख्यात लोक और उत्कृष्ट संख्यात क्रमसे हैं। यह भाग और गुणेका प्रमाण है ॥५०६॥

विशेषार्थ—अनन्त भाग, असंख्यात भाग, संख्यात भाग, संख्यात गुण, असंख्यात गुण, अनन्त गुण ये छह स्थानोंके नाम हैं। इनका प्रमाण गुणकार और भागहारमें पूर्ववत् जानना। पूर्वमें वृद्धिका अनुक्रम कहा है हानिमें उससे उल्टा अनुक्रम है। वही कहते हैं। कपोतलेश्याके जघन्यसे लगाकर कृष्णलेश्याके उत्कृष्ट पर्यन्त विवक्षा हो तो क्रमसे संक्लेशकी वृद्धि होती है। यदि कृष्णलेश्याके उत्कृष्टसे लगाकर कपोतलेश्याके जघन्य पर्यन्त विवक्षा हो तो संक्लेशकी हानि होती है। तथा पीतके जघन्यसे लगाकर शुक्लके उत्कृष्ट पर्यन्त विवक्षा हो तो क्रमसे विशुद्धिकी वृद्धि होती है। यदि शुक्लके उत्कृष्टसे लगाकर पीतके जघन्य पर्यन्त विवक्षा हो तो क्रमसे विशुद्धिकी हानि होती है। सो वृद्धिमें षट्स्थानपतित वृद्धि और हानिमें षट्स्थानपतित हानि जानना।

पूर्वमें कहा था कि सूच्यंगुलके असंख्यातवें भाग मात्र बार अनन्त भागवृद्धि होनेपर एक बार अनन्त गुणवृद्धि होती है। उसमें अनन्त गुणवृद्धिरूप स्थान नवीन षट्स्थान पतित वृद्धिका प्रारम्भरूप प्रथम स्थान है। उसके पहले जो अनन्त भाग वृद्धिरूप स्थान है वह विवक्षित षट्स्थानपतित वृद्धिका अन्तस्थान है। नवीन षट्स्थानपतित वृद्धिके अनन्त गुणवृद्धिरूप प्रथम स्थानके आगे सूच्यंगुलके असंख्यातवें भाग मात्र अनन्त भागवृद्धिरूप स्थान होते हैं उसके आगे पूर्वोक्त अनुक्रम जानना।

यहाँपर कृष्णलेश्याका उत्कृष्ट स्थान षट्स्थानपतितका अन्त स्थानरूप होनेसे पूर्वस्थानसे अनन्तभाग वृद्धिरूप है। और कृष्णलेश्याका जघन्य स्थान षट्स्थान पतितका प्रारम्भरूप प्रथम स्थान है। उसके पूर्व नीललेश्याका उत्कृष्ट स्थान उससे अनन्त गुण वृद्धिरूप है। तथा कृष्णलेश्याके जघन्यका समीपवर्ती स्थान उस जघन्य स्थानसे अनन्त भाग वृद्धिरूप है। हानिकी अपेक्षा कृष्णलेश्याके उत्कृष्ट स्थानसे उसके समीपवर्ती स्थान अनन्त भाग हानिको लिये है। कृष्णलेश्याके जघन्य स्थानसे नीललेश्याका उत्कृष्ट स्थान अनन्त गुण हानिको लिये है। इसी प्रकार अन्य स्थानोंमें भी जानना ॥५०६॥

चतुर्थ संक्रमण अधिकार समाप्त हुआ। अब कर्माधिकार दो गाथाओंसे कहते हैं—

मत्ते कृष्णलेश्येयनुळ्ळ जीवनक्कुं ॥

मंदो बुद्धिविहीणो णिव्विण्णाणी य विसयलोलो य ।
माणी माई य तहा आलस्सो चेव भेज्जो य ॥५१०॥

मंदो बुद्धिविहीनो निर्व्विज्ञानी च विषयलोलश्च । मानी मायी च तथा आलस्यश्चैव भेद्यश्च ॥

मंदः स्वच्छंदसंज्ञिकनुं क्रियेगळोळुमंदं मेणु बुद्धिविहीनः वर्त्तमानकार्य्यानभिज्ञनुं । निर्व्विज्ञानी च विज्ञानविहीननुं । विषयलोलश्च विषयंगळोळु स्पर्शादिबाह्येंद्रियार्त्थंगळोळु लंपटनुं । मानी अहंकारियुं । मायी च कुटिलवृत्तियुं तथा आलस्यश्चैव क्रियेगळोळु कर्त्तव्यंगळोळु कुंठनुं । भेद्यश्च पेर्रारिंदमोळगरियल्पडुवनुमेंदिंतु कृष्णलेश्येय जीवलक्षणमक्कुं ॥

णिद्दावंचणबहुलो धणधण्णे होदि तिव्वसण्णा य ।
लक्खणमेयं भणियं समासदो णीललेस्सस्स ॥५११॥

निद्रावंचनाबहुलः धनधान्ये भवति तीव्रसंज्ञश्च । लक्षणमेतद् भणितं समासतो नीललेश्यस्य ॥

निद्राबहुलनुं वंचनाबहुलनुं धनधान्यंगळोळु तीव्रसंज्ञेयनुळ्ळनुं धनधान्यंगळोळुतीव्रसंज्ञेयनुळ्ळनुं एंदिंती लक्षणं संक्षेपदिंदं नीललेश्येयनुळ्ळ जीवंगे पेळल्पट्टुदु ॥

रूसइ णिंदइ अण्णे दूसइ बहुसो य सोयभयबहुलो ।
असुयइ परिभवइ परं पसंसये अप्पयं बहुसो ॥५१२॥

रोषति निंदत्यन्यान् दुष्यति बहुशश्च शोकभयबहुलः । असूयति परिभवति परं प्रशंसत्यात्मानं बहुशः ।

एतल्लक्षणं तु—पुनः कृष्णलेश्यस्य भवति ॥५०९॥

मन्दः—स्वच्छन्दक्रियासु मन्दो वा, बुद्धिविहीनः वर्तमानकार्यानभिज्ञः, निर्विज्ञानी च—विज्ञानरहितश्च विषयलोलश्च—स्पर्शादिबाह्येन्द्रियार्थेषु लम्पटश्च, मानी—अभिमानी, मायी च—कुटिलवृत्तिश्च तथा आलस्यश्चैवं क्रियासु कर्तव्येषु कुण्ठश्चैव भेद्यश्च परेणानवबोध्याभिप्रायश्च एतदपि कृष्णलेश्यस्य लक्षणं भवति ॥५१०॥

निद्राबहुलः वञ्चनबहुलः धनधान्येषु तीव्रसंज्ञश्च इत्येतल्लक्षणं संक्षेपेण नीललेश्यस्य भणितम् ॥५११॥

हो, दुष्ट और निर्दय हो, किसीके वशमें न आता हो, ये कृष्णलेश्यावालेके लक्षण हैं ॥५०९॥

स्वच्छन्द अथवा कार्य करनेमें मन्द हो, बुद्धिहीन हो—वर्तमान कार्यको न जानता हो, अज्ञानी हो, स्पर्शन आदि इन्द्रियोंके विषयमें लम्पट हो, अभिमानी हो, कुटिल वृत्तिवाला मायाचारी हो, कर्तव्य कर्ममें आलसी हो, दूसरोंके द्वारा जिसका अभिप्राय न जाना जा सके ये सब भी कृष्ण लेश्याके लक्षण हैं ॥५१०॥

बहुत सोता हो, दूसरोंको खूब ठगता हो, धन्य-धान्यकी तीव्र लालसा हो ये संक्षेपसे नीललेश्यावालेके लक्षण हैं ॥५११॥

लेश्यामध्यमांशंगळें टप्पुवष्टापकर्षंगळिनवरुत्पत्तिक्रममं पेळ्दनंतरं शेषाष्टादशांशंगळु चतुर्गति-गमनकारणंगळें दु पेळ्दपं ।

सेसट्ठारस अंसा चउगइगमणस्स कारणा होंति ।
सुक्कुक्कस्संसमुदा सव्वट्ठं जांति खलु जीवा ॥५१९॥

शेषाष्टादशांशाश्चतुर्गतिगमनस्य कारणानि भवंति । शुक्लोत्कृष्टांशमृताः सर्वार्थं यांति खलु जीवाः ।

आयुर्बंधनयोग्यलेश्यामध्यमांशंगळनेंटं कळेदुळिदष्टादशलेश्यांशंगळु चतुर्गतिगमनकारणंगळप्पुववरोळु शुक्ललेश्योत्कृष्टांशदिदं मृतराद जीवंगळु सर्वार्थसिद्धींद्रकदोळु याति पुट्टुवरु खलु नियमदिदं ।

अवरंसमुदा होंति सदारदुगे मज्झिमंसगेण मुदा ।
आणदकप्पादुवरिं सव्वट्ठाइल्लगे होंति ॥५२०॥

अवरांशमृता भवंति शतारद्विके मध्यमांशेन मृताः । आनतकल्पादुपरि सर्वार्थादिमके भवंति ।

शुक्ललेश्या जघन्यांशदिदं मृतराद जीवंगळु शतारसहस्रारकल्पद्विकदोळु भवंति पुट्टुवरु । शुक्ललेश्यामध्यमांशदिदं मृतराद जीवंगळु आनतकल्पदिदं मेले सर्वार्थसिद्धींद्रकदकादियागि विजयादिविमानावसानमादुववरोळु यथासंभवमागि भवंति पुट्टुवरु ।

पम्मुक्कस्संसमुदा जीवा उवजांति खलु सहस्सारं ।
अवरंसमुदा जीवा सणक्कुमारं च माहिंदं ॥५२१॥

पद्मोत्कृष्टांशमृताः जीवा उपयांति खलु सहस्रारं । अवरांशमृता जीवाः सनत्कुमारं च माहेंद्रं ॥

धिकं २१ । ५ । ४ । ५ । ४ । ५ । ४ । ५ । ४ । ५ । ४ । ५ एवमेकापकर्षस्योत्कृष्टपर्यन्तं नीते द्वात्रिंश-
४ । ४ । ४ । ४ । ४

विकल्पा भवन्ति ७२ एवमायुर्बन्धयोग्ये लेश्यामध्यमांशानामष्टानामष्टापकर्षैरुत्पत्तिक्रम उक्तः ॥५१८॥

तेभ्यो मध्यमांशेभ्यः शेषाः अष्टादशांशाः चतुर्गतिगमनकारणानि भवन्ति । तेषु मध्ये शुक्ललेश्योत्कृष्टांशेन मृता जीवाः सर्वार्थसिद्धीन्द्रके यान्ति–उत्पद्यन्ते खलु नियमेन ॥५१९॥

शुक्ललेश्याजघन्यांशेन मृता जीवाः शतारसहस्रारकल्पद्विके भवन्ति–उत्पद्यन्ते । शुक्ललेश्यामध्यमांशेन मृता जीवाः आनतकल्पादुपरिसर्वार्थसिद्धीन्द्रकस्यादिमविजयादिविमानपर्यन्तेषु यथासंभवमुत्पद्यन्ते ॥५२०॥

इस प्रकार आयुबन्धके योग्य लेश्याके आठ मध्यम अंशोंकी आठ अपकर्षोंके द्वारा उत्पत्तिका क्रम कहा ॥५१८॥

उन मध्यम अंशोंसे शेष रहे अठारह अंश चारों गतियोंमें गमनके कारण होते हैं। उनमें-से शुक्ललेश्याके उत्कृष्ट अंशसे मरे जीव सर्वार्थसिद्धि नामक इन्द्रक विमानमें नियमसे उत्पन्न होते हैं ॥५१९॥

शुक्ललेश्याके जघन्य अंशसे मरे जीव शतार सहस्रार कल्पोंमें उत्पन्न होते हैं। शुक्ललेश्याके मध्यम अंशसे मरे जीव आनतकल्पसे ऊपर और सर्वार्थसिद्धि नामक इन्द्रक विजयादि विमान पर्यन्त यथासम्भव उत्पन्न होते हैं ॥५२०॥

किण्हवरंसेण मुदा अवधिट्ठाणम्मि अवरअंसमुदा ।
पंचमचरिमतिमिस्से मज्झे मज्झेण जायंते ॥५२४॥

कृष्णवरांशेन मृताः अवधिस्थाने अवरांशमृताः । पंचमचरमतिमिश्रे मध्ये मध्येन जायंते ॥५२४॥

कृष्णलेश्योत्कृष्टांशदिंद मृतराद जीवंगळु सप्तमपृथ्वियोळोंदे पटलमक्कुमदरवधिस्थानेंद्रक बिलदोळु जायंते पुट्टुवरु। कृष्णलेश्याजघन्यांशदिदं मृतराद जीवंगळु पंचमपृथ्विय चरमपटल तिमिश्रेंद्रकबिलदोळु जायंते पुट्टुवरु। कृष्णलेश्यामध्यमांशदिदं मृतराद जीवंगळु सप्तमपृथ्विय अवधिस्थानेंद्रकद चतुःश्रेणिबद्धंगळोळं आ बिलदिदं मेलण षष्ठपृथ्वियपटलत्रयदोळं पंचमपृथ्विय चरमपटलदोळु तत्तद्योग्यमागि जायंते पुट्टुवरु।

णीलुक्कस्संसमुदा पंचमअंधिंदयम्मि अवरमुदा ।
वालुकसंपज्जलिदे मज्झे मज्झेण जायंते ॥५२५॥

नीलोत्कृष्टांशमृताः पंचम अंध्रेंद्रके अवरमृताः । वालुकासंप्रज्वलिते मध्ये मध्येन जायंते ॥

नीललेश्योत्कृष्टांशदिदं मृतराद जीवंगळु पंचमपृथ्वियपटलपंचकदोळु द्विचरमपटल अंध्रेंद्रकबिलदोळु जायंते पुट्टुवरु। पंचमपटलदोळं केलंबरु पुट्टुवरवु कारणमागि पंचमारिष्टेयोळु चरमपटलदोळु कृष्णलेश्याजघन्यांशदिदं नीललेश्योत्कृष्टांशदिदमुं, मृतराद केलवु जीवंगळु पुट्टुवरेंबी विशेषमरियल्पडुगुं। नीललेश्याजघन्यांशदिदं मृतराद जीवंगळु वालुकाप्रभेयनवपटलं

कृष्णलेश्योत्कृष्टांशेन मृता जीवाः सप्तमपृथिव्यामेकमेव पटलं तस्यावधिस्थानेन्द्रके जायन्ते। कृष्णलेश्याजघन्यांशेन मृता जीवाः पञ्चमपृथ्वीचरमपटलस्य तिमिश्रेन्द्रके जायन्ते। कृष्णलेश्यामध्यमांशेन मृता जीवाः तदवधिस्थानेन्द्रकस्य चतुःश्रेणीबद्धेषु षष्ठपृथ्वीपटलत्रये पञ्चमपृथ्वीचरमपटले च तत्तद्योग्यतया जायन्ते ॥५२४॥

नीललेश्योत्कृष्टांशेन मृता जीवाः पञ्चमपृथ्वीद्विचरमपटलस्यान्ध्रेन्द्रके जायन्ते। केचित् पञ्चमपटलेऽपि जायन्ते। ततोऽरिष्टाचरमपटले कृष्णलेश्याजघन्यांशेन नीललेश्योत्कृष्टांशेनापि मृताः केचिज्जीवाः उत्पद्यन्ते।

कृष्णलेश्याके उत्कृष्ट अंशसे मरे जीव सातवीं पृथिवीमें एक ही पटल है उसके अवधिस्थान नामक इन्द्रक बिलमें उत्पन्न होते हैं। कृष्णलेश्याके जघन्य अंशसे मरे जीव पाँचवी पृथ्वीके अन्तिम पटल सम्बन्धी तिमिश्र नामक इन्द्रक बिलमें उत्पन्न होते हैं। कृष्णलेश्याके मध्यम अंशसे मरे जीव अवधिस्थान नामक इन्द्रकके चारों दिशा सम्बन्धी श्रेणीबद्ध बिलोंमें, छठी पृथ्वीके तीनों पटलोंमें और पाँचवीं पृथ्वीके अन्तिम पटलमें अपनी अपनी योग्यतानुसार उत्पन्न होते हैं ॥५२४॥

नीललेश्याके उत्कृष्ट अंशसे मरे जीव पाँचवीं पृथ्वीके द्विचरम पटलके आन्ध्रेन्द्रकमें उत्पन्न होते हैं। कोई-कोई पाँचवें पटलमें भी उत्पन्न होते हैं। अरिष्ट पृथ्वीके अन्तिम पटलमें कृष्णलेश्याके जघन्य अंशसे और नीललेश्याके उत्कृष्ट अंशसे भी मरे कोई-कोई जीव उत्पन्न होते हैं इतना विशेष जानना। नीललेश्याके जघन्य अंशसे मरे जीव बालुकाप्रभा नामक तीसरी पृथ्वीके नौ पटलोंमें-से अन्तिम पटल सम्बन्धी संप्रज्वलित इन्द्रकमें उत्पन्न

१. म° क बिर्दिदं मेले, षष्ठपृथ्वि मघवियोळु पंचमपृथ्वि, अरिष्टेयेंबुददर पटल पंचकदोळु चरमपटलदिदं केळगे पद्य।

किण्हचउक्काणं पुण मज्झंसमुदा हु भवणगादितिये।
पुढवी-आउवणप्फइजीवेसु हवंति खलु जीवा ॥५२७॥

कृष्णचतुष्काणां पुनः मध्यमांशमृताः खलु भवनकादित्रये। पृथिव्यब्वनस्पति[illegible] खलु जीवाः ॥

कृष्णनीलकापोततेजोलेश्याचतुष्टयद मध्यमांशंगळिंदं मृतराद कर्म्मभूमि[illegible] भोगभूमितिर्य्यग्मनुष्यरु भवनत्रयदोळु भवंति परिणमंति पुट्टुवरु। ततु [illegible] भोगभूमिजतिर्य्यग्मनुष्यमिथ्यादृष्टिगळु तेजोलेश्यामध्यमांशदिदं मृतरादवर्गळु [illegible] पुट्टुव कारणदिदं तेजोलेश्यासंभवमुमरियल्पडुगुं। तु मत्ते कृष्णादिचतुर्लेश्यामध्य[illegible] मृतराद तिर्य्यग्मनुष्यरुं भवनवानज्योतिष्करुं सौधर्म्मैशानकल्पजरुगळुमप्प मिथ्यादृ[illegible] बादरपर्य्याप्तपृथ्वीकायिकजीवंगळोळं बादरपर्य्याप्ताप्कायिकजीवंगळोळं प्रत्येक[illegible] कायिकजीवंगळोळं भवंति—परिणमंति पुट्टुवरु। भवनत्रयादि जीवंगळोळ[illegible] तेजोलेश्यासंभवमरियल्पडुगुं।

किण्हतियाणं मज्झिमअंसमुदा तेउवाउवियलेसु।
सुरणिरया सगलेस्सहि णरतिरियं जांति सगजोगं ॥५२८॥

कृष्णत्रयाणां मध्यमांशमृताः तेजोवायुविकलेषु। सुरनारकाः स्वलेश्याभि[illegible] यांति स्वयोग्यं ॥

कृष्णाद्यशुभलेश्यात्रयंगळ मध्यमांशदिदं मृतराद तिर्य्यग्मनुष्यरुगळु तेजस्कायिक[illegible] कायिकविकलत्रेय असंज्ञिपंचेंद्रियसाधारणवनस्पतिगळेंबी जीवंगळोळु जांति जायंते पुट्टु[illegible]

अत्र पुनःशब्दो विशेषप्ररूपकोऽस्ति। तेन कृष्णादित्रिलेश्यामध्यमांशमृताः कर्मभूमितिर्यग्मनुष्यमिथ्या[illegible] तेजोलेश्यामध्यमांशमृताः भोगभूमितिर्यग्मनुष्यमिथ्यादृष्टयश्च भवनत्रये खलु उत्पद्यन्ते इति ज्ञातव्यम्। पु[illegible] कृष्णादिचतुर्लेश्यामध्यमांशमृततिर्यग्मनुष्यभवनत्रयसौधर्मैशानमिथ्यादृष्टयः बादरपर्याप्तपृथ्व्यप्कायिकेषु [illegible] वनस्पतिकायिकेषु चोत्पद्यन्ते।[3] भवनत्रयाद्यपेक्षया अत्रापि तेजोलेश्यासंभवो बोद्धव्यः ॥५२७॥

कृष्णाद्यशुभलेश्यात्रयस्य मध्यमांशमृततिर्यग्मनुष्याः तेजोवायुविकलत्रयासंज्ञिसाधारणवनस्पति[illegible]

इस गाथामें 'पुनः' शब्द विशेष कथनका सूचक है। अतः कृष्ण आदि तीन लेश्याओं के मध्यम अंशसे मरे कर्मभूमिके मिथ्यादृष्टि तिर्यंच और मनुष्य तथा तेजोलेश्याके मध्य[illegible] अंशसे मरे भोगभूमि या मिथ्यादृष्टि तिर्यंच और मनुष्य भवनवासी व्यन्तर और ज्योतिष्क देवोंमें उत्पन्न होते हैं यह जानना। तथा कृष्ण आदि चार लेश्याके मध्यम अंशसे मरे तिर्यंच मनुष्य, भवनवासी, व्यन्तर, ज्योतिषी और सौधर्म ऐशान स्वर्गके देव ये सब मिथ्यादृष्टि बादर पर्याप्तक पृथ्वीकायिक, जलकायिक और वनस्पतिकायिकोंमें उत्पन्न होते हैं। भवन[illegible] त्रिककी अपेक्षा यहाँ भी तेजोलेश्या सम्भव है यह जानना ॥५२७॥

कृष्ण आदि तीन अशुभ लेश्याओंके मध्यम अंशसे मरे तिर्यंच और मनुष्य तेज[illegible]

---

१. क पर्याप्तबादरप्रत्येकवन°। २. म °वरुगळेंबी। ३. ब. अत्रापि तेजोलेश्या भवनत्रयाद्यपेक्षया[illegible]
४ ब °वर्त्य°।

घतरोळसंज्ञिनः असंज्ञिपंचेंद्रियपर्याप्तजीवंगे कृष्णाद्यशुभलेश्यात्रयमुं तेजोलेश्येयुमक्कुमेकें दोडा असंज्ञिजीवं कपोतलेश्येयिवं मृतनागि घर्मेयोळ्पुट्टुगुं। तेजोलेश्येयिवं मृतनागि भवनव्यंतरदेवगतिद्वयदोळ्पुट्टुगुमशुभलेश्यात्रयदिवं मृतनागि नरतिर्य्यग्गतिद्वयदोळ्पुट्टुगुमप्पुदरिदं। संज्ञिपंचेंद्रियलब्ध्यपर्याप्तकनोळं मनुष्यलब्ध्यपर्याप्तकनोळं अपि शब्ददिनसंज्ञिपंचेंद्रियलब्ध्यपर्य्याप्तकनोळं सासादनसम्यग्दृष्टी निर्वृत्यपर्याप्तकसासादननोळमासासादननुं।

["णिरयं सासणसम्मो ण गच्छदित्ति य ण तस्स णिरयाऊ। एंदु,

"णहि सासणो अपुण्णे साहारणसुहुमगे य तेउदुगे॥" एंदितु]

तेजस्कायिकलब्ध्यपर्य्याप्तकरोळं साधारणजीवंगळोळं नारकरोळं सूक्ष्मजीवंगळोळं वातकायिकंगळोळं संभविसनप्पुदरिदं भवनत्रयापर्य्याप्तकरोळं शेषतिर्य्यग्मनुष्यरोळं संभविसुगुमा निर्वृत्यपर्य्याप्तकसासादननोळं अशुभत्रयमो कृष्णाद्यशुभलेश्यात्रयमेयक्कुं। तिर्य्यग्मनुष्योपशमसम्यग्दृष्टिगळ्गे तत्कालाभ्यंतरदोळु मृत्युसंक्लिष्टरादोडमवर्गोळगे देशसंयतरोळेंतंतेकृष्णनीलकपोतलेश्यात्रयंगळागवेंदिंतु तद्विराधकसासादननोळु पर्य्याप्तविषयदोळशुभलेश्यात्रयमेयक्कुमें दरियुवुदु।

भोगापुण्णगसम्मे काउस्स जहण्णियं हवे णियमा।

सम्मे वा मिच्छे वा पज्जत्ते तिण्णि सुहलेस्सा॥५३१॥

भोगापूर्णसम्यग्दृष्टौ कापोतस्य जघन्यं भवेन्नियमात्। सम्यग्दृष्टौ वा मिथ्यादृष्टौ वा पर्य्याप्ते तिस्रः शुभलेश्याः॥

शुभलेश्या एव। असंज्ञिपर्याप्तस्य तत्त्रयं तेजोलेश्या च, कुतः? तस्य कपोतमृतस्य घर्मायां तेजोमृतस्य भवनव्यन्तरयोरशुभत्रयमृतस्य संज्ञिनरतिर्यग्गत्योश्च उत्पादात्। संज्ञिलब्ध्यपर्याप्तकतिर्यग्मनुष्यमिथ्यादृष्टौ असंज्ञिलब्ध्यपर्याप्तके तिर्यग्मनुष्यभवनत्रयनिर्वृत्यपर्याप्तकसासादने च कृष्णाद्यशुभत्रयमेव। तिर्यग्मनुष्योपशमसम्यग्दृष्टीनां सम्यक्त्वकालाभ्यन्तरे मृत्यु संक्लेशेऽपि देशसंयतवत् तत्त्रयं नास्ति तथापि तद्विराधकसासादनापर्याप्तानामस्तीति ज्ञातव्यम्॥५३०॥

उनमें-से एकेन्द्रिय और विकलत्रय जीवोंमें कृष्णादि तीन अशुभ लेश्या ही होती हैं। असंज्ञी पंचेन्द्रिय पर्याप्तकके कृष्णादि तीन और तेजोलेश्या होती है। क्योंकि यदि वह कपोतलेश्यासे मरता है तो घर्मा नरकमें उत्पन्न होता है। तेजोलेश्यासे मरता है तो भवनवासी और व्यन्तरोंमें उत्पन्न होता है। और यदि तीन अशुभ लेश्याओंसे मरता है तो मनुष्यगति, तिर्यंचगतिमें उत्पन्न होता है। संज्ञी लब्ध्यपर्याप्तक तिर्यंच और मनुष्य मिथ्यादृष्टिमें 'अपि' शब्दसे असंज्ञी लब्ध्यपर्याप्तक तिर्यंचमें तथा सासादन गुणस्थानवर्ती निर्वृत्यपर्याप्त तिर्यंच, मनुष्य और भवनत्रिकमें कृष्णादि तीन अशुभलेश्या ही होती हैं। उपशम सम्यग्दृष्टि तिर्यंच और मनुष्योंके सम्यक्त्वकालके भीतर अतिसंक्लेशमें भी देशसंयतकी तरह तीन अशुभ लेश्या नहीं होती हैं। तथापि उपशम सम्यक्त्वके विराधक सासादन सम्यग्दृष्टिके अपर्याप्त अवस्थामें

उपशांतकषायादिगुणस्थानत्रयदोळु कषायोदयरहितमागुत्तिरलुमवरोळु पेळल्पट्ट आवुदो लेश्येयदु । तु मत्ते भूतपूर्व्वगतिन्यायदिनुपशांतकषायवीतरागछद्मस्थनोळं क्षीणकषायवीतरागछद्मस्थनोळं सयोगिकेवलिजिननोळं भूतपूर्व्वगतिन्यायदिदमेयक्कुम ।। योगप्रवृत्तिर्म्मुख्यदिं योगप्रवृत्तिर्लेश्या येंदितु योगप्रवृत्तिप्रधानत्वदिदं तत्रिस्थानदोळु लेश्यासंभवमक्कुं ।

> तिण्हं दोण्हं दोण्हं छण्हं दोण्हं च तेरसण्हं च ।
> एत्तो य चोद्दसण्हं लेस्सा भवणादिदेवाणं ॥५३४॥

त्रयाणां द्वयोर्द्वयोः, षण्णां द्वयोश्च त्रयोदशानां च इतश्चतुर्दशानां लेश्या भवनादिदेवानां।

> तेऊ तेऊ तह तेऊपम्मा पम्मा य पम्मसुक्का य ।
> सुक्का य परमसुक्का भवणतिया पुण्णगे असुहा ॥५३५॥

तेजस्तेजस्तथा तेजःपद्मे पद्मा च पद्मशुक्ले च । शुक्ला च परमशुक्ला भवनत्रया पूर्णे अशुभाः ।

भवनत्रयद भवनादित्रिधामरर्गो पर्य्याप्तापेक्षेयिं तेजोलेश्याजघन्यमक्कुं । सौधर्मैशानद्वयद वैमानिकर्गे तेजोलेश्यामध्यमांशमक्कुं । सनत्कुमारमाहेंद्रद्वयद कल्पजर्ग्गे तेजोलेश्योत्कृष्टांशमुं पद्मलेश्याजघन्यमुमक्कुं । ब्रह्मब्रह्मोत्तरलांतवकापिष्ठशुक्रमहाशुक्रंगळेंबारु कल्पंगळ कल्पजर्ग्गे पद्मलेश्यामध्यमांशमक्कुं । शतारसहस्रारकल्पद्वयद वैमानिकर्ग्गे पद्मलेश्योत्कृष्टमुं शुक्ललेश्याजघन्यमुमक्कुं । आनतप्राणत आरणाच्युतंगळु नवग्रैवेयकंगळुमेंबितु पदिमूरर सुरर्ग्गे शुक्ललेश्यामध्यमांशमक्कुमिल्लिदं मेले अनुदिशानुत्तरविमानंगळ्पदिनाल्कर कल्पातीतजर्ग्गे शुक्ललेश्योत्कृष्टांश-

उपशान्तकषायादित्रिकषायगुणस्थानत्रये कषायोदयाभावेऽपि या लेश्या उच्यते सा भूतपूर्वगतिन्यायादेव । अथवा योगप्रवृत्तिर्लेश्येति योगप्रवृत्तिप्राधान्येन तत्र लेश्या भवति ॥५३३॥

भवनत्रयादिदेवानां लेश्योच्यते । तत्र पर्याप्तापेक्षया भवनत्रयस्य तेजोजघन्यांशः । सौधर्मैशानयोः तेजोमध्यमांशः । सानत्कुमारमाहेन्द्रयोः तेजउत्कृष्टांशपद्मजघन्यांशौ । ब्रह्मब्रह्मोत्तरादिषट्कस्य पद्ममध्यमांशः । शतारसहस्रारयोः पद्मोत्कृष्टांशशुक्लजघन्यांशौ । आनतादिचतुर्णां नवग्रैवेयकाणां च शुक्लमध्यमांशः । अत उपरि

उपशान्त कषाय आदि तीन गुणस्थानोंमें यद्यपि कषायका उदय नहीं है और बारहवें, तेरहवेंमें तो कषाय नष्ट ही हो गयी है। फिर भी वहाँ जो लेश्या कही जाती है वह भूतपूर्व गतिन्यायसे ही कही जाती है। अथवा योगकी प्रवृत्तिको लेश्या कहते हैं और योगकी प्रवृत्तिकी प्रधानता है इसलिए वहाँ लेश्या है ॥५३३॥

भवनत्रय आदि देवोंके लेश्या कहते हैं। पर्याप्तकी अपेक्षा भवनवासी, व्यन्तर और ज्योतिषी देवोंके तेजोलेश्याका जघन्य अंश है। सौधर्म ऐशानमें तेजोलेश्याका मध्यम अंश है। सानत्कुमार माहेन्द्रमें तेजोलेश्याका उत्कृष्ट अंश और पद्मलेश्याका जघन्य अंश है। ब्रह्म-ब्रह्मोत्तर आदि छह स्वर्गोंमें पद्मलेश्याका मध्यम अंश है। शतार-सहस्रारमें पद्मका उत्कृष्ट अंश और शुक्लका जघन्य अंश है। आनत आदि चार स्वर्गोंमें और नौ ग्रैवेयकोंमें शुक्लका मध्यम अंश है। उससे ऊपर अनुदिश और अनुत्तर सम्बन्धी चौदह विमानोंमें

संचयमनाश्रयिसि द्रव्यतः प्रमाणं पेळल्पट्टुदु ।

खेत्तादो असुहतिया अणंतलोगा कमेण परिहीणा ।
कालादोतीदादो अणंतगुणिदा कमा हीणा ॥५३८॥

क्षेत्रतोऽशुभत्रयाः अनंतलोकाः क्रमेण परिहीनाः । कालावतीतादनंतगुणाः क्रमाद्धीनाः ॥

क्षेत्रप्रमाणदिदं अशुभत्रया जीवाः अशुभलेश्यात्रयद जीवंगळु अणंतलोगा अनंतलोक ≡ ≡ प्रमितंगळागुत्तं क्रमदिदं परिहीनंगळप्पुवु किंचिदूनक्रमंगळप्पुवु क्षेत्र कृ = ख नी ख − क ख = इल्लिपुं त्रैराशिकं माडल्पडुगुं प्र ≡ फ श १ । इ १३/३ लब्ध शला । ख । प्रमा श १ । फ ≡ इ ख । लब्ध ≡ ख । कालावतीतात् कालप्रमाणदिदं अशुभलेश्यात्रय जीवंगळु अतीतकालमं नोडलु अनंत-गुणिताः अनंतगुणितंगळागुत्तलुं क्रमाद्धीनाः क्रमहीनंगळप्पुवु । का । कृ । अ ख । नी अ ख − का अ ख = इल्लिपुं त्रैराशिकं माडल्पडुगुं । प्र अ । फ अ १ । इ १३/३ − लब्ध शलाका । ख । मतं प्र श १ । फ अ । इ । श ख । लब्ध अ ख ।

कपोतयोरपि ज्ञातव्यम् । कृ १३/३ − । नी १३/३ − । क १३/३ − । इति कालसंचयमाश्रित्य द्रव्यतः प्रमाणमुक्तम् ॥५३७॥

क्षेत्रप्रमाणेन अशुभत्रिलेश्याजीवाः अनन्तलोका अपि क्रमेण परिहीनाः किंचिदूनक्रमा भवन्ति । कृ ≡ ख । नी ≡ ख- । क ≡ ख ≡ । अत्र त्रैराशिकं प्र ≡ फ श १ । इ १३/३ − लब्धशलाकाः ख । पुनः प्र । श १ । फ ≡ । इ श ख । लब्धं ≡ ख । कालप्रमाणेनाशुभत्रिलेश्या जीवा अतीतकालादनन्तगुणिता अपि क्रमहीना भवन्ति । का कृ अ ख । नी अ ख− । क अ ख = । अत्रापि त्रैराशिकं-प्र अ फ श । १ इ १३/३ − लब्धशलाकाः ख । पुनः प्र श १ । फ अ । इ श ख । लब्धं अ ख ॥५३८॥

जीवोंके प्रमाणमें देनेपर जो लब्ध आवे उतना है। इसी तरह नील और कापोतलेश्यावालोंका प्रमाण लाना चाहिए। इस तरह कालकी अपेक्षा अशुभलेश्यावाले जीवोंका प्रमाण कहा ॥५३७॥

क्षेत्रप्रमाणकी अपेक्षा तीन अशुभलेश्यावाले जीव अनन्तलोक प्रमाण हैं किन्तु क्रमसे कुछ-कुछ हीन हैं। यहाँ प्रमाणराशि लोक, फलराशि एक शलाका, इच्छा राशि अपने-अपने जीवोंका प्रमाण। ऐसा करनेपर लब्धराशि मात्र अनन्त शलाका हुई। तथा प्रमाण एक शलाका, फल एक लोक, इच्छा अनन्त शलाका। ऐसा करनेपर लब्धराशि अनन्त लोकमात्र कृष्णादि लेश्यावाले जीवोंका प्रमाण होता है। तथा काल प्रमाणसे तीन अशुभ लेश्यावाले जीव अतीतकालके समयोंसे अनन्तगुने हैं। किन्तु क्रमसे हीन हैं। यहाँ भी त्रैराशिक करना। प्रमाणराशि अतीतकाल, फलराशि एक शलाका, इच्छाराशि अपने-अपने जीवोंका प्रमाण। ऐसा करनेपर लब्धराशिमात्र अनन्त शलाका हुई। फिर प्रमाण एक शलाका, फल एक अतीत काल, इच्छा अनन्त शलाका। ऐसा करनेपर लब्धराशि अनन्त अतीतकाल प्रमाण कृष्णादि लेश्यावाले जीव होते हैं ॥५३८॥

तेजोलेश्याजीवंगळु ज्योतिषिकजीवराशियं नोडलु साधिकमप्परदें तें दोडे ज्योतिष्कर भवनवासिगळुं व्यंतररुं सौधर्म्मद्वयकल्पजरुं संज्ञिपंचेंद्रियजीवंगळोळु केलवु जीवंगळुं मनुष्यरोळु केलवु जीवंगळुं एंदितावप्रकारद जीवराशिगळं कूडिदोडे तेजोलेश्या जीवंगळप्पुवल्लि ज्योतिष्कर पण्णट्ठिप्रमितप्रतरांगुलभक्तजगत्प्रतरप्रमितरप्परु ४। ६५= भवनवासिगळु घनांगुलप्रथममूलगुणितजगच्छ्रेणीमात्ररप्परु ।-१। व्यंतररु त्रिशतयोजनभक्तजगत्प्रतरप्रमितरप्परु । ४६५=८१=१० सौधर्म्मद्वयद कल्पजरु घनांगुलतृतीयमूलगुणितजगच्छ्रेणिप्रमितरप्परु ।—३॥ संज्ञिपंचेंद्रियतेजोलेश्याजीवंगळु :—

"जोइसियवाणजोणिणितिरिक्खपुरिसा य सण्णिणो जाया।
तत्तेउपम्मलेस्सा संखगुणूणा कमेणेदे॥"

एंदितु पंचेंद्रियसंज्ञिजीवराशियं नोडलुं संख्यातगुणहीनरप्परु ४। ६५=१ १ १ ११ मनुष्यरुं संख्यातरप्परितीवारुं राशिगळुं कूडिदोडे ज्योतिषिकरं नोडलु साधिकमप्पुवु ४। ६५=१ त्रिचु-सौधर्मनारिदं तेजोलेश्याजीवंगळोळेयल्पदुदु। पद्मलेश्येय जीवंगळुमा तेजोलेश्याजीवंगळं नोडलुं संख्यातगुणहीनमागियुं संज्ञितेजोलेश्याजीवंगळं नोडलु संख्यातगुणहीनरप्परप्पा राशियोळु पद्मलेश्या [illegible] मनुष्यरुमं साधिकं माडिदोडे प्रतरासंख्येयभागमेयक्कु। संदृष्टि—

तेजोलेश्याजीवाः ज्योतिष्कजीवराशितः साधिका भवन्ति । = = = १। कथं ? पण्णट्ठिप्रमप्रतरांगु-
४। ६५=१
लभक्तजगत्प्रतरमात्रज्योतिष्काः = घनांगुलप्रथममूलगुणितजगच्छ्रेणिमात्रभवनाः-१ त्रिशतयोजन-
४। ६५=
[illegible]भक्तजगत्प्रतरमात्रव्यन्तराः = • घनांगुलतृतीयमूलगुणितजगच्छ्रेणिमात्रसौधर्मद्वयजाः-
४। ६५=८१। १०
३ [illegible]संख्यातगुणहीनसंज्ञितिर्यंच = तावत्संख्यातगुणा
४। ६५=११११
[illegible] [illegible]। पद्मलेश्याजीवाः तेजोलेश्येभ्यः संख्यातगुणहीनाः। संज्ञितिर्यक्तेजोलेश्येभ्योऽपि

तेजोलेश्यावाले जीव ज्योतिषी देवोंकी राशिसे कुछ अधिक होते हैं। इसका हेतु यह है कि पैंसठ हजार पाँच सौ छत्तीस प्रतरांगुलका भाग जगत्प्रतरमें देनेसे जो लब्ध आवे [illegible] ज्योतिषी देव हैं। घनांगुलके प्रथम वर्गमूलसे गुणित जगच्छ्रेणि प्रमाण भवनवासी देव हैं। तीन सौ योजनके वर्गका भाग जगत्प्रतरमें देनेसे जो लब्ध आवे उतने व्यन्तर देव हैं। घनांगुलके तृतीय वर्गमूलसे गुणित जगच्छ्रेणिमात्र सौधर्म ऐशान स्वर्गके देव हैं। [illegible] संख्यातसे गुणित पण्णट्ठि (६५५३६) प्रमाण प्रतरांगुलसे भाजित जगत्प्रतर प्रमाण [illegible] तेजोलेश्यावाले जीव हैं। तथा संख्यात तेजोलेश्यावाले मनुष्य। इन सबको जोड़नेसे [illegible] तेजोलेश्यावाले जीव हैं। पद्मलेश्यावाले जीव तेजोलेश्यावाले जीवोंसे

१ [illegible]। [illegible] [illegible]। ३. ब. लेश्या अपि।

तेजोलेश्याजीवंगळु पद्मलेश्याजीवंगळुं प्रत्येकमसंख्येयकल्पगळागुत्तं तेजोलेश्याजीवंगळं नोडलु पद्मलेश्याजीवंगळु संख्यातगुणहीनंगळप्पुवु। ते क १। पद्म क ०। शुक्लाः शुक्ललेश्याजीवंगळु पल्यासंख्येयभागाः पल्यासंख्यातैकभागमात्रंगळप्पुवु प इंतु कालप्रमाणदिदं शुभलेश्यात्रयजीवंगळु
०
पेळल्पट्टुवु। अवधेरसंख्येयभागास्तेजस्त्रयो भवंतो भवंति अवधिज्ञानविकल्पंगळ असंख्येयभागंगळु प्रत्येकमागुत्तमा मूरु लेश्येगळ जीवंगळु संख्यातगुणहीनंगळुमसंख्यातगुणहीनंगळुमप्पुवु। ते ओ (१)
प ओ (१)। शु ओ (१) इंतु भावप्रमाणदिदं शुभलेश्यात्रयजीवंगळु पेळल्पट्टुवु :—
० ०१० ०

१३— कृ ३—	१३— नी ३।	१३— क ३।	ते ० ० १	प ० ०	शु ०
≡ख	≡ख —	≡ख =	≡ — १ ४६५१	≡ ४६५=१।१।१।१।१।१।मू	२ ०
अ ख	अ ख	अ ख =		क ०	प ०
के ख	के ख	के ख		ओ १ ०	ओ ०१०

इंतु पत्तनेय संख्याधिकारंतिद्दुवु।

अनंतरं क्षेत्राधिकारमं पेळ्वपं :—

तेजोद्वयजीवाः प्रत्येकमसंख्येयकल्पा अपि तेजोलेश्येभ्यः पद्मलेश्याः संख्यातगुणहीनाः ते क ०१। प क ०। शुक्ललेश्याः पल्यासंख्यातैकभागमात्रा भवन्ति प इति कालप्रमाणेन शुभलेश्यात्रयजीवा उक्ताः।
०
तेजस्त्रयजीवाः प्रत्येकं अवधिज्ञानविकल्पानामसंख्येयभागाः तथापि संख्यातासंख्यातगुणहीना भवन्ति ते ओ प ओ शु ओ इति भावप्रमाणेन शुभलेश्यात्रयजीवा उक्ताः ॥५४२॥ इति संख्याधिकारः ॥
० ०१ ०१०

अथ क्षेत्राधिकारमाह—

तेजोलेश्या और पद्मलेश्यावाले जीव प्रत्येक असंख्यात कल्पप्रमाण हैं फिर भी तेजोलेश्यावालोंसे पद्मलेश्यावाले संख्यातगुणा हीन हैं। शुक्ललेश्यावाले पल्यके असंख्यातवें भाग मात्र होते हैं। इस प्रकार काल प्रमाणसे तीन शुभलेश्यावाले जीवोंका प्रमाण कहा। तेजोलेश्या आदि तीन लेश्यावाले जीव प्रत्येक अवधिज्ञानके भेदोंके असंख्यातवें भाग हैं तथापि तेजोलेश्यावालोंसे पद्मलेश्यावाले संख्यातगुणे हीन हैं और पद्मलेश्यावालोंसे शुक्ललेश्यावाले असंख्यातगुणे हीन हैं। इस प्रकार भावप्रमाणसे तीन शुभलेश्यावाले जीवोंका प्रमाण कहा ॥५४२॥

इस प्रकार संख्याधिकार समाप्त हुआ। अब क्षेत्राधिकार कहते हैं—

१. म प्रती संदृष्टिर्न।

इंनु विशेषदिदं दशपदंगळप्पुवल्लि स्वस्थानस्वस्थानमें बुदेनें दोडे उत्पन्नग्रामादि क्षेत्रं स्वस्थानस्वस्थानमें बुदु, विवक्षितपर्य्यायपरिणतनिदं परिभ्रमिसल्कुचितक्षेत्रं विहारवत्स्वस्थानमें बुदु। वेदनादिवशदिदं निजशरीरदत्तणिदं जीवप्रदेशंगळ्गे बहिःप्रवेशदोळ् तत्प्रायोग्यविसर्प्पणं समुद्घातमें बुदु। परित्यक्तपूर्व्वभवंगे उत्तरभवप्रथमसमयदोळ् प्रवर्त्तनमनुपपादमें बुदु। इंती स्वस्थानस्वस्थानादिदशपदंगळोळ् स्वस्थानस्वस्थानदोळं वेदनासमुद्घातदोळं कषायसमुद्घातदोळं मारणांतिकसमुद्घातदोळमुपपाददोळमितो पंचपदंगळोळं कृष्णलेश्याजीवंगळ्गे क्षेत्रं सर्व्वलोकमेयक्कुमोयप्पु पदंगळोळं मुन्नं सख्याधिकारदोळ्पेळ्द कृष्णलेश्याजीवंगळ् सर्व्वसंसारिजीवराशिय किंचिदूनत्रिभागंगळप्पुववं संख्यातदिदं भागिसि बहुभागंगळ् स्वस्थानस्वस्थानदोळप्पुवें दु कोट्टु शेषैकभागमं मत्तं संख्यातदिदं भागिसि बहुभागमं वेदनासमुद्घातदोळप्पुवें दु कोट्टु शेषैकभागमं मत्तं संख्यातदिदं भागिसि बहुभागमं कषायसमुद्घातपददोळित्तु शेषैकभागमं फलराशियं माडि एकनिगोदजीवन एकभवायुःस्थितिप्रमाणमुच्छ्वासाष्टादशैकभागमप्पुमन्तर्मुहूर्त्तमेयक्कु २१॥ मा कालमं प्रमाणराशियं माडियों दु समयमनिच्छाराशियं माडि प्र २१। फ १३-१। इ स १ बंद लब्धमात्रं कृष्णलेश्याजीवंगळ् उपपादपददोळप्पुवु १३
३-५।५।५ ३-५।५५।२१

तत्र कृष्णलेश्याजीवराशिं १३— संख्यातेन भक्त्वा बहुभागः १३-४ स्वस्थानस्वस्थाने देयः। शेषैकभागस्य
३— ३-।५।
संख्यातभक्तबहुभागः १३-।४ वेदनासमुद्घाते देयः। शेषैकभागस्य संख्यातभक्तबहुभागः —१३-।४ कषाय-
३-।५।५ ३-५।५।५।
समुद्घाते देयः। शेषैकभागं फलराशिं कृत्वा, एकनिगोदभवायुरुच्छ्वासाष्टादशैकभागान्तर्मुहूर्तं २१ [illegible] प्र २१ फ १३-१। इ स १ लब्धमुपपादपदे देयं १३ एकस्मिन्नेव
३-५।५।५ ३-५।५।५।२१
[illegible] मारणान्तिकसमुद्घातकालान्तर्मुहूर्तेन गुणिते प्र स १। फ १३-। इ २१। लब्धं मूलराशिसंख्यात-
३-।५।५५।२१

[illegible] मारणान्तिकसमुद्घाते देयम् १३—पुनःकृष्णलेश्याजीव [illegible] राशि ४। ३- संख्यातेन भक्त्वा बहु-
३-३ ५—

[illegible] प्रमाण कहते हैं—कृष्णलेश्यावाले जीवोंकी पूर्वोक्त संख्यामें संख्यातसे भाग देकर बहुभाग प्रमाण स्वस्थानस्वस्थानवाले हैं। शेष एक भागमें संख्यातसे भाग देकर [illegible] बहुभाग [illegible] वेदना समुद्घातवाले हैं। शेष एक भागमें पुनः संख्यातसे भाग देकर जो बहुभाग [illegible] कषाय समुद्घातवाले जीव हैं। शेष एक भागको फलराशि [illegible] और [illegible] आयु उच्छ्वासके अठारहवें भाग प्रमाण अन्तर्मुहूर्त, [illegible] फलको इच्छाराशिसे गुणा कर [illegible] प्रमाणराशिका भाग देनेसे जितना प्रमाण आवे उतने जीव [illegible] हैं। [illegible] मारणान्तिक समुद्घातके काल अन्तर्मुहूर्तसे गुणा करके [illegible] मारणान्तिक समुद्घातवाले हैं। [illegible] पुनः कृष्णलेश्यावाले पर्याप्त-

मात्रघनांगुलगुणितजगच्छ्रेणीमात्रकृष्णलेश्यावैक्रियिकराशियं —६ प / ३ a संख्यातदिदं भागिसि बहुभागमं —६ प ४ / ३—a ५ स्वस्थानस्वस्थानदोळित्तु मत्तमितें शेषद शेषद संख्यातव बहुभाग-बहुभागंगळं विहारवत्स्वस्थानदोळं —६ प ४ a / ३—a । ५ वेदनासमुद्घातदोळं —६ प ४ a / ३—५ । ५५ कषायसमुद्घातदोळं —६ प ४ a / ३— । ५५५५ दातव्यंगळप्पुवु शेषैकभागं वैक्रियिकसमुद्घातदोळ्दातव्य-मक्कु —६ प १ a / ३— । ५५५५५ मिदं यथायोग्यवैकुर्वणावगाहनोत्पन्न संख्यातघनांगुलंगळिदं गुणिसुत्तं विरलु घनांगुलवर्गगुणितासंख्यातश्रेणीमात्रं वैक्रियिकसमुद्घातपददोळु क्षेत्रमक्कुं ।=a ६ । ६। इंती वशपदंगळ रचनासंदृष्टियं स्थापिसि रचनेयिदु :

भवति = मू २ १ । पुनः पल्यासंख्यातमात्रघनाङ्गुलगुणितजगच्छ्रेणि कृष्णलेश्यावैक्रियिकराशिं — ६ प / ३— a संख्यातेन भक्त्वा बहुभागं — ६ प ४ / ३—a । ५ स्वस्थानस्वस्थाने[2] दत्त्वा शेषशेषस्य संख्यातबहुभागसंस्थानबहुभागो विहारवत्स्वस्थाने—६ प ४ / ३— a ५ ५ वेदनासमुद्घाते — ६ प ४ / ३— a ५ ५ ५ कषायसमुद्घाते च ६ । प ४ / ३—a५५५५ पतितोऽस्तीति ज्ञात्वा शेषैकभागो वैक्रियिकसमुद्घाते देयः—६ प । १ / ३— a ५ ५ ५ ५ ५ अयमेव यथायोग्यवैगुर्वाणावगाहनोत्पन्नसंख्यातघनाङ्गुलैर्गुणितः—घनाङ्गुलवर्गगुणितासंख्यातश्रेणिमात्रं वैक्रियिकसमुद्घाते क्षेत्रं भवति—a ६ । ६ । पुनः सामान्याथ ऊर्ध्वतिर्यग्मनुष्यलोकान् पञ्च संस्थाप्यालापः क्रियते—

वैक्रियिक समुद्घातमें क्षेत्र घनांगुलके वर्गसे गुणित असंख्यात जगतश्रेणि प्रमान है। वह इस प्रकार है—कृष्णलेश्यावाले वैक्रियिक शक्तिसे युक्त जीवोंके प्रमाणको संख्यातसे भाग दो। बहुभाग प्रमाण जीव स्वस्थानस्वस्थानमें हैं। शेष एक भागमें पुनः संख्यातसे भाग दो। बहुभाग प्रमाण जीव विहारवत्स्वस्थानमें हैं। शेष एक भागमें पुनः संख्यातसे भाग दो। बहुभाग प्रमाण जीव वेदना समुद्घातमें हैं। शेष एक भागमें संख्यातसे भाग दो। बहुभाग प्रमाण जीव कषाय समुद्घातमें हैं। शेष एक भाग प्रमाण जीव वैक्रियिक समुद्घातमें हैं। इस प्रकार जो वैक्रियिक समुद्घातवाले जीवोंका प्रमाण है उसको यथायोग्य एक जीव सम्बन्धी वैक्रियिक समुद्घातके क्षेत्र संख्यात घनांगुलसे गुणा करनेपर घनांगुलके वर्गसे गुणित असंख्यात श्रेणिमात्र वैक्रियिक समुद्घातका क्षेत्र होता है।

---

१. ब. °भागः । २. ब. °नेऽस्तीतिज्ञात्वा° ।

रतिप्पुवेके दोडसंख्यातघनांगुलवर्गमात्रजगच्छ्रेणीमात्रं तज्जीवक्षेत्रमप्पुवरिवं । ई प्रकारदिं नीललेश्येगं कापोतलेश्येगं वक्तव्यमक्कुं ।

मत्तं तेजोलेश्या राशियं ≡ ॥ १ (१) संख्यातदिवं भागिसि वंव बहुभागमं स्वस्थानस्व-
४ ६५ = १

स्थानदोळिक्कु शेषैकभागमं मत्तं संख्यातदिवं भागिसि बहुभागमं विहारवत्स्वस्थानदोळिक्कु

(७)

≡ ॥ १ । ४ शेषैकभागमं मत्तं संख्यातदिवं भागिसि बहुभागमं वेदनासमुद्घातदोळिक्कु—
४।६५ = १५५

(७)

≡ ॥ १ । ४ शेषैकभागमं मत्तं संख्यातदिवं भागिसि बहुभागमं कषायसमुद्घात दोळिक्कु—
४६५ = १ ५५५

(७)

≡ ॥ १ । ४ शेषैकभागमं वैक्रियिकपददोळीयुवु ।—
४६५ = १ ५५५५

कुतः ? असंख्यातघनाङ्गुलवर्गमात्रजगच्छ्रेणीनां तत्क्षेत्रत्वात् । एवं नीलकपोतयोरपि वक्तव्यम् । पुनस्तेजोलेश्या


जीवराशि ≡ ॥ १— १ संख्यातेन भक्त्वा भक्त्वा बहुभागं स्वस्थानस्वस्थाने—
४ । ६५ = १

≡ ॥ १— १ ४ विहारवत्स्वस्थाने ≡ ॥ १— १ ४ वेदनासमुद्घाते— ≡ ॥ १— १ ४
४ । ६५ = १ ५ ४ । ६५ = १ । ५ । ५ । ४ । ६५ = १ । ५ । ५ । ५

भागमें और मनुष्यलोकसे असंख्यातगुणे क्षेत्रमें रहते हैं। क्योंकि वैक्रियिक समुद्घातवालोंका क्षेत्र असंख्यात घनांगुलके वर्गसे गुणित जगतश्रेणि प्रमाण है। इसी प्रकार नील और कपोतलेश्याका भी कहना चाहिए।

अब तेजोलेश्याका क्षेत्र कहते हैं—तेजोलेश्यावाले जीवोंकी राशिमें संख्यातसे भाग देकर बहुभाग विहारवत्स्वस्थानमें जानना। शेष रहे एक भागमें संख्यातसे भाग देकर बहुभाग वेदना समुद्घातमें जानना। पुनः शेष रहे एक भागमें संख्यातसे भाग देकर बहुभाग कषाय समुद्घातमें जानना। शेष रहा एक भाग सो वैक्रियिक समुद्घातमें जानना। इस

प्रदेश विसर्प्पणक्रमदिवं वृद्धियुत्कृष्टदिवं त्रिगुणितविस्तारदिवं पुट्टिद राशि[1] मूलराशियं नोडलु नवगुण-
मक्कु ६ । ६ । ६ । ०० । ६ । ९ मा[2] नवगुणमूलराशियं मुखभूमि समासार्द्ध मध्यफलमें—
(above: १ । २; below: ७ ७७ ७)



दु मुखं शून्यमक्कुमेकेंदोडे द्वितीयविकल्पं मोदल्गोंडु प्रदेशवृद्धिक्रममप्पुदरिंदमा शून्यमं कूडि-
क्कियिसिदोडे समीकरणदिं पुट्टिद मध्यमावगाहनं नवार्द्धंघनांगुलसंख्यातैकभागमक्कुमदरिंदं वेदना-
समुद्घातराशियमं कषायसमुद्घातराशियुमं गुणिसुवुदु वेद ≡ ३ १ ४ ६ । ९ / ४ । ६५ = ५५५२ कषाय
≡ ३ १ ४ ६ । ९ / ४ । ६५ । ५५५ । २ मत्तं संख्यातयोजनायाममुं सूच्यंगुलसंख्यातभागविष्कंभोत्सेधमुमागि मूल-

संख्येयभागेन ६ हतस्तत्क्षेत्रं स्यात् । वेदनाकषायराशी द्वौ तत्समुद्घातयोर्मूलशरीरात्प्रदेशोत्सर्पणवृद्धया उत्कृष्ट-
विकल्पस्य त्रिगुणितव्यासस्य वासो त्रिगुणो परिहीत्यायानीत—७ । ३ । ३ । ७ । ३ । ७ / १० । १० । ४ घनफलस्य नव-

देना। ऐसा करनेसे प्रमाणरूप घनांगुलके संख्यातवें भाग एक देवके शरीरकी अवगाहन हुई। इस अवगाहनासे पहले जो स्वस्थानस्वस्थानमें जीवोंका प्रमाण कहा था उसे गुणा करनेपर जो प्रमाण हो उतना स्वस्थानस्वस्थानका क्षेत्र जानना।

वेदना समुद्घात और कषाय समुद्घातमें आत्माके प्रदेश मूल शरीरसे बाहर निकलकर एक प्रदेश क्षेत्रको रोकें या एक-एक प्रदेश बढ़ते-बढ़ते उत्कृष्ट क्षेत्रको रोकें तो चौड़ाईमें मूल शरीरसे तिगुने क्षेत्रको रोकते हैं और ऊँचाई मूल शरीर प्रमाण ही है। इसका घनरूप क्षेत्रफल करनेपर मूल शरीरके क्षेत्रफलसे नौगुणा क्षेत्रफल होता है। सो जघन्य एक प्रदेश और उत्कृष्ट मूल शरीरसे नौगुणा क्षेत्र हुआ। इनका समीकरण करनेसे एक जीवके मूल-शरीरसे साढ़े चार गुना क्षेत्र हुआ। शरीरका प्रमाण पहले घनांगुलके संख्यातवें भाग कहा था। सो उसे साढ़े चार गुना करनेपर एक जीव सम्बन्धी क्षेत्र होता है। उससे वेदना समुद्घातवाले जीवोंके प्रमाणको गुणा करनेपर वेदना समुद्घात सम्बन्धी क्षेत्र आता है। तथा कषाय समुद्घातवाले जीवोंके प्रमाणसे गुणा करनेपर कषाय समुद्घात सम्बन्धी क्षेत्र आता है। विहार करते हुए देवोंके मूलशरीरसे बाहर आत्माके प्रदेश फैलें तो वे प्रदेश एक जीवकी अपेक्षा संख्यात योजन तो लम्बे और सूच्यंगुलके संख्यातवें भाग प्रमाण चौड़े व ऊँचे क्षेत्रको रोकते हैं। उसका क्षेत्रफल संख्यात घनांगुल प्रमाण होता है। इससे पूर्वमें कहे विहारवत्स्वस्थानवाले जीवोंके प्रमाणको गुणा करनेपर सब जीवोंके विहारवत्स्वस्थान

1. म राशि ७ । ३ । ३ । ७ । ३ । ७ / १० । १० । ४ मूलं। 2. म मा मूलं।

मुत्तिरलु तेजःसमुद्घातक्षेत्रमक्कुं ६२।७। मत्तं सूच्यंगुलसंख्यातैकभागविष्कंभोत्सेधमुं संख्यातयोजनायामक्षेत्रघनफलमं २ २ / १ १ / यो १ लब्धसंख्यातघनांगुलप्रमितमं संख्यातजीवंगळिवं गुणिसुत्तं विरलु आहारसमुद्घातक्षेत्रमक्कुं ६।१।१।

मरदि असंखेज्जदिमं तस्सासंखाय विग्गहे होंति ।
तस्सासंखं दूरे उववादे तस्स खु असंखं ॥५४४॥

ई सूत्राभिप्रायमें तें दोडे उपपादक्षेत्रमं तरल्वेडि सौधर्मैशानकल्पद्वयद जीवराशियनांगुलतृतीयमूलगुणितजगच्छ्रेणिप्रमितमक्कुं ३ ॥

ई राशियं पल्यासंख्यातदिदं खंडिसिदेकभागं प्रतिसमयं म्रियमाणराशियक्कुं –३ / प / a मतमं

– प। प।१।a१।—४ / a a ७।११ पुनर्द्वादशयोजनायामनवयोजनविष्कंभसूच्यङ्गु-
४।९९=८१।१०।a११।पपप / aaa

पल्यासंख्यातैकभागोत्सेध २।९ / ११ / यो १२ यो क्षेत्रघनफलं संख्यातघनाङ्गुलप्रमितं ६ १ संख्यातजीवैर्गुणितं तैजससमुद्घातक्षेत्रं भवति ६।१।१। पुनः सूच्यङ्गुलसंख्यातैकभागविष्कम्भोत्सेधसंख्यातयोजनायामक्षेत्रस्य २।२ / १।१ / यो १ घनफलं संख्यातघनाङ्गुलप्रमितं ६ १ संख्यातजीवैर्गुणितं आहारकसमुद्घातक्षेत्रं भवति ६ १।१ ॥५४३॥

अस्यार्थः उपपादक्षेत्रमानेतुं सौधर्मद्वयजीवराशौ घनाङ्गुलतृतीयमूलगुणितजगच्छ्रेणिप्रमिते – ३ प्रथ-

---

करनेवालोंके प्रमाण संख्यातको गुणा करनेपर तैजस समुद्घात सम्बन्धी क्षेत्र आता है। आहारक समुद्घातमें एक जीवके प्रदेश शरीरसे बाहर निकलनेपर संख्यात योजन प्रमाण लम्बे और सूच्यंगुलके संख्यातवें भाग चौड़े ऊँचे क्षेत्रको रोकते हैं। इसका घनक्षेत्रफल संख्यात घनांगुल होता है। इससे आहारक समुद्घातवाले जीवोंके प्रमाण संख्यातको गुणा करनेपर आहारक समुद्घातका क्षेत्र होता है ॥५४३॥

इस गाथाका अभिप्राय उपपादक्षेत्र लाना है। पीतलेश्यावाले सौधर्म ईशानवर्ती जीव मध्यलोकसे दूर क्षेत्रवर्ती हैं। अतः इनके कथनमें क्षेत्रका परिमाण बहुत आता है। अतः

१. म ६।०।१।

संख्यातसूच्यंगुलविष्कंभोत्सेधद्व्यर्द्धरज्वायतक्षेत्र २१ २१ घनफलदिदं संख्यातप्रतरांगुलगुणित-
३
२

द्व्यर्द्धरज्जुगळिवं – ३ । ४ १ गुणिसुत्तं विरलु उपपादक्षेत्रमक्कुं – ३ प प – ३ । ४ ३ पद्म-
७ २ ａ ａ
प प प प प । ७ २
ａ ａ ａ ａ ａ

लेश्येयोळु पद्मलेश्याजीवराशिय संख्यातदिदं भागिसि बहुभागमं स्वस्थानस्वस्थानपदवोळित्तु
= ४ शेषैकभागमं मत्त संख्यातदिदं भागिसि बहुभागमं विहारवत्स्वस्थानदोळित्तु
४ । ६५ = १ । ६ । ५
= ४ । शेषैकभागमं मत्तं संख्यातदिदं भागिसि बहुभागमं वेदनासमुद्घातपद-
४ । ६५ = १ । ६ । ५ । ५
दोळित्तु = ४ शेषैकभागमं कषायसमुद्घातपदवोळित्तु = १
४ । ६५ = १६।५।५।५ ४ । ६५ = १६।५ । ५ । ५
वळिकमल्लि प्रथमराशियं द्वितीयं द्वितीयराशियुमं क्रोशायाम तन्नवमभागमुखविष्कंभतिर्य्यग्जीवा-

राशिर्भवति—३ । प प ११ अस्मिन् समीकरणकृततिर्यग्जीवमुखप्रमाणसंख्यातसूच्यंगुलविष्कंभोत्से-
ａ ａ
प प प प प
ａ ａ ａ ａ ａ
धद्व्यर्धरज्ज्वायतक्षेत्रघनफलेन २ १ । २ १ संख्यातप्रतराङ्गुलगुणितद्व्यर्धरज्जुप्रमितेन —३ । ४ । १ गुणितं
—३ ७ । २
७ । २
उपपादक्षेत्रं भवति—३ प प – ३ । ४ । १ । पद्मलेश्यायां तज्जीवराशेः संख्यातभक्तबहुभागः स्वस्थान-
ａ ａ ७ २
प प प प प
ａ ａ ａ ａ ａ
॥
स्वस्थाने देयः = ४ शेषैकभागस्य संख्यातभक्तबहुभागो विहारवत्स्वस्थाने देयः—
४ । ६५ = १ ६ । ५
॥
= ४ शेषैकभागस्य संख्यातभक्तबहुभागो वेदनासमुद्घाते देयः = ४
४ । ६५ = १ ६ । ५ । ५ ४ । ६५ = १६ । ५ । ५ । ५

की मुख्यतासे एक जीव सम्बन्धी प्रदेश फैलनेकी अपेक्षा डेढ़ राजू लम्बा संख्यात सूच्यंगुल प्रमाण चौड़ा ऊँचा क्षेत्र है। इसका घनक्षेत्रफल संख्यात प्रतरांगुलसे डेढ़ राजूको गुणा करनेपर जो प्रमाण है उतना है। इससे उपपाद जीवोंके प्रमाणको गुणा करनेपर उपपाद सम्बन्धी क्षेत्र आता है। यह पीतलेश्यामें क्षेत्रका कथन किया। अब पद्मलेश्यामें करते हैं—

पद्मलेश्यावाले जीवोंकी संख्यामें संख्यातका भाग देकर बहुभाग स्वस्थानस्वस्थानमें जानना। एक भागमें पुनः संख्यातसे भाग देकर बहुभाग विहारवत्स्वस्थानमें जानना। शेष एक भागमें संख्यातसे भाग देकर बहुभाग वेदना समुद्घातमें जानना। शेष रहा एक

वेदनासमुद्घातपददोळ् वरियुत्तु $\frac{-४}{११।५।५।५}$ ञोवेकभाग संख्यातबहुभागं कषायसमुद्घातपददोळ् वरियुत्तु $\frac{-४}{११।५।५।५।५}$ ञोवेकभागं वैक्रियिकसमुद्घातपदवोळक्कु $\frac{-१}{११।५।५।५।५}$ मा राशियना जीवंगळु विगुर्व्विसिद गजादिशरीररावगाहनसंख्यातघनांगुलंगळिं गुणिमुत्तं विरलु वैक्रियिकसमुद्घातपददोळु क्षेत्रमक्कु $\frac{-६१}{११।५५५५}$ मी राशियन्ने "मरदि असंखेज्जदिमं तस्सासंखा विग्गहे होंति तस्सासंखं दूरे उववादे तस्स खु असंखं ॥" एंदितु पल्यासंख्यातभागादिदं भागिमुत्तं विरलेकभागं प्रतिसमयं म्रियमाणजीवप्रमाणमक्कु $\frac{=१}{११।प / a}$ मत्तं पल्यासंख्यातदिदं भागिसिद बहुभागं विग्रहगतिय जीवप्रमाणमक्कुं $\frac{-प / a}{११ पप / aa}$ मत्तमिदं पल्यासंख्यातदिदं भागिसिद बहुभागं मारणां-

---

वेदनासमुद्घाते $\frac{-४}{११।५।५।५}$ कषायसमुद्घाते च पतितोऽस्तीति ज्ञात्वा $\frac{-४}{११।५।५।५।५}$ शेषैकभागो वैक्रियिकसमुद्घाते देव $\frac{-१}{११।५५५५}$ अस्मिन् तज्जीवविकुर्वितगजादिशरीरावगाहनसंख्यातघनाङ्गुलैर्गुणिते तत्समुद्घातक्षेत्रं भवति $\frac{-६१}{११।५५५५}$ पुनस्तस्मिन्नेव सनत्कुमारमाहेन्द्रदेवराशौ—

मरदि असंखेज्जदिमं तस्सासंखा य विग्गहे होंति । तस्सासंखं दूरे उववादे तस्स खु असंखं ॥

इति पल्यासंख्यातभक्तैकभागः प्रतिसमयं म्रियमाणजीवप्रमाणं भवति $\frac{-१}{११।प / a}$ । पुनः पल्यासंख्यातभक्तबहुभागो विग्रहगतिजीवप्रमाणं भवति $\frac{-प / a}{११ a। पप / aa}$ पुनः पल्यासंख्यातभक्तबहुभागो मारणान्तिकसमुद्घातजीवप्रमाण

ग्यारहवें वर्गमूलसे जगतश्रेणिको भाग देनेपर जो प्रमाण आवे उतनी है। इस राशिमें असंख्यातसे भाग देकर बहुभाग प्रमाण स्वस्थानस्वस्थानमें जीव जानना। शेष रहे एक भागमें पुनः असंख्यातसे भाग देकर बहुभाग विहारवत्स्वस्थानमें जीव जानने। शेष रहे एक भागमें पुनः असंख्यातसे भाग देकर बहुभाग वेदना समुद्घातमें जानना। शेष रहे एक भागमें पुनः असंख्यातसे भाग देकर बहुभाग कषाय समुद्घातमें जानना। शेष रहे एक भाग प्रमाण वैक्रियिक समुद्घातमें जीव जानना। इतने-इतने जीव इनमें होते हैं। इन वैक्रियिक समुद्घातवाले जीवोंके प्रमाणको एक जीव सम्बन्धी हाथी-घोड़े रूप विक्रियाकी अवगाहना संख्यात घनांगुलसे गुणा करनेपर वैक्रियिक समुद्घातका क्षेत्र आता है। मारणान्तिक समुद्घात और उपपादमें भी क्षेत्र सानत्कुमार माहेन्द्रकी अपेक्षासे बहुत है अतः इनका कथन भी उनकी ही अपेक्षा करते हैं—

राशियं गुणिसिदोडे तन्मारणांतिकसमुद्घातपदवोळु क्षेत्रमक्कुं — प प । १ । ३ । ४ मत्तं
०० ११ प प प प ००००

[illegible]संख्यातसूच्यंगुल[illegible]सनत्कुमारद्वयमं कुरुत्तु तिर्य्यग्जीवंगलिवं मुक्तोपपाद[illegible] [illegible]संख्यातप्रतरांगुलहतत्रिरज्जुमात्रंगळिदं गुणिसिदोडे उपपाददोळु क्षेत्रमक्कुं

— प प । १ । ३ । ४ । १ तैजससमुद्घातदोळं आहारकसमुद्घातदोळं—क्षेत्रंगळु तेजो-
०० ११ प प प प प ०००००

[illegible] संख्यातघनांगुलगुणितसंख्यातजीवप्रमाणराशिगळप्पुवु ते १ । ६ । १ । आहार
१ । ६ । १ । मत्तं शुक्ललेश्येयोळु—शुक्ललेश्याजीवराशियं पल्यासंख्यातप्रमितमं संख्यातांश

[illegible] — ३ । ४ गुणिते तत्क्षेत्रं स्यात्— प प ७ । ३ । ४ पुनः उपपाद[illegible]
११ ० ० १ प प प प ००००

[illegible] सनत्कुमारद्वयं प्रति [illegible]मुक्तोपपाद[illegible]

[illegible] — ३ । ६ ३ गुणिते तत्क्षेत्रं भवति— प प — ३ । ६ ३
१११ ० ०७ प प प प प ० ० ० ० ०

[illegible]संख्यातराशिर्भवति—
१ । ६ । १ । ६ । १ [illegible] भागाः बहुभागबहु[illegible]
[illegible] विहारवत्स्वस्थाने प । ८ वेदनासमुद्घाते प ८ कषायसमुद्घाते प प ४ [illegible]
० १ ० ११ ० १११ ० ११११

है । [illegible] द्वारा सानत्कुमार माहेन्द्रमें उत्पन्न होनेके लिए किया गया [illegible] राजू लम्बा और संख्यात सूच्यंगुल प्रमाण चौड़ा व ऊँचा है । इसको [illegible] गुणित तीन राजू मात्र होता है । इससे उपपाद[illegible] उपपाद सम्बन्धी क्षेत्रका प्रमाण होता है । तैजस और [illegible] समुद्घातमें [illegible] कथनकी तरह है वैसे ही यहाँ भी [illegible] प्रमाण जानना । आगे शुक्ललेश्यामें क्षेत्र कहते हैं— [illegible] असंख्यातवें भागसे भाग देकर बहुभाग [illegible] असंख्यातवें भागसे भाग देकर बहुभाग [illegible] [illegible] भागमें [illegible] असंख्यातवें [illegible] वेदना समुद्घात, कषाय समुद्घातमें [illegible]
[illegible]

वोडे द्वितीयपदवोळु क्षेत्रमक्कुं प ४ । ६ । १ / ७ ५५ वैक्रियिकसमुद्घातपंचमजीवराशियं स्वस्वयोग्यमागिविगुर्व्विसिव शरीरावगाहनंगळिदं लब्धसंख्यातघनांगुलंगळिदं गुणिसिदोडे वैक्रियिकसमुद्घातपदवोळु क्षेत्रमक्कुं प ६ १ / ७ ५५५५ मत्तं मारणांतिकसमुद्घातपदवोळु रज्जुषट्कायामसूच्यंगुलसंख्यातभागविष्कंभोत्सेध २ २ / १ १ / ७ ६ क्षेत्रघनफलमिदे —६ । ४ / ७ । १ कजीवप्रतिबद्धमक्कुमी क्षेत्रमुमानतादिदेवकळ्गे मनुष्यरोळेयुत्पत्तिनियममप्पुदरिदं च्युतकल्पदोळु संख्यातजीवंगळे मरणमनेय्दुवुदु कारणमागि संख्यातजीवंगळिदं गुणिसिदोडे मारणांतिकसमुद्घातक्षेत्रप्रमाणं १ ७ । ६ । ४ / १ १ तैजससमुद्घातपदवोळं आहारकसमुद्घातपदवोळं पद्मलेश्येयोळ्पेळ्दंते क्षेत्रंगळप्पुवु तै १ । ६ । १ । आ १ । ६ । १ । केवलिसमुद्घातपदवोळु क्षेत्रं पेळल्पडुगु मदेंतेंदोडल्लि दंडम्

क्षेत्रघनफलसंख्यातघनाङ्गुलैः ६ १ गुणिते विहारवत्स्वस्थाने क्षेत्रं भवति प । ४ । ६ १ / ७ ५ ५ । पुनः पञ्चमराशौ स्वस्वयोग्यतया विकुर्वितशरीरावगाहलब्धसंख्यातघनाङ्गुलैः ६ १ गुणिते वैक्रियिकसमुद्घातपदे क्षेत्रं भवति प । ६ १ / ७ ५ । ५ । ५ ५

पुनः रज्जुषट्कायामसूच्यङ्गुलसंख्यातभागविष्कम्भोत्सेध २ । २ / १ १ / ७ ६ क्षेत्रघनफलमेकजीवप्रतिबद्धं भवति — ६ । ४ / ७ । १ अस्मिन्नानतादिदेवानां मनुष्येष्वेवोत्पत्तेस्तत्र संख्यातैरेव म्रियमाणैर्गुणिते मारणान्तिकसमुद्घातक्षेत्रं भवति १ । ७ ६ । ४ / १ तैजसाहारकसमुद्घातक्षेत्रं पद्मलेश्यावत् । —तै १ । ६ १ । आ १ । ६ १ केवलि-

विहारवत्स्वस्थान सम्बन्धी क्षेत्र होता है। तथा अपने-अपने योग्य विक्रियारूप बनाये गये हाथी आदिके शरीरकी अवगाहना संख्यात घनांगुल है। उससे वैक्रियिक समुद्घातवाले जीवोंके प्रमाणको गुणा करनेपर वैक्रियिक समुद्घातमें क्षेत्रका प्रमाण आता है। शुक्ललेश्या आनतादि स्वर्गोंमें होती है। सो आरण अच्युतकी मुख्यतासे वहाँसे मध्यलोक छह राजू है। अतः वहाँसे मारणान्तिक समुद्घात करनेपर एक जीवके प्रदेश छह राजू लम्बे और सूच्यंगुलके संख्यातवें भाग चौड़े-ऊँचे होते हैं। उसका जो क्षेत्रफल एक जीवकी अपेक्षा हुआ उसको संख्यातसे गुणा करना, क्योंकि आनतादिकसे मरकर देव मनुष्य ही होता है। इसलिए मारणान्तिक समुद्घातवाले जीव संख्यात ही होते हैं। अतः संख्यातसे गुणा करनेपर मारणान्तिक समुद्घात सम्बन्धी क्षेत्र आता है। तैजस और आहारक समुद्घात सम्बन्धी क्षेत्र पद्मलेश्यामें जैसा कहा है वैसा ही जानना। अब केवलि समुद्घातमें क्षेत्र कहते हैं—

१. म. गच्छंगर्न ।

मोडुवुदादोडे अशीत्युत्तराष्टशतद्विसहस्रसूच्यंगुलगुणितजगत्प्रतरमात्रं निष्पण्णपूर्व्वाभिमुखकवाटसमुद्घातक्षेत्रमक्कुं = सू २। २८८०। किंचिदूनचतुर्द्दशरज्जुदीर्घं पूर्व्वापरदिदं सप्तैकपंचैकरज्जुविष्कंभं द्वादशांगुलरुंद्रसमीकृतक्षेत्रफलं मुख -१/७। भूमि-७/७ जोग ■ दळे-४/७ प-७ गुणिदे =४/७ पदधणं होदि एंदिदधोलोकक्षेत्रफलमक्कुं =४/७। मत्तं। मुख-१/७ भूमि-५/७ जोग-६/७ दळे-३/७ पद-७ गुणिदे-२१/७।७।२ पदधणं होदि। अपवर्त्तितं =३/७२ इदं द्विगुणिसिदोडूर्ध्वलोकक्षेत्रफलमक्कुमोयूर्ध्वलोकक्षेत्रफलमुमं =३/■ अधोलोकक्षेत्रफलमुमं =४/७ कूडि जगत्प्रतरमितमक्कुमदं द्वादशांगुलरुंद्रदिदं गुणिसिदो =१२ डेकजीवप्रतिबद्धक्षेत्रमक्कुमदं जीवगुणकारदिदं ४० गुणिसिदोडे चतुःशताशीति सूच्यंगुलगुणितजगत्प्रतरमात्रमुत्तराभिमुखस्थितकवाटसमुद्घातक्षेत्रमक्कु = सू २। ४८०। मिदं त्रिगुणितं माडिदोडे चत्वारिंशदुत्तरचतुःशतैकसहस्रसूच्यंगुलसंगुणितजगत्प्रतरमात्रमुत्तराभिमुखासीनकवाटसमुद्घातक्षेत्रमक्कुं = सू २। १४४०। ई कवाटसमुद्घातक्षेत्रमं नोडलसंख्यातगुणमप्पुदु सर्व्वलोकमं नोडलुमसंख्यातभागहीनमुमप्पुदु प्रतरसमुद्घातक्षेत्रमक्कुमदें तें दोडे :—

नवशतषष्टिसूच्यङ्गुलहतजगत्प्रतरं पूर्वाभिमुखस्थितकवाटसमुद्घातक्षेत्रं भवति—= सू २। ९६० एतदेव त्रिगुणितं द्विसहस्राष्टशताशीतिसूच्यङ्गुलहतजगत्प्रतरं निषण्णपूर्वाभिमुखकवाटसमुद्घातक्षेत्रं भवति सू २। २८८० किंचिदूनचतुर्दशरज्जुदीर्घस्य पूर्वापरेण सप्तैकपञ्चैकरज्जुविष्कम्भस्य मुख—१/७ भूमि—/७७ जोग—८/७ ■—४/७ पद—/७७ गुणिदे =४/७ पदधणं होदीत्यधोलोकफलं =४/७ मुख—१/७ भूमि—५/७ जोग—६/७ दले—३/७ पद—/७।२ गुणिदे =२१/७७।२ पदधणं होदीत्यपवर्त्य =३/७२ द्विहते ऊर्ध्वलोकफलं =३/७ अस्मिन्नधोलोकफले मिलिते जगत्प्रतरद्वादशाङ्गुलं रुद्रेण गुणितः =१२ एकजीवप्रतिबद्धं तदेव जीवगुणकारेण ४० गुणितं चतुःशताशीतिसूच्यङ्गुलहतजगत्प्रतरमुत्तराभिमुखस्थितकवाटसमुद्घातक्षेत्रं भवति = सू २। ४८० एतदेव त्रिहतं एकसहस्रचतु-

इससे तीससे गुणा किया है। पूर्वाभिमुख स्थित कपाट समुद्घातमें एक जीवके प्रदेश वातवलय बिना लोक प्रमाण अर्थात् कुछ कम चौदह राजू लम्बे हैं। उत्तर-दक्षिण दिशामें लोककी चौड़ाई सात राजु, सो इतने चौड़े हैं। बारह अंगुल प्रमाण पूरब पश्चिममें ऊँचे हैं। इसका क्षेत्रफल चौबीस अंगुलसे गुणित जगत्प्रतर प्रमाण होता है। चूँकि एक समयमें इस समुद्घात करनेवाले जीवोंका प्रमाण चालीस है अतः चालीससे गुणा करनेपर नौ सौ साठ सूच्यंगुलसे गुणित जगत्प्रतर प्रमाण पूर्वाभिमुख स्थित कपाट समुद्घातका क्षेत्र होता है। इसीको तिगुणा करनेपर दो हजार आठ सौ अस्सी सूच्यंगुलसे गुणित जगत्प्रतर प्रमाण पूर्वाभिमुख स्थित कपाट समुद्घातका क्षेत्र होता है। उत्तराभिमुख स्थित कपाट समुद्घातमें एक जीवके प्रदेश वातवलय बिना लोक प्रमाण अर्थात् कुछ कम चौदह राजू प्रमाण लम्बे होते हैं। और पूरब-पश्चिममें लोककी चौड़ाई प्रमाण चौड़े होते हैं। सो लोक

१. म. माडुवदोडे।

[illegible] कवाटचतुष्टयदोळं प्रत्येकमुत्कृष्टदिदं विंशतिविंशतिप्रमितजीवंगळ् [illegible] ४० नाल्वत्तक्कुमें दु केळेल्पडुगुं ।

[illegible] मनुष्यादि असंख भागा य सव्वलोगो य ॥५४८॥

[illegible] केवलिसमुद्घातमेयोयिदं लोकासंख्यातबहुभागंगळुं लोकमुं [illegible] [illegible] । [illegible] संख्यातसूच्यंगुलविष्कंभोत्सेध [illegible] [illegible] मा क्षेत्रमुमक्कुतक्कल्पदोळ् [illegible] [illegible] संख्यातजीवंगळिवं गुणिसिदोडे [illegible] [illegible] मतमो गुणलेश्यंगळिल्लियु सर्व्वत्र गुणकारभागहारंगळ [illegible] [illegible] माडल्पडुगुं । पनों [illegible] ।

[illegible]

[illegible]

[illegible]

[illegible]

केवलि स वं	उपपाद				
	—प प ə ə प प प प प ə ə ə ə ə	७ २ . ३।४७			
	प प ७ ə ə ११ प प प प प ə ə ə ə ə	३।४।७		७-६।७ ७	
स्थित दंड –४।८६४०	पू स्थि = क = =सू २।९६०	उत्थित क= = २।४८०	प्रतर ≡ , ə ə		
आसीन दंड —४।७७६०	पू आसीन क =सू२।२८८०	आसीन क =२।१४४०	लोकपूर ≡		

स्पर्शाधिकारमं सार्द्धगाथाषट्कदिदं पेळ्वपं :—

फासं सव्वं लोयं तिट्ठाणे असुहलेस्साणं ॥५४५॥

स्पर्शः सव्वलोकस्त्रिस्थाने अशुभलेश्यानां ॥

अशुभलेश्यात्रयक्के स्वस्थानमें बुं समुद्घातमें बुं उपपादमें बितु सामान्यदिदं त्रिस्थानमागु मल्लिया त्रिस्थानदोळं स्पर्शः स्पर्शं सर्व्वलोकः सर्व्वलोकमक्कुं । ≡ विशेषदि स्वस्थानस्वस्थानादि दशपदंगळोळं स्पर्शं पेळल्पडुगुं ।

स्पर्शमें बुदेनें दोडे स्वस्थानस्वस्थानादिदशपदंगळोळु विवक्षितपदपरिणतंगळप्प जीवंगळिं वर्त्तमानक्षेत्रसहितमागियतीतकालदोळु स्पृष्टक्षेत्रं स्पर्शमें बुदक्कुमल्लि अल्लेवरं कृष्णलेश्याजीवंगळ्गे स्वस्थानस्वस्थानवेदना कषाय मारणान्तिक उपपादमें ब पंचपदंगळोळु स्पर्शं सर्व्वलोकमक्कुं ≡ विहार-

अशुभलेश्यात्रयस्य स्वस्थानसमुद्घातोपपादसामान्यस्थानत्रये स्पर्शः विवक्षितपदपरिणतैर्वर्त्तमानाती-तकालस्पृष्टक्षेत्रम् सर्वलोकः ≡ विशेषेण तु दशपदेषु उच्यते । तत्र कृष्णलेश्याजीवान स्वस्थानस्वस्थानवेदनाकषायमारणान्तिकोपपादेषु पञ्चपदेषु सर्वलोकः≡विहारवत्स्वस्थाने संख्यातसूच्यंगुल

आगे साढ़े छह गाथाओंसे स्पर्शाधिकार कहते हैं—

क्षेत्रमें तो केवल वर्तमान कालमें रोके गये क्षेत्रका ही ग्रहण होता है किन्तु स्पर्शमें वर्तमान क्षेत्र सहित अतीत कालमें स्पृष्ट क्षेत्रका ग्रहण होता है। अतः तीन अशुभ लेश्याओंका स्पर्श स्वस्थान, समुद्घात और उपपाद इन तीन सामान्य स्थानोंमें सर्वलोक होता है। विशेष रूपसे दस स्थानोंमें कहते हैं—उनमें-से स्वस्थान स्वस्थान, वेदना-समुद्घात, कषाय-समुद्घात, मारणान्तिक और उपपाद इन पाँच स्थानोंमें कृष्णलेश्यावाले जीवोंका स्पर्श सर्वलोक है। विहारवत्स्वस्थानमें एक राजू लम्बा व चौड़ा और संख्यात सूच्यंगुल ऊँचा तिर्यक् लोक

नोडलुमसंख्यातगुणं क्षेत्रं स्पृष्टं वैक्रियिकपददोळु कृष्णलेश्याजीवंगळिंदं कियत् क्षेत्रं स्पृष्टं मूरुं लोकंगळ संख्यातैकभागं। तिर्य्यग्लोकमुमं मनुष्यलोकमुमं नोडलुमसंख्यातगुणं क्षेत्रं स्पृष्टं। इंते नीललेश्येयोळं कपोतलेश्येयोळं वक्तव्यमक्कुं ।

तेजोलेश्यात्रिस्थानदोळु सामान्यदिदं स्पर्शमं पेळ्वपं गाथाद्वयदिदं :—

तेउस्स य सट्ठाणे लोगस्स असंखभागमेत्तं तु ।
अड चोद्दस भागा वा देसूणा होंति णियमेण ॥५४६॥

तेजोलेश्यायाः स्वस्थाने लोकस्यासंख्यभागमात्रं तु । अष्ट चतुर्दशभागा वा देशोना भवंति नियमेन ॥

तेजोलेश्येय स्वस्थानदोळु स्पर्शं स्वस्थानस्वस्थानापेक्षेयिं लोकद असंख्यातभागमात्रमक्कुं। तु मत्ते अष्टचतुर्दशभागंगळु मेणु किंचिदूनंगळप्पुवु नियमदिदं विहारवत्स्वस्थानादिचतुःपदंगळं विवक्षिसि :—

एवं तु समुद्घादे नवचोद्दसभागयं च किंचूणं ।
उववादे पढमपदं दिवड्ढचोद्दस य किंचूणं ॥५४७॥

एवं तु समुद्घाते नव चतुर्दशभागकं च किंचिदूनं। उपपादे प्रथमपदं द्वयर्द्धचतुर्दशभागः किंचिदूनः ॥

समुद्घातदोळं स्वस्थानदोळ्पेळ्दंते किंचिदून अष्टचतुर्दशभागमुं किंचिदूननवचतुर्दशभागमु स्पर्शमक्कुं । मारणांतिकसमुद्घातापेक्षेयिदं उपपाददोळु प्रथमपदं द्वयर्द्धचतुर्दशभागं किंचिदूनं स्पर्शमक्कुं इंतु सामान्यदिदं तेजोलेश्यंगे त्रिस्थानदोळु स्पर्शं पेळल्पट्टुदु ।

भवति ≡ ५ अत्र तैजसाहारककेवलिसमुद्घाताः पुनः न संभवन्ति। अत्रापि १ञ्च लोकान् संस्थाप्य आलाप-
१४३
कर्तव्यः। एवं नीलकपोतयोरपि वक्तव्यम् ॥५४५॥ अथ तेजोलेश्यायां गाथाद्वयेनाह—

तेजोलेश्यायाः स्वस्थाने स्पर्शः स्वस्थानात् स्वस्थानापेक्षया लोकस्यासंख्येयभागः। तु—पुनः, अष्टचतुर्दशभागाः अथवा किंचिदूना भवन्ति नियमेन विहारवत्स्वस्थानापेक्षया ॥५४६॥

समुद्घाते स्वस्थानवत् किंचिदूनाष्टचतुर्दशभागः किंचिदूननवचतुर्दशभागश्च स्पर्शो भवति मारणान्तिकसमुद्घातापेक्षया। उपपादपदे द्वयर्धचतुर्दशभागः किंचिदूनः इति सामान्येन तेजोलेश्यायास्त्रिस्थाने स्पर्शं

लम्बा-चौड़ा तथा पाँच राजू ऊँचा क्षेत्र हुआ। उसका क्षेत्रफल लोकके संख्यातवें भाग हुआ। यही वैक्रियिक समुद्घातमें स्पर्श जानना। इस कृष्णलेश्यामें आहारक, तैजस और केवलि समुद्घात नहीं होते। यहाँ भी पाँच लोकोंकी स्थापना करके यथासम्भव गुणकार भागहार जानना। कृष्णलेश्याकी ही तरह नीललेश्या और कपोतलेश्यामें भी कथन करना ॥५४५॥

तेजोलेश्यामें दो गाथाओंसे कहते हैं—

तेजोलेश्याका स्वस्थानमें स्पर्श स्वस्थानस्वस्थान अपेक्षा लोकका असंख्यातवाँ भाग है। और विहारवत्स्वस्थानकी अपेक्षा नियमसे त्रसनालीके चौदह भागोंमें-से कुछ कम आठ भाग स्पर्श होता है ॥५४६॥

समुद्घातमें स्वस्थानकी तरह त्रसनालीके चौदह भागोंमें-से कुछ कम आठ भाग स्पर्श है। मारणान्तिक समुद्घातकी अपेक्षा त्रसनालीके चौदह भागोंमें-से कुछ कम नौ भाग प्रमाण

११९०४। वारुणवरद्वीपदोळ् चतुरशीतित्रिशताष्टचत्वारिंशत्सहस्रंगळप्पुवु ४८३८४।
दोळ् द्वासप्तत्युत्तर पंचनवतिसहस्रैकलक्षप्रमितंगळप्पुवु १९५०७२। क्षीरवरद्वीपदोळ्
त्र्यशीतिसहस्रत्रिशतषष्टिमात्रंगळप्पुवु ७८३३६०। तद्वर्णवदोळ् ५ ... २
पंचशतचतुरशीतिप्रमितंगळप्पुवु। ३१३९५८४। एवं स्वयंभूरमणसमुद्रपर्य्यंतं नेतव्यंगळप्पुवु। २४।

३१३९५८४। स — ई खंडंगळं साधिसुवकरण सूत्रत्रयं :—
७८३३६० क्षी
१९५०७२। स
४८३८४ वा
११९०४। स
२८८०। पु
६७२। स
१४४। धा
२४ लं ल
१। ज

बाहिरसूईवग्गं अब्भंतरसूइवग्गपरिहीणं।
जंबूवासविभत्ते तत्तियमेत्ताणि खंडाणि ॥ —त्रि. सा. ३१६ गा.।

बाहिरसूई ५ ल। वग्गं ५ ल। ५ ल। गुणिते। २५ ल ल। अब्भंतरसूइ १ ल। व ल। १ ल। परिहीणं। २४। ल ल। जंबूवास १ ल ल। विभत्ते $\frac{२४ \text{ ल ल}}{१ \text{ ल ल}}$ तत्तियमेत्ताणि खंडाणि २४।

रूऊण सला बारस सलागगुणिदे दु वलयखंडाणि।
बाहिर सूइ सलागा कदी तदंता खिला खंडा ॥

वरसमुद्रे एकादशसहस्रनवशतचत्वारि ११९०४। वारुणीद्वीपे अष्टचत्वारिंशत्सहस्रत्रिशतचतुरशीतिः ४८३८
वरसमुद्रे एकलक्षपञ्चनवतिसहस्रद्वासप्ततिः १९५०७२। क्षीरवरद्वीपे सप्तलक्षत्र्यशीतिसहस्रत्रिशतषष्टिः ७८३३६
द्वर्णवे एकत्रिंशल्लक्षैकोनचत्वारिंशत्सहस्रपञ्चशतचतुरशीतिः। ३१३९५८४ एवं स्वयंभूरमणसमुद्रपर्यन्तम
व्यानि। तदानयनसूत्रत्रयं बाहिरसूई ५ ल, वग्गं ५ ल ५ ल, गुणिते पच्चीस ल ल, अब्भन्तरसूई १ ल,
१ ल १ ल, गुणिते लल परिहीणं २४ ल ल, जंबूवास १ ल ल, विभक्ते $\frac{२४ \text{ ल ल}}{१ \text{ ल ल}}$ अपवर्तिते तत्तियमे

प्रमाण वाले चौबीस खण्ड होते हैं। धातकी खण्डमें एक सौ चवालीस खण्ड होते हैं। का
समुद्रमें छह सौ बहत्तर खण्ड होते हैं। पुष्कर द्वीपमें दो हजार आठ सौ अस्सी खण्ड
हैं। पुष्कर समुद्रमें ग्यारह हज़ार नौ सौ चार खण्ड होते हैं। वारुणी द्वीपमें अड़ता
हजार तीन सौ चौरासी खण्ड होते हैं। वारुणी समुद्रमें एक लाख पनचानवे हजार ब
खण्ड होते हैं। क्षीरवर द्वीपमें सात लाख तिरासी हजार तीन सौ साठ खण्ड होते हैं।
वर समुद्रमें इकतीस लाख उनतालीस हजार पाँच सौ चौरासी खण्ड होते हैं। इस प्र
स्वयम्भूरमण समुद्र पर्यन्त लाना चाहिए। इसके लानेके लिए तीन सूत्र हैं। लवण
लवणसमुद्रकी बाह्य सूची पाँच लाख योजन, उसका वर्ग पचीस लाख लाख योजन।
समुद्रकी अभ्यन्तर सूची एक लाख योजन। उसका वर्ग एक लाख लाख योजन। घटा

समानखंडंगळं पेर्वणिसुत्तं विरलु पुष्करसमुद्रखंडंगळु षण्णवत्युत्तरचतुःशतप्रमितंगळप्पुवु ४९६। मत्तमा चतुर्विंशतिखंडंगळिंदं वारुणिसमुद्रद जंबूद्वीपसमानसकलखंडंगळं प्रमाणिसुत्तं विरलु ८१२८। मत्तमा चतुर्विंशतिखंडंगळिंदं १९५०७२ अष्टाविंशतिशतोत्तराष्टसहस्रप्रमितंगळप्पुवु
२४
क्षीरसमुद्रद जंबूद्वीपसदृशखंडंगळु ३१३९९८४ प्रमाणिसुत्तं विरलु मेकलक्षत्रिंशत्सहस्राष्टशत-
२४

षोडशप्रमितखंडंगळप्पुवु १३०८१६। इंतु स्वयंभूरमणसमुद्रपर्य्यंतं नडसल्पडुवुवु १३०८१६ मत्तमल्लि
६ प्रकारदिंदमरियु
८१२८
४९६ ^1
२८
१

गळ्ळिंद प्रथमोत्तरोत्पत्तिनिमित्तमेतादिचतुर्ग्गुणोत्तरमयप्रमाणऋणखंडंगळं प्रक्षेपिसुत्तं विरलु पुष्करसमुद्रदोळाद्यंतरगुणमकळिकमममागि नडेवुवल्लि प्रकृतक्षेत्रफलसमुत्पत्तिनिमित्तं द्विगुणषोडशवर्गखंडप्रमाण माडि

	वि १ छे ३ छे ३/२	वि १ छे ३ छे ३/२
क्षी	२। १६। १६। १६। १६	१ ४ ४ ४ ४
[illegible]	२। १६। १६। १६।	१ ८ ४ ४
पु	२। १६। १६।	१ ८ ४
[illegible]	२। १६। ८। ऋ	१ ८।
ज	२। १ धन	ऋण

प्रतरांगुलदिदं गुणिसि वळिक्कं :—

विरलिदरासीदो पुण जेत्तियमेत्ताणि हीणरूवाणि ।
तेसिं अण्णोण्णहदे हारो उप्पण्णरासिस्स ॥

एंदु लक्षयोजनच्छेदमात्रद्विकद्वयंगळ संवर्गजनितलक्षयोजनवर्गदिदमुं येकयोजनांगुलच्छेदमात्रद्विकद्वयसंवर्गजनितएकयोजनांगुलंगळ वर्गदिदमुं मेरुमध्यच्छेदमों दर द्विकवर्गदिदमुं जलचरसहितसमुद्रत्रयशलाकात्रयद गुणोत्तरगुणितघनप्रमितदिदमुं १६। १६। १६ गुणितलब्ध प्रतरांगुलदिदं भागिसि भाज्यभागहारंगळं निरीक्षिसि :—

जम्बूद्वीपक्षेत्रफलयोजनाङ्गुलवर्गप्रतराङ्गुलैः संगुण्य पश्चात्—

विरलिदरासीदो पुण जेत्तियमेत्ताणि हीणरूवाणि ।
तेसिं अण्णोण्णहदी हारो उप्पण्णरासिस्स ।

इति लक्षयोजनछेदमात्रद्विकद्वयंजातलक्षयोजनवर्गेण एकयोजनाङ्गुलछेदमात्रद्विकद्वयंजनितैकयोजनाङ्गुल-वर्गेण मेरुमध्यच्छेदस्य द्विकवर्गेण जलचरसमुद्रशलाकात्रयस्य गुणोत्तरघनेन च १६। १६। १६ हतप्रतराङ्गुले-

---

गुणकार वर्गरूप होता है अतः सात लाख अड़सठ हजारका दो बार गुणा करना होता है। सूच्यंगुलके वर्गको प्रतरांगुल कहते हैं अतः इतने प्रतरांगुलोंसे उक्त राशिको गुणा करना। पश्चात् 'विरलिदरासीदो' इत्यादि करणसूत्रके अनुसार द्वीप समुद्रोंके प्रमाणमें-से राजूके अर्धच्छेदोंमें-से जितने अर्धच्छेद घटाये हैं उनके आधे प्रमाणमात्र गुणकार सोलहको परस्परमें गुणा करनेसे जो प्रमाण हो उसे उक्त राशिका भागहार जानना। सो यहाँ जिसका आधा ग्रहण किया उस सम्पूर्ण राशि प्रमाण सोलहके वर्गमूल चारको परस्परमें गुणा करनेसे भी वही राशि आती है। सो अपने अर्धच्छेद प्रमाण दो-दोके अंकोंको परस्परमें गुणा करनेसे विवक्षित राशि होती है। यहाँ चार कहे हैं अतः उतने ही मात्र दो बार दो-दोके अंकोंको परस्परमें गुणा करनेसे विवक्षित राशिका वर्ग आता है। तदनुसार यहाँ लाख योजनके अर्धच्छेद प्रमाण दो बार दो-दोके अंकोंको रखकर परस्परमें गुणा करनेसे एक लाखका वर्ग आता है। एक योजनके अंगुलके अर्धच्छेद मात्र दो बार दो-दोको रखकर परस्परमें गुणा करनेसे एक योजनके अंगुल सात लाख अड़सठ हजारका वर्ग आता है। मेरुके ऊपर आनेवाले एक अर्धच्छेद मात्र दो दुओंको परस्परमें गुणा करनेसे चार हुआ। सूच्यंगुलके अर्धच्छेदमात्र दो-दोको रखकर परस्परमें गुणा करनेसे प्रतरांगुल हुआ। ये सब भागहार होते हैं। तथा जलचरवाले तीन समुद्र गच्छमें-से कम किये हैं अतः गुणोत्तर सोलहका तीन बार भाग होता है। इस प्रकार जगत्प्रतरमें प्रतरांगुल, दो, सोलह, चौबीस और सात सौ नौ करोड़ छप्पन लाख, चौरानवे हजार, एक सौ पचास तथा सात लाख अड़सठ हजार, सात लाख अड़सठ हजार तो गुणकार हुआ। तथा प्रतरांगुल, सात, सात, पन्द्रह, एक लाख, एक लाख, तथा सात लाख अड़सठ हजार, सात लाख अड़सठ हजार और चार और सोलह-सोलह-सोलह भागहार हुआ। इनमें-से प्रतरांगुल, दो बार सोलह, दो बार सात लाख अड़सठ हजार ये गुणकार और भागहारमें समान हैं अतः इनका अपवर्तन हो जाता है। गुणकारमें दो और चौबीसको परस्परमें गुणा करनेसे अड़तालीस होते हैं, तथा भाग-

---

१. ब छेदमत्र।

वर्गीदिदमुं प्रतरांगुलदिदमुं गुणिसि वळिकं "विरळिदरासीदो पुण जेत्तियमेत्ताणि हीनरूवाणि। तेसिं अण्णोण्णहदे हारो उप्पण्णरासिस्स" एंदु ओंदु लक्षयोजनंगळिदमुं एकयोजनांगुलंगळिदमुं मेरुमध्यच्छेददद्विकदिदमुं जलचरसहितसमुद्रशलाकात्रयजनितगुणोत्तरघनदिदमुं । ४ । ४ । गुणिसल्पट्ट सूच्यंगुलं भागहारमक्कु १६ । ४ । २४ । ७९०५६९४१५० । ७६८००० । ७६८००० मिन्ते
७ । ३ । २ । १ ल । ७६८००० । २ । ४ । ४ । ४ ।
पर्वात्तिसिदोडे संख्यातसूच्यंगुलप्रमितजगच्छ्रेणिगळप्पुववं २१ किंचिदूनं माडिदोडिंदु ०१
१२३९

गुणेन हिते – ३ मुहेण १६ । गुणवम्मि गुणगणियं – ३ । १६ । इदं चतुर्विंशतिखण्डजम्बूद्वीपक्षेत्रफलं
७ ७

मात्रगुलवर्गप्रतरांगुलैः संगुण्य पश्चात्—

विरलिदरासीदो पुण जेत्तियमेत्ताणि हीनरूवाणि।
तेसिं अण्णोण्णहदी हारो उप्पण्णरासिस्स ॥

इति लक्षयोजनैकयोजनांगुलैर्मेरुच्छेदस्य द्विकेन समुद्रशलाकात्रयजगुणोत्तरघनेन च । ४ । ४ ।।

हतसूच्यंगुलेन भक्ता— । १६ । ४ । २४ । ७९०५६९४१५० । ७६८००० । ७६८००० अपवर्तिते संख्यात
७ ३ । २ । १ ल । ७६८००० । २ । ४ । ४ । ४

सूच्यंगुलप्रमितजगच्छ्रेणिमात्रं भवति – २ १ । अनेन किंचिदूनितं = १ पूर्वोक्तं साधिकघनरज्जुभक्तजगत्प्रतर
१२३९

इनसे गुणा करें। ऐसा करनेसे एक कम जगतश्रेणिको सोलहका गुणकार व सात और तीनका भागहार हुआ। इसको पूर्वोक्त प्रकारसे चौबीस खण्ड, जम्बूद्वीपके क्षेत्रफल प्रमाण योजनोंके प्रमाण और एक योजनके अंगुलोंके वर्ग तथा प्रतरांगुलोंसे गुणा करो। पश्चात् 'विरलिदरासीदो' इत्यादि सूत्रके अनुसार गच्छमेंसे जितने राजूके अर्धच्छेद घटायें उसका आधा प्रमाण चारके अंकोंको परस्परमें गुणा करनेसे जो प्रमाण हो उतना भागहार जानना। जिस राशिका आधा प्रमाण लिया उस राशिमात्र चारके वर्गमूल दोको परस्परमें गुणा करनेपर एक लाख योजनके अर्धच्छेद प्रमाण दुओंको परस्परमें गुणा करनेसे एक लाख हुए। एक योजनके अंगुलोंके अर्धच्छेद प्रमाण दुओंको परस्परमें गुणा करनेसे सात लाख अड़सठ हजार अंगुल हुए। मेरुके मध्यमें एक अर्धच्छेदके दूने दो हुए। सूच्यंगुलके अर्धच्छेद प्रमाण दुओंको परस्परमें गुणा करनेसे सूच्यंगुल हुआ। ये सब भागहार हुए। तीन समुद्र घटाये थे सो तीन बार गुणोत्तर चारका भी भागहार जानना। इस प्रकार जगतश्रेणिको सोलह, चार, चौबीस, और सात सौ नब्बे करोड़ छप्पन लाख चौरानवे हजार एक सौ पचास तथा सात लाख अड़सठ हजार और सात लाख अड़सठ हजारका तो गुणकार हुआ। तथा सात, तीन, और सूच्यंगुल और दो, और सात लाख अड़सठ हजार तथा दो, चार, चार, चारका भागहार हुआ
१६।४।२४।७९०५६९४१५०।७६८०००।७६८०००
७।३।२।१ सू।७६८०००।२।४।४।४ । अपवर्तन करनेपर संख्यात

१. ब. संख्यात...।

सा = अं = को २
कषायज. ००० ... ३
अनुभागज ००० ... ३
योगस्थानज. ००० ... ३

आयाय [illegible] परिस्थिति [illegible] द्रव्यनिर्देश [illegible]।

१	२	३		सा० १० को २

[illegible] कोटिकोटिप्रमा

मी गेळल्पट्टु जघन्यस्थिति [illegible] स्थितिबन्धाध्यवसायस्थानंगळु [illegible] संख्यातलोकमात्र [illegible] [illegible] स्थितिय स्थितिबंधाध्यवसायस्थानंगळु अनुभागबंधाध्यवसायस्थानंगळु योगस्थानंगळु [illegible] मूलप्रकृतिगळुमुत्तरप्रकृतिगळु परिवर्तनं [illegible] भावपरिवर्तन [illegible] मितिल्लिगुपयोगियप्पार्यावृत्तं :—

सर्वप्रकृतिस्थित्यनुभागप्रदेशबंधयोग्यानि ।
स्थानान्यनुभूतानि भ्रमता भुवि भावसंसारे ॥

अन्तःको २— □ १ □ २ □ ३ □ ● ● □ १० को २ सा.

कषाय	जघ००≡a००≡a००≡a००≡a००३
अनुभाग	जघ००≡a००≡a००≡a००—a००≡a००≡a००≡a००≡a००३
योग	जघ००a००a००a००a००a००a००a००a००a००a००a००a००a००a००a००a००a००३

अत्रोपयोग्यार्यावृत्तं—

विशेषार्थ—योगस्थान, अनुभाग बन्धाध्यवसायस्थान, कषायाध्यवसायस्थान और स्थितिस्थानोंके परिवर्तनसे भावपरिवर्तन होता है। आत्माके प्रदेशोंके परिस्पन्दको योग कहते हैं। यह प्रकृतिबन्ध और प्रदेशबन्धमें कारण होता है। इन योगोंके जघन्य आदि स्थानोंको योगस्थान कहते हैं। जिन कषाययुक्त परिणामोंसे कर्मोंमें अनुभागबन्ध होता है उनके जघन्य आदि स्थान अनुभागबन्धाध्यवसायस्थान हैं। जिन कषाय परिणामोंसे स्थितिबन्ध होता है उनके जघन्य आदि स्थान कषायाध्यवसायस्थान हैं इन्हींको स्थितिबन्धाध्यवसायस्थान भी कहते हैं। कर्मोंकी स्थितिके जघन्यादि स्थानोंको स्थितिस्थान कहते हैं। एक-एक स्थितिभेदके बन्धके कारण असंख्यात लोक प्रमाण कषायाध्यवसायस्थान होते हैं। एक-एक कषायाध्यवसायस्थानके असंख्यात लोक प्रमाण अनुभागबन्धाध्यवसायस्थान होते हैं। एक-एक अनुभागबन्धाध्यवसायस्थानके जगत्श्रेणिके असंख्यातवें भाग योगस्थान होते हैं।

इस परिवर्तनके सम्बन्धमें उपयोगी आर्याछन्दका अभिप्राय इस प्रकार है—

तत्सम्यक्त्वं सरागवीतरागात्मविषयत्वदिवं द्विप्रकारवरिमें यल्पडुगुं। मुन्नं मोदल सरागात्मविषयसम्यक्त्वं प्रशमादिगुणं प्रशमसंवेगानुकंपास्तिक्याभिव्यक्तियोळ्कूडिदुदु। परं द्वितीयं वीतरागात्मविषयसम्यक्त्वं आत्मविशुद्धितः प्रतिपक्षप्रक्षयजनितजीवविशुद्धियिंदमानुदु। आस्तिक्यमें बुदेनें बोडे :—

'आप्ते व्रते श्रुते तत्त्वे चित्तमस्तित्वसंयुतं।
आस्तिक्यमास्तिकैरुक्तं सम्यक्त्वेन युते नरे ॥ —[यशो. उ. २३१ श्लो.]

अथवा तत्वार्थश्रद्धानं सम्यग्दर्शनं अथवा तत्वरुचिः सम्यक्त्वं ॥

"प्रदेशप्रचयात्कायाः द्रवणात् द्रव्यनामकाः।
परिच्छेद्यत्वतस्तेऽर्थास्तत्त्वं वस्तुस्वरूपतः ॥" —[ ]

एंदितु सामान्यदिं पंचास्तिकायषड्द्रव्य नवपदार्थंगळगे लक्षणमरकुं।

अनंतरं षड्द्रव्यंगळधिकारनिर्देशमं माडिदपं :—

छद्दव्वेसु य णामं उवलक्खणुवाय अत्थणे कालो।
अत्थणखेत्तं संखा ठाणसरूवं फलं च हवे ॥५६२॥

षड्द्रव्येषु च नामानि उपलक्षणानुवादः आसने कालः। आसनक्षेत्रं संख्यास्थानस्वरूपं फलं च भवेत् ॥

षड्द्रव्यंगळोळु नामंगळुमुपलक्षणानुवादमुं स्थितियुं क्षेत्रमुं संख्येयुं स्थानस्वरूपमुं फलमुमें दितु सप्ताधिकारंगळप्पुवु।

'यथोद्देशस्तथा निर्देशः' एंबी न्यायदिदं प्रथमोद्दिष्ट नामाधिकारमं पेळदपं :—

आप्ते व्रते श्रुते तत्त्वे चित्तमस्तित्वसंयुतम्। आस्तिक्यमास्तिकैरुक्तं सम्यक्त्वेन युते नरे ॥२॥
अथवा तत्त्वार्थश्रद्धानं सम्यग्दर्शनम्। अथवा तत्त्वरुचिः सम्यक्त्वम्।
प्रदेशप्रचयात्काया द्रवणाद् द्रव्यनामकाः। परिच्छेद्यत्वतस्तेऽर्थाः तत्त्वं वस्तुस्वरूपतः ॥१॥
इति सामान्येन पञ्चास्तिकायषड्द्रव्यनवपदार्थानां लक्षणम् ॥५६१॥ अथ षड्द्रव्याणामधिकारान्दिशति—

षड्द्रव्येषु नामानि उपलक्षणानुवादः स्थितिः क्षेत्रं संख्या स्थानस्वरूपं फलं चेति सप्ताधिकारा भवन्ति ॥५६२॥ अथ प्रथमोद्दिष्टनामाधिकारमाह—

युक्त मनुष्यका आस्तिक्य गुण कहा है। अथवा तत्त्वार्थके श्रद्धानको सम्यग्दर्शन कहते हैं अथवा तत्त्वोंमें रुचिको सम्यक्त्व कहते हैं। प्रदेशोंके समूह रूप होनेसे काय कहलाते हैं। गुण और पर्यायोंको प्राप्त करनेसे द्रव्य नामसे कहे जाते हैं। जीवके द्वारा जाननेमें आनेसे अर्थ कहलाते हैं और वस्तुस्वरूपके कारण तत्त्व कहलाते हैं। यह सामान्यसे पाँच अस्तिकाय, छह द्रव्य और नौ पदार्थोंका लक्षण है ॥ ५६१ ॥

छह द्रव्योंके अधिकारोंको कहते हैं—

छह द्रव्योंके सम्बन्धमें नाम, उपलक्षणानुवाद, स्थिति, क्षेत्र, संख्या, स्थान, स्वरूप और फल ये सात अधिकार होते हैं ॥ ५६२ ॥

प्रथम उद्दिष्ट नाम अधिकार को कहते हैं—

षडंशता । षण्णां समानदेशित्वे पिंडं स्यादणुमात्रकम् ॥" [ ] एंदितु पूर्व्वपक्षमं माडुत्तिरलु द्रव्यार्त्थिकनयदिदं निरंशत्वमुं पर्य्यायार्त्थिकनयदिदं षडंशतेयक्कुमें दितु परिहारं पेळल्पट्टुदु।

"आद्यंतरहितं द्रव्यं विश्लेषरहितांशकं ।
स्कंधोपादानमत्यक्षं परमाणुं प्रचक्षते ॥" [ ]

आद्यंतरहितं आदियुमवसानमुमिल्लदुदुं द्रव्यं गुणपर्य्यायंगळनुळ्ळुदुं विश्लेषरहितांशकं बेक्केय्यलिल्लद अंशमनुळ्ळुदुं स्कंधोपादानं स्कंधक्के कारणमप्पुदुं अत्यक्षं इंद्रियविषयमल्लदुदुं परमाणुं प्रचक्षते परमाणुवें दुपचरिसल्पडुगुं परमागमजर पेळ्वरु । नामाधिकारं तिद्दुदु ।

उवजोगो वण्णचऊ लक्खणमिह जीवपोग्गलाणं तु ।
गदिठाणोग्गहवट्टणकिरियुवयारो दु धम्मचऊ ॥५६५॥

उपयोगो वर्णचतुष्कं लक्षणमिह जीवपुद्गलयोस्तु । गतिस्थानावगाहवर्त्तनक्रियोपकारस्तु धर्म्मचतुर्णां ॥

उपयोगमुं वर्णचतुष्कमुं यथासंख्यमागिह परमागमदोळु जीवंगळ्गं पुद्गलंगळ्गं लक्षणमक्कुं । तु मत्ते गतिस्थानावगाहवर्त्तनक्रियेगळेंबुपकारंगळु तु मत्ते यथासंख्यमागि धर्म्माधर्म्माकाशकालंगळेंब नाल्कुं द्रव्यंगळ लक्षणमक्कुं ।

षट्केन युगपद्योगात् परमाणोः षडंशता ।
षण्णां समानदेशित्वे पिण्डं स्यादणुमात्रकम् ॥

सैत्यं, द्रव्यार्थिकनयेन निरंशत्वेऽपि परमाणोः पर्यायार्थिकनयेन षडंशत्वे दोषाभावात् ।

आद्यन्तरहितं द्रव्यं विश्लेषरहितांशकम् ।
स्कन्धोपादानमत्यक्षं परमाणुं प्रचक्षते ॥

॥५६४॥ इति नामाधिकारः ।

उपयोगः जीवानां, तु—पुनः वर्णचतुष्कं पुद्गलानां, इह परमागमे लक्षणं भवति । गतिस्थानावगाहनवर्तनक्रियाख्याः उपकाराः । तु—पुनः यथासंख्यं धर्माधर्माकाशकालानां लक्षणं भवति ॥५६५॥

करते हैं, प्राप्त करेंगे और पहले प्राप्त कर चुके हैं इस व्युत्पत्तिके अनुसार द्व्यणुकादिमें भी पुद्गलपना घटित होता है।

शंका—यदि परमाणु एक साथ छह दिशामें छह परमाणुओंसे सम्बन्ध करता है तो परमाणु छह अंशवाला सिद्ध होता है। यदि छहों समान देश वाले माने जाते हैं तो छह परमाणुओंका पिण्ड परमाणु मात्र सिद्ध होता है ?

समाधान—आपका कथन यथार्थ है, द्रव्यार्थिकनयसे यद्यपि परमाणु निरंश है किन्तु पर्यायार्थिकनयसे उसके छह अंशवाला होनेमें कोई दोष नहीं है। जो द्रव्य आदि और अन्तसे रहित है, जिसके अंश कभी भी अलग नहीं होते, जो स्कन्धका उपादान कारण तथा अतीन्द्रिय है उसे परमाणु कहते हैं ॥ ५६४ ॥

इस प्रकार नामाधिकार समाप्त हुआ।

परमागममें जीवका लक्षण उपयोग और पुद्गलोंका लक्षण वर्ण, गन्ध, रस स्पर्श कहा है। तथा यथाक्रमसे गतिरूप उपकार, स्थानरूप उपकार, अवगाहनरूप उपकार और वर्तनाक्रियारूप उपकार धर्मद्रव्य, अधर्मद्रव्य, आकाशद्रव्य और कालद्रव्यका लक्षण है ॥५६५॥

१. म परमागमं पेळ्दुदु । २. ब सत्यं पर्या° ।

र्तम्मिदमे वर्त्तिसुतिप्पवक्के बाह्योपग्रहमिल्लदे तद्वृत्त्यसंभवमप्पुदरिंदमा द्रव्यंगळ प्रवर्त्तनोपलक्षितं कालमें दितु माडिवर्त्तने कालदुपकारमक्कुमें दरियल्पडुवुदु । इल्लि णिच्चिगर्त्थमावुदें दोडे वर्त्तते द्रव्यपर्य्यायस्तस्य वर्त्तयिता कालः एंदितु कालक्कर्त्थमादोडे कालक्के क्रियावत्वमागि बक्कुमें तोगळु अधीते शिष्यः उपाध्यायोध्यापयति एंबंते कर्तृत्वमक्कुमें दोडिल्लि दोषमिल्लेकें दोडे निमित्तमात्र-मादोडं हेतुकर्तृव्यपदेशं काणल्पट्टुदुं । यें तोगळु कारिषोऽग्निरध्यापयति एंदितु कालक्के हेतुकर्तृ-लेयक्कुमंतादोडा कालमें तु निश्चयिसल्पडुगुमे दोडे समयाधिकक्रियाविशेषंगळ्गं समयादिनिर्व्वर्त्य-गळप्प पाकादिगळ्गं समयमें दुं पाकमें दितित्येवमादि स्वसंज्ञारूढिसद्भाववोळं समयः कालः ओदनपाककालः एंदितध्यारोपिसल्पडुत्तिर्द्दावुदों दु कालव्यपदेशनिमित्तमप्प मुख्यकालदस्तित्वमं पेळ्गुमेकें दोडे गौणक्के मुख्यापेक्षत्वमुंटप्पुदरिंदं । षड्द्रव्यंगळवर्त्तनाकारणं मुख्यकालमक्कुमा वर्त्तन-गुणमुं द्रव्यनिचयंगळोळे अक्कुमंतादोडमा कालाधारदिंदमे सर्व्वद्रव्यंगळुं वर्त्तते । परिणमंति स्वपर्य्यायंगळिंदं परिणमिसुतिप्पंवु खलु नियमदिंदं इल्लि खलुशब्दमवधारणार्त्थमक्कुं । इदरिंदं कालक्के परिणामक्रियापरत्वापरत्वोपकारंगळुं पेळल्पट्टवु ।

द्रव्याणां स्वपर्यायनिर्वृतिं प्रति स्वयमेव वर्तमानानां बाह्योपग्रहाभावे तद्वृत्त्यसंभवात् तेषां प्रवर्तनोपलक्षितः काल इति कृत्वा वर्तना कालस्य उपकारो ज्ञातव्यः । अत्र णिचोऽर्थः कः ? वर्तते द्रव्यपर्यायः तस्य वर्तयिता काल इति । तदा कालस्य क्रियावत्त्वं प्रसज्यते अधीते शिष्यः, उपाध्यायोऽध्यापयतीत्यादिवत्, तन्न-निमित्तमात्रेऽपि हेतुकर्तृत्वदर्शनात् कारीषोऽग्निरध्यापयतीत्यादिवत् । तर्हि स कथं निश्चीयते ? समयादिक्रिया-विशेषाणां समय इत्यादिः समयादिनिर्वर्त्यपाकादीनां पाक इत्यादेश्च स्वसंज्ञायाः रूढिसद्भावेऽपि तत्र काल इति अध्यारोप्यमाणः कालव्यपदेशः तद्व्यपदेशनिमित्तस्य मुख्यकालस्यास्तित्वं कथयति गौणस्य मुख्यापेक्षत्वात् इति षड् द्रव्याणां वर्तनाकारणं मुख्यकालः । वर्तनागुणो द्रव्यनिचये एव, तथा सति कालाधारेणैव सर्वद्रव्याणि वर्तन्ते स्वस्वपर्यायैः परिणमन्ति खलु नियमेन । अनेन कालस्यैव परिणामक्रियापरत्वापरत्वोपकारो उक्तो । तो तु जीवपुद्गल-अत्र खलुशब्दोऽवधारणार्थः, धर्मादीनां पर्यायैः परिणामानुपकारकत्वं कथं ? इति चेदाह—

वर्तन करते हैं किन्तु बाह्य उपकारके बिना यह सम्भव नहीं है अतः उनकी वर्तनामें जो निमित्त मात्र होता है वह काल है। ऐसा करके वर्तना कालका उपकार जानना। यहाँ णिच् प्रत्ययका अर्थ है—द्रव्यकी पर्याय वर्तन करती है उसका वर्तन करानेवाला काल है। शंका—तब तो कालको क्रियावान् होनेका प्रसंग आता है। जैसे शिष्य पढ़ता है और उपाध्याय पढ़ाता है?

समाधान—नहीं, क्योंकि निमित्त मात्रमें भी हेतुकर्तापना देखा जाता है, जैसे (शीतके समयमें) कण्डेकी आग पढ़ाती है।

शंका—तब कालके अस्तित्वका निश्चय कैसे होता है?

समाधान—समय, घड़ी, मुहूर्त आदि जो क्रिया विशेष हैं उनमें जो समय आदि रूपसे व्यवहार किया जाता है, समय आदिसे होनेवाले पकाने आदिको जो समय या पाक कहा जाता है इन रूढ़ संज्ञाओंमें जो कालका आरोप है वह मुख्य कालके अस्तित्वको कहता है क्योंकि उपचरित कथन मुख्य कथनकी अपेक्षा रखता है। इस प्रकार छह द्रव्योंकी वर्तनाका कारण मुख्य काल है। वर्तना गुण द्रव्यसमूहमें ही वर्तमान है [illegible] उसके आधारसे ही सब द्रव्य वर्तन करते हैं अर्थात् अपनी-अपनी पर्यायरूपसे परिणमन करते हैं। यहाँ खलु शब्द अवधारणार्थक है। इससे परिणाम क्रिया और पर

कालमनाश्रयिसि जीवादिसर्व्वंद्रव्यं स्वस्वपर्य्यायपरिणतमक्कुं । आ पर्य्यायावस्थानमुं ऋजुसूत्रनयदोळु येकसमयमेयक्कुमर्त्थपर्य्यायापेक्षेयिदं ।

ववहारो य वियप्पो भेदो तह पज्जओत्ति एयट्ठो ।
ववहार अवट्ठाणट्ठिदी हु ववहारकालो दु ॥५७२॥

व्यवहारश्च विकल्पो भेदश्च तथा पर्य्याय इत्येकार्त्थः । व्यवहारावस्थानस्थितिः खलु व्यवहारकालस्तु ॥

व्यवहारमें दोडं विकल्पमें दोडं भेदमें दडमंते पर्य्यायमें दोडमेकार्त्थमक्कुमल्लि व्यंजनपर्य्यायापेक्षेयिंद व्यवहारावस्थानस्थितिः व्यवहारमें दोडे पर्य्यायमें दु पेळल्पट्टवरिवमा पर्य्यायद अवस्थानदिदं वर्त्तमानतेयिंदमावुदों दु स्थितियदु तु मत्ते व्यवहारकालः व्यवहारकालमें दुदक्कुं ।

अवरा पज्जायठिदी खणमेत्तं होदि तं च समओत्ति ।
दोण्णमणूणमदिक्कमकालपमाणं हवे सो दु ॥५७३॥

अवरा पर्य्यायस्थितिः क्षणमात्रा भवति सैव समय इति । द्वयोरण्वोरतिक्रमकालप्रमाणो भवेत्स तु ॥

द्रव्यंगळ पर्य्यायंगळगे जघन्यस्थिति क्षणमात्रमक्कुमा स्थितिये समयमें ब संज्ञेयुळ्ळुदक्कुं । सः आ समयमुं तु मत्ते गमनपरिणतंगळप्पेरडुं परमाणुगळ परस्परातिक्रमकालप्रमाणमक्कुमिल्लि गुपयोगियप्प गाथासूत्रमिदु :—

णभएयपएसत्थो परमाणू मंदगइपवट्टंतो ।
बीयमणंतरखेत्तं जावदियं जादि तं समयकाळो ॥

कालमाश्रित्य जीवादि सर्वद्रव्यं स्वस्व-पर्यायपरिणतं भवति । तत्पर्यायावस्थानं ऋजुसूत्रनयेन एकसमयो भवति अर्थपर्यायापेक्षया ॥५७१॥

व्यवहारः विकल्पः भेदः तथा पर्यायः इत्येकार्थः तु पुनः तत्र व्यञ्जनपर्यायस्य अवस्थानतया स्थितिः सैव व्यवहारकालो भवति ॥५७२॥

द्रव्याणां जघन्या पर्यायस्थितिः क्षणमात्रं भवति । सा च समय इत्युच्यते । स च समयः द्वयोर्गमनपरिणतपरमाण्वोः परस्परातिक्रमकालप्रमाणं स्यात् ॥५७३॥ अत्रोपयोगिगाथाद्वय—

णभएयपएसत्थो परमाणू मन्दगइपवट्टंतो ।
बीयमणंतरखेत्तं जावदियं जादि तं समयकालो ॥१॥

कालका आश्रय पाकर जीव आदि सब द्रव्य अपनी-अपनी पर्याय रूपसे परिणमन करते हैं। उस पर्यायके ठहरनेका काल ऋजू सूत्रनयसे अर्थपर्यायकी अपेक्षा एक समय होता है ॥ ५७१ ॥

व्यवहार, विकल्प, भेद तथा पर्याय ये सब एक अर्थवाले हैं। अर्थात् इन शब्दोंका अर्थ एक है। उनमें-से व्यंजन पर्यायकी वर्तमान रूपसे स्थिति व्यवहार काल है ॥५७२॥

द्रव्योंकी पर्यायकी जघन्य स्थिति क्षण मात्र होती है उसको समय कहते हैं। गमन करते हुए दो परमाणुओंके परस्परमें अतिक्रमण करनेमें जितना काल लगता है उतना ही समयका प्रमाण है ॥ ५७३ ॥

आढ्यनप्प सुखितनप्प अनालस्यनप्प निरुपहतनप्प जीवंगक्कुमावुदोंदुच्छ्वासनिश्वासमदोंदु प्राणमेंदितु पेळल्पट्टुदु । सप्तोच्छ्वासमोंदु स्तोकमक्कुं । सप्तस्तोकंगळोंदु लवमेंबुदक्कुं ।

अट्ठत्तीसद्धलवा नाली वे नालिया मुहुत्तं तु ।
एगसमयेण हीणं भिण्णमुहुत्तं तदो सेसं ॥५७५॥

अष्टात्रिंशदर्द्धलवाः नाडी द्वे नाडिके मुहूर्तस्तु । एकसमयेन हीनो भिन्नमुहूर्तस्ततः शेषः ॥

मूवत्तेंटुवरे लवेगळु घळिगे येंबुदक्कुं । द्विघळिगेगळोंदु मुहूर्तमक्कुं । तु मत्ते एकसमयविरहीनमाद मुहूर्त्तं भिन्नमुहूर्तमंतर्म्मुहूर्तमुत्कृष्टमक्कुं । ततः मुंदे द्विसमयोनाद्यावल्यसंख्यातैकभागपर्य्यंतमाद शेषंगळनितुमंतर्म्मुहूर्त्तंगळेयप्पुवु ।

इल्लिगुपयोगियप्प गाथासूत्रमिदु :—

ससमयमावलि अवरं समऊण मुहुत्तयं तु उक्कस्सं ।
मज्झासंखवियप्पं वियाण अंतोमुहुत्तमिणं ॥ [ ]

समयाधिकावलि जघन्यांतर्म्मुहूर्तमक्कुं । समयोनमुहूर्तमुत्कृष्टांतर्म्मुहूर्तमक्कुं । मध्यमसंख्यातविकल्पमं मध्यमांतर्म्मुहूर्त्तंगळेंदिदरिं ।

दिवसो पक्खो मासो उडु अयणं वस्समेवमादी हु ।
संखेज्जासंखेज्जाणंततवो होदि ववहारो ॥५७६॥

दिवसः पक्षो मास ऋतुरयनं वर्षमेवमादिः खलु । संख्यातासंख्यातानंततो भवति व्यवहारः ॥

सुखिनः अनलसस्य निरुपहतस्य यो जीवस्य उच्छ्वासनिश्वासः स एव एकः प्राण उक्तो भवेत् । सप्तोच्छ्वासाः स्तोकः । सप्तस्तोका लवः ॥५७४॥

सार्धाष्टात्रिंशल्लवा नाली घटिका । द्वे नाल्यौ मुहूर्तः । स चैकसमयेन हीनो भिन्नमुहूर्तः, उत्कृष्टान्तर्मुहूर्त इत्यर्थः । ततोऽग्रे द्विसमयोनाद्या आवल्यसंख्यातैकभागान्ताः सर्वेऽन्तर्मुहूर्ताः ॥५७५॥ अत्रोपयोगि गाथासूत्रम्—

ससमयमावलि अवरं समऊणमुहुत्तयं तु उक्कस्सं ।
मज्झासंखवियप्पं वियाण अन्तोमुहुत्तमिणं ॥१॥

समयाधिकावलिः जघन्यान्तर्मुहूर्तः समयोनमुहूर्तः उत्कृष्टान्तर्मुहूर्तः । मध्यमा असंख्यातविकल्पा मध्यमान्तर्मुहूर्ताः, इति जानीहि ॥१॥

निश्वास होता है। उसीको प्राण कहते हैं। सात उच्छ्वासका एक स्तोक और सात स्तोकका एक लव होता है ॥ ५७४ ॥

साढ़े अड़तीस लवकी एक नाली होती है उसे घटिका कहते हैं। दो नालीका मुहूर्त होता है। एक समयहीन मुहूर्तको भिन्न मुहूर्त कहते हैं यह उत्कृष्ट अन्तर्मुहूर्त है। इससे आगे दो समयहीन आदिसे लेकर आवलीके एक असंख्यात भाग पर्यन्त सब अन्तर्मुहूर्त होते हैं ॥ ५७५ ॥

यहाँ उपयोगी गाथा सूत्रका अर्थ इस प्रकार है—

वोंदु द्रव्यवोळावु केलवुवर्त्थपर्य्यायंगळं व्यंजनपर्य्यायंगळुमतीतानागतकालंगळोळ्वर्त्तिसुवुवु वर्त्तिसल्पडुवयुमपि शब्ददिदं वर्त्तमानपर्य्यायवेल्लमुं कूडि तत् अदु द्रव्यं भवति द्रव्यमक्कुं स्थित्यधिकारंतिद्दुंदु ।

आगासं वज्जित्ता सव्वे लोगम्मि चेव णत्थि वहिं ।
वावी धम्माधम्मा अवट्ठिदा अचलिदा णिच्चा ॥५८३॥

आकाशं विवर्ज्य सर्व्वे लोके चैव न संति वहिः । व्यापिनौ धर्म्माधर्म्मौ अवस्थितौ अचलितौ नित्यौ ॥

आकाशद्रव्यं पोरगागि शेषद्रव्यंगळनितुं लोकदोळेयप्पवु । लोकदिं पोरगिल्ल । आ द्रव्यंगळोळु धर्म्माधर्म्मद्रव्यंगळेरडुं व्यापिगळेकेंदोडे लोकप्रदेशंगळेनितोळवनितं व्यापिसिर्दुवु तिलदोळु तैलमेंतंते । अवस्थितौ स्थानचलनरहितंगळप्पुदरिंदमवस्थितंगळु, अचलितौ प्रदेशचलनरहितंगळप्पुदरिंदमचलितंगळु, त्रिकालदोळं नाशरहितंगळप्पुदरिंदं नित्यौ नित्यंगळप्पुवु । इल्लिगुपयोगियप्प श्लोकमिदु :—

"औपश्लेषिकवैषयिकावभिव्यापक इत्यपि ।
आधारः त्रिविधः प्रोक्तः कटाकाशतिलेषु च ॥ [ ]

एकस्मिन् द्रव्ये ये अर्थपर्याया व्यञ्जनपर्यायाश्च अतीतानागताः अपिशब्दाद्वर्तमानाश्च सन्ति तावत् तद् द्रव्यं भवति ॥५८२॥ इति स्थित्यधिकारः ॥

आकाशं विवर्ज्य शेषसर्वद्रव्याणि लोके एव सन्ति न तद्बहिः । तेषु धर्माधर्मौ व्यापिनौ सर्वलोकव्याप्तत्वात् तिले तैलवत्, अवस्थितौ स्थानचलनाभावात्, अचलितौ प्रदेशचलनाभावात्, नित्यौ त्रैकालेऽपि विनाशाभावात् । अत्रोपयोगी श्लोकः—

औपश्लेषिकवैषयिकावभिव्यापक इत्यपि ।
आधारस्त्रिविधः प्रोक्तः कटाकाशतिलेषु च ॥५८३॥

एक द्रव्यमें जितनी अतीत, अनागत और वर्तमान अर्थपर्याय तथा व्यंजनपर्याय होती है उतना ही वह द्रव्य होता है ॥५८२॥ स्थिति अधिकार पूर्ण हुआ ।

आकाशको छोड़कर शेष सब द्रव्य लोकमें ही हैं, बाहर नहीं हैं। उनमें धर्म और अधर्म तिलोंमें तेलकी तरह सब लोकमें व्याप्त होनेसे व्यापी हैं। तथा अवस्थित हैं क्योंकि अपने स्थानसे विचलित नहीं होते। प्रदेशों में हलन-चलन न होने से अचलित हैं और तीनों कालोंमें भी विनाश न होनेसे नित्य हैं। इस विषयमें उपयोगी श्लोक—आधार तीन प्रकार का कहा है—औपश्लेषिक, वैषयिक और अभिव्यापक। इसके तीन उदाहरण हैं—चटाई, आकाश और तेल। अर्थात् चटाईपर बालक सोता है, यहाँ चटाई औपश्लेषिक आधार है। आकाश में पदार्थ स्थित हैं, यहाँ आकाश वैषयिक आधार है। तिलोंमें तेल यहाँ अभिव्यापक आधार है। इसी तरह लोकाकाशमें धर्म-अधर्म व्यापी हैं यहाँ अभिव्यापक आधार है ॥५८३॥

ववहारो पुण कालो पोग्गलदव्वादणंतगुणमेत्तो ।
तत्तो अणंतगुणिदा आगासपदेसपरिसंखा ॥५९०॥

व्यवहारः पुनः कालः पुद्गलद्रव्यादनंतगुणमात्रः । ततोऽनंतगुणिताः आकाशप्रदेशपरिसंख्याः ॥

व्यवहारकालमें बुदु मत्ते पुद्गलद्रव्यमं नोडलुमनंतगुणमात्रमक्कुमदं नोडलुमनंतगुणंगळाकाशद्रव्यद प्रदेशपरिसंख्येगळु ।

लोगागासपदेसा धम्माधम्मेगजीवगपदेसा ।
सरिसा हु पदेसो पुण परमाणु अवट्ठिदं खेत्तं ॥५९१॥

लोकाकाशप्रदेशाः धर्माधर्मैकजीवप्रदेशाः सदृशाः खलु प्रदेशः पुनः परमाण्ववस्थितं क्षेत्रं ॥

लोकाकाशप्रदेशंगळुं धर्मद्रव्यप्रदेशंगळुमधर्मद्रव्यप्रदेशंगळुमेकजीवप्रदेशंगळुं सदृशंगळप्पुवु खलु स्फुटमागि । ई नाल्कुं द्रव्यंगळ प्रदेशंगळु प्रत्येकं जगच्छ्रेणीघनप्रमितंगळप्पुवु । प्रदेशमें बुदेनितु प्रमाणमें दोडे पुनः मत्ते पुद्गलपरमाण्ववष्टब्ध क्षेत्रमेनितें प्रमाणमक्कुमदु कारणदिदं जघन्यक्षेत्रमं जघन्यद्रव्यमुमविभागिगळप्पुवु । संदृष्टि :—

	जीव	पुद्गल	ध.	अ.	लो =	मु का	व्य-का	अलोकाकाश
							१६ ख ख	१६ ख ख ख
द्र	१६	१६ ख	१	१	१	≡	≡ख ख ख	≡ ख ख ख ख
क्षे	≡ख	≡ख ख	≡	≡	≡	≡	अ ख ख ख	अ ख ख ख ख
का	अ=ख	अ ख ख	क ३	क ३	क ३	क ३	के	के १
भा	के ४ ख ख ख ख	के ३ ख ख ख	ओ. ३	ओ. ३	ओ ३	ओ ३	ख ख	ख

व्यवहारकालः पुनः पुद्गलद्रव्यादनन्तगुणः । ततोऽनन्तगुणिता आकाशप्रदेशपरिसंख्या ॥५९०॥

लोकाकाशप्रदेशा धर्मद्रव्यप्रदेशा अधर्मद्रव्यप्रदेशा एकैकजीवद्रव्यप्रदेशाश्च सदृशाः खलु संख्यया समाना एव प्रत्येकं जगच्छ्रेणिघनमात्रत्वात् । प्रदेशप्रमाणं पुनः पुद्गलपरमाण्ववष्टब्धक्षेत्रमात्रं भवति । तेन जघन्यक्षे-

व्यवहारकाल पुद्गल द्रव्यसे अनन्तगुणा है। और उससे अनन्तगुणी आकाशके प्रदेशोंकी संख्या है ॥५९०॥

लोकाकाशके प्रदेश, धर्मद्रव्यके प्रदेश, अधर्मद्रव्यके प्रदेश और एक-एक जीवद्रव्यके प्रदेश संख्याकी दृष्टिसे समान ही हैं क्योंकि प्रत्येकके प्रदेश जगत्श्रेणिके घन प्रमाण हैं। पुद्गलका परमाणु जितने क्षेत्रको रोकता है उतना ही प्रदेशका प्रमाण है। अतः जघन्यक्षेत्र अर्थात् प्रदेश और जघन्यद्रव्य परमाणु अविभागी हैं उनका विभाग नहीं हो सकता। अ-

१. ब °क्षेत्रमेनितनितें । २. म °मिरप्पुवु ।

पोग्गलदव्वंहि अणू संखेज्जादी हवंति चलिदा हु ।
चरिममहक्खंधम्मि य चलाचला होंति हु पदेसा ॥५९३॥

पुद्गलद्रव्ये अणवः संख्यातादयो भवंति चलिताः खलु । चरममहास्कंधे च चलाचला भवंति प्रदेशाः ॥

पुद्गलद्रव्यदोळु अणुगळुं द्व्यणुकादि संख्यातासंख्यातानंतपरमाणुस्कंधंगळुं चलितंगळु स्फुटमागि, चरममहास्कंधदोळु प्रदेशाः परमाणुगळु चलाचला भवंति चलाचलंगळप्पुवु ।

अणुसंखासंखेज्जाणंता य अगेज्झगेहि अंतरिया ।
आहारतेजभासामणकम्मइया धुवक्खंधा ॥५९४॥

अणुसंख्यातासंख्यातानंताश्चाग्राह्यैरंतरिताः आहारतेजोभाषामनःकार्म्मण ध्रुवस्कंधाः ॥

सांतरणिरंतरेण य सुण्णा पत्तेयदेह धुवसुण्णा ।
बादरणिगोदसुण्णा सुहुमणिगोदा णभो महक्खंधा ॥५९५॥

सांतरणिरंतरेण च शून्य प्रत्येकदेहध्रुवशून्यानि । बादरनिगोदशून्यानि सूक्ष्मनिगोदाः नभांसि महास्कंधाः ॥

अणुवर्गणेगळें दुं[1] संख्याताणुसमूहवर्गणेगळें दुं[2] मसंख्याताणुसमूहवर्गणेगळें दु[3] मनंतपरमाणुसमूहवर्गणेगळें दुं[4] आहारवर्गणेगळें दुं[5] मी याहारवर्गणं मोदलागुमेल्लमुमनंतपरमाणुस्कंधंगळप्पुवु-। मग्राह्यवर्गणेगळें दुं[6] तैजसशरीरवर्गणेगळें दु[7] मग्राह्यवर्गणेगळें दु[8] भाषावर्गणेगळें दु[9] मग्राह्यवर्गणेगळें दु[10] मनोवर्गणेगळें दु[11] मग्राह्यवर्गणेगळें दु[12] कार्म्मणवर्गणेगळें दु[13] ध्रुववर्गणेगळें दु[14] सांतरणिरंतरवर्गणेगळें दु[15] शून्यवर्गणेगळें दु[16] प्रत्येकशरीरवर्गणेगळें दु[17] ध्रुवशून्यवर्गणेगळें दु[18] बादरनिगोदवर्गणेगळें दु[19] शून्यवर्गणेगळें दु[20] सूक्ष्मनिगोदवर्गणेगळें दु[21] नभोवर्गणेगळें दु[22] महास्कंधवर्गणेगळें दितु[23] पुद्गलवर्गणेगळु प्रभे-

---

पुद्गलद्रव्ये अणवः द्व्यणुकादिसंख्यातासंख्यातानन्ताणुस्कन्धाश्चलिताः खलु स्फुटम् । चरममहास्कन्धे च प्रदेशाः परमाणवः चलाचला भवन्ति ॥५९३॥

अणुवर्गणा संख्याताणुवर्गणा असंख्याताणुवर्गणा अनन्ताणुवर्गणा आहारवर्गणा अग्राह्यवर्गणा तैजसशरीरवर्गणा अग्राह्यवर्गणा भाषावर्गणा अग्राह्यवर्गणा मनोवर्गणा अग्राह्यवर्गणा कार्मणवर्गणा ध्रुववर्गणा सान्तरनिरन्तरवर्गणा शून्यवर्गणा प्रत्येकशरीरवर्गणा ध्रुवशून्यवर्गणा बादरनिगोदवर्गणा शून्यवर्गणा सूक्ष्मनिगोदवर्गणा नभोवर्गणा महास्कन्धवर्गणा चेति पुद्गलवर्गणाः त्रयोविंशतिभेदा भवन्ति । अत्रोपयोगी श्लोकः—

पुद्गल द्रव्यमें परमाणु और द्व्यणुक आदि संख्यात, असंख्यात और अनन्त परमाणुओंके स्कन्ध चलित होते हैं । अन्तिम महास्कन्धमें प्रदेश चल-अचल हैं ॥५९३॥

अणुवर्गणा, संख्याताणुवर्गणा, असंख्याताणुवर्गणा, अनन्ताणुवर्गणा, आहारवर्गणा, अग्राह्यवर्गणा, तैजसशरीरवर्गणा, अग्राह्यवर्गणा, भाषावर्गणा, अग्राह्यवर्गणा, मनोवर्गणा, अग्राह्यवर्गणा, कार्मणवर्गणा, ध्रुववर्गणा, सान्तरनिरन्तरवर्गणा, शून्यवर्गणा, प्रत्येकशरीरवर्गणा, ध्रुवशून्यवर्गणा, बादरनिगोदवर्गणा, शून्यवर्गणा, सूक्ष्मनिगोदवर्गणा, नभोवर्गणा, महास्कन्धवर्गणा ये तेईस प्रकारकी पुद्गलवर्गणाएँ होती हैं । इस विषयमें उपयोगी श्लो-

उ २५५ । २५५ । ० । २५५   ई संख्यातासंख्यातवर्ग्गणेगळोळु तंतम्मधस्तनराशियिदमनंतरो-

म १६ १६ ०० १६
ज १६ । १६ । ०० । १६

परितनराशिगळं भागिसिदोडावुदों दु लब्धमदु विवक्षितवर्ग्गणेगे गुणकारमक्कुमदें तें दोडे संख्यातवर्ग्गणेगळोळु जघन्यवर्ग्गणेयिंद २ मुपरितनराशियं ३ भागिसि $\frac{३}{२}$ बंद लब्धं द्वितीयवर्ग्गणेयोळु गुणकारमक्कुं गुण्यं जघन्यवर्ग्गणेयक्कु $२\frac{३}{२}$ मिदनपवर्त्तिसिदोडे त्र्यणुकमक्कु-३। मंते द्विचरमवर्ग्गणेयिंदं चरमवर्ग्गणेयं भागिसिदोडिदु $\frac{१५}{१४}$ चरमवर्ग्गणेयोळु गुणकारमक्कुं। गुण्यं द्विचरमवर्ग्गणेयक्कु $१४\frac{१५}{१४}$ मिदनपवर्त्तिसिदोडे चरमवर्ग्गणेयक्कु-१५। मिंते असंख्यातवर्ग्गणेगळोळं द्विचरमवर्ग्गणेयिंदमुपरितनचरमवर्ग्गणेयं भागिसिदोडे चरमदोळु गुणकारमक्कुं गुण्यं द्विचरमवर्ग्गणेयक्कु $२५४\frac{२५५}{२५५}$ मिदनपवर्त्तिसिदोडे चरमवर्ग्गणेयक्कुं। २५५। इल्लियों दु परमाणुवं कूडिदोडे अनंतवर्ग्गणेगळोळु जघन्यवर्ग्गणे परिमितानंतजघन्यराशिप्रमाणमक्कुमेकें दोडे द्विकवारासंख्यातोत्कृष्टदोळों दु रूपं कूडिदोडे या स्कंधमनंतवर्ग्गणेगळोळु जघन्यवर्ग्गणेयप्पुदरिदं। आ जघन्यानंतवर्ग्गणेय मेलेकैक परमाणुविदमधिकंगळागुत्तं पोगि तदुत्कृष्टवर्ग्गणे तज्जघन्यमं नोडलनंतगुणितमक्कुं उ २५६ ख मेलेयाहारजघन्यसदृशवर्ग्गवर्ग्गणेगळु एकपरमाणुविदमधिकंग-

ज २५६

उ २५५ । २५५ ० ० २५५

म १६ । १६ । ० ० १६
ज १६ । १६ । ० ० १६

अत्र संख्याताणुवर्गणासु असंख्याताणुवर्गणासु च विवक्षितवर्गणामानेतुं गुणकारः तदधस्तनवर्गणाया अधस्तनवर्गणाभक्तविवक्षितवर्गणामात्रः यथा त्र्यणुकमानेतुं द्व्यणुकस्य द्व्यणुकभक्तत्र्यणुकमात्रः २ । $\frac{३}{२}$ तदनन्तरोपरि-

---

वर्गणामें भाग देनेसे जो प्रमाण आवे उतना है। जैसे त्र्यणुक लानेके लिए द्व्यणुकका गुणकार द्व्यणुकसे त्र्यणुकमें भाग देनेपर जितना प्रमाण आवे उतना है। उसके अनन्तर उत्कृष्ट असंख्याताणुवर्गणामें एक परमाणु अधिक होनेपर अनन्ताणुवर्गणाका जघन्य होता है। उसे सिद्धराशिके अनन्तवें भाग प्रमाण अनन्तसे गुणा करनेपर अनन्ताणुवर्गणाका उत्कृष्ट होता है। उसमें एक परमाणु अधिक होनेपर उससे ऊपरकी आहारवर्गणाका जघन्य होता है। उसमें सिद्धराशिके अनन्तवें भाग देनेपर जो लब्ध आवे उसे जघन्यमें मिलानेपर आहारवर्गणा

नंतरोपरितनाग्राह्यवर्गणेगळोळु जघन्यमेकपरमाणुविनमधिकमक्कुं। तदुत्कृष्टं तज्जघन्यमं नोडलनंतगुणमक्कुं

उ २५६ ख १ ख १ ख ख ख / ख ख
अग्रा ः
ज २५६ ख १ ख १ ख १ ख / ख ख

तदनंतरोपरितनभाषावर्गणेगळोळु जघन्यमेकपरमाणुविनधिकमक्कुं, तदुत्कृष्टं तदनंतैकभागदिं विशेषाधिकमक्कुं

उ २५६ ख १ ख १ ख १ ख १ ख ख / ख ख ख
भाषा ः
ज २५६ ख १ ख १ ख १ ख १ ख / ख ख

तदनंतरोपरितनाग्राह्यवर्गणेगळोळु जघन्य-

तदुत्कृष्टं तदनन्तैकभागेनाधिकं—उ २५६ ख १ ख १ ख १ ख / ० ख ख
तेजो ः
ज २५६ ख १ ख १ ख / ख

तदनन्तरोपरितनाग्राह्यवर्गणाजघन्यमेकाणुनाधिकं तदुत्कृष्टं ततोऽनन्तगुणं—उ २५६ ख १ ख १ ख १ ख ख / ० ख ख
अग्रेज ः
ज २५६ ख १ ख १ ख १ ख / ख ख

तदनन्तरोपरितनभाषावर्गणाजघन्यं एकाणुनाधिकं तदुत्कृष्टं तदनन्तैकभागेनाधिकं—

उ २५६ ख १ ख १ ख १ ख १ ख १ ख / ० ख ख ख
भाषा ः
ज २५६ ख १ ख १ ख १ ख १ ख / ख ख

ऊपरकी तैजसशरीरवर्गणाका जघन्य होता है। उसमें सिद्धराशिके अनन्तवें भागसे भाग देनेसे जो लब्ध आवे उसे उसीमें मिलानेपर तैजसशरीरवर्गणाका उत्कृष्ट होता है। उसमें एक परमाणु अधिक होनेपर उससे ऊपरकी अग्राह्यवर्गणाका जघन्य होता है। उसमें सिद्धराशिके अनन्तवें भागसे गुणा करनेपर उसका उत्कृष्ट होता है। उसमें एक परमाणु अधिक होनेपर

तदनंतरोपरितनकार्म्मणवर्गणाजघन्यमेकपरमाणुविंदधिकमक्कुं । अदरुत्कृष्टं तदनंतैकभागदिंदं विशेषाधिकमक्कुं

उ २५६ ख १ ख ख ख १ ख १ ख ख १ ख ख ख
कार्म्मण ० ख ख ख [illegible] ख

ज २५६ ख १ ख ख ख ख १ ख ख १ ख १ ख
ख ख ख ख

तदनंतरोपरितनध्रुववर्गणेगळोळु जघन्यमेकपरमाणुविंदधिकमक्कुं तदुत्कृष्टमनंतजीवराशिगुणित-मक्कुं :—उ २५६ ख १ ख ख ख १ ख १ ख १ ख ख १ ख ख १६ ख
ध्रुव ० ख ख ख ख ख

ज २५६ ख १ ख ख १ ख ख १ ख ख १ ख ख १ ख
ख ख ख ख ख

उ २५६ ख १ ख १ ख १ ख १ ख १ ख १ ख १ ख ख
० ख [illegible] [illegible] ख
अग्रह्य ०

ज २५६ ख १ ख १ ख १ ख १ ख १ ख १ ख
ख ख ख ख ख

तदनन्तरोपरितनकार्मणवर्गणाजघन्यमेकाणुनाधिकं तदुत्कृष्टं तदनन्तैकभागेनाधिकं—

उ २५६ ख १ ख १ ख १ ख १ ख १ ख १ ख १ ख १ ख १ ख
० ख ख ख ख ख
कार्मण ०

ज २५६ ख १ ख १ ख १ ख १ ख १ ख १ ख १ ख
ख ख ख ख

तदनन्तरोपरितनध्रुववर्गणाजघन्यमेकाणुनाधिकं तदुत्कृष्टं ततोऽनन्तजीवराशिगुणं—

उ २५६ ख १ ख १ ख १ ख १ ख १ ख १ ख १ ख १ ख १६ ख
० ख ख ख ख ख
ध्रुव ०

ज २५६ ख १ ख १ ख १ ख १ ख १ ख १ ख १ ख १ ख
ख ख ख [illegible] ख

अनन्तवें भागसे भाग देनेपर जो लब्ध आवे उसे उसीमें मिला देनेपर उसका उत्कृष्ट होता है। उससे एक परमाणु अधिक होनेपर उससे ऊपरकी अग्राह्यवर्गणाका जघन्य है। उससे अनन्तगुणा उसका उत्कृष्ट है। उससे एक परमाणु अधिक होनेपर उससे ऊपरकी कार्मणवर्गणा का जघन्य है। उसमें सिद्धराशिके अनन्तवें भागसे भाग देनेपर जो लब्ध आवे उसे उसमें मिलानेपर उसका उत्कृष्ट होता है। उससे एक परमाणु अधिक उससे ऊपरकी ध्रुववर्गणा

तदनंतरोपरितनप्रत्येकशरीरवर्ग्गणे पेळल्पडुगुमदेंतेंदोडे ओव्वं जीवन वोंदु देहदोळु पचितकर्म्मनोकर्म्मस्कंधं प्रत्येकशरीरवर्ग्गणेयेंबुदक्कुमदर जघन्यवर्ग्गणे यावजीवनोळक्कुमेंदोडे आवनोव्वं क्षपितकर्म्माशलक्षणदिदं बंदु पूर्व्वकोटिवर्षायुष्यमनुष्यजीवंगळोळ्पुट्टि मनुष्यनागियंतर्म्मुहूर्त्ताधिकाऽष्टवर्षंगळिंदं मेले सम्यक्त्वमुमं संयममुमं युगपत्स्वीकरिसि सयोगकेवलियादोडदेशोनपूर्व्वकोटियं औदारिकतैजसशरीरंगळ अवस्थितिगणनेयोळु निर्ज्जरेयं माडि कार्म्मणशरीरक्कं गुणश्रेणिनिर्ज्जरेयं माडि चरमसमयभव्यसिद्धमप्प चरमसमयवयोगिकेवलिगे त्रिशरीरसंचयं नामगोत्रवेदनीयंगळ मेले आयुरौदारिकतैजसशरीरंगळिनधिकमाद त्रिशरीरसंचयं प्रत्येकशरीरजघन्यवर्ग्गणेयक्कुं । तदुत्कृष्टवर्ग्गणासंभवमावेडेयोळेंदोडे नंदीश्वरद्वीपद अकृत्रिममहाचैत्यालयंगळ धूपघटंगळोळं स्वयंभूरमणद्वीपदकर्म्मभूमिप्रतिबद्धक्षेत्रदोळु नेगेदकाळ्किच्चुगळोळं बादर-

उ २५६ ख १ ख १ ख १ ख १ ख १ ख १ ख १ ख १ ख १ ख १६ ख १६ ख १६ ख
　　० ख ख ख ख ख
सुणव ०
　　०

ज २५६ ख १ ख १ ख १ ख १ ख १ ख १ ख १ ख १ ख १ ख १६ ख १६ ख
　　ख ख ख ख ख

षोडशवर्गणा एवं सिद्धाः । तदनन्तरोपरितनप्रत्येकशरीरवर्गणा तु एकजीवस्य एकदेहोपचितकर्मनोकर्मस्कन्धः । तत्र कश्चिज्जीवः क्षपितकर्मांशलक्षणः पूर्वकोटिवर्षायुः मनुष्यो भूत्वा अन्तर्मुहूर्ताधिकाष्टवर्षोपरि सम्यक्त्वसंयमौ युगपत् स्वीकृत्य सयोगकेवली जातः देशोनपूर्वकोटिपर्यन्तमौदारिकतैजसशरीरयोरवस्थितिगणनया निर्जरां कुर्वन् कार्मणशरीरस्य च गुणश्रेणिनिर्जरां कुर्वन् चरमसमयायोगिकेवली स्यात् । तस्यायुः औदारिकतैजसशरीराधिकनामगोत्रवेदनीयरूपत्रिशरीरसंचयः तज्जघन्यं भवति । नन्दीश्वरद्वीपस्य अकृत्रिममहाचैत्यालयानां धूपघटेषु स्वयंभूरमणद्वीपसंभूतदवाग्निषु च बादरपर्याप्ततेजस्कायिकाः एकबन्धनबद्धा असंख्यातावलिवर्गमात्राः

उत्कृष्ट सान्तरनिरन्तरवर्गणामें एक परमाणु अधिक होनेपर उससे ऊपरकी शून्यवर्गणाका जघन्य होता है। उसे अनन्तगुणित जीवराशिके प्रमाणसे गुणा करनेपर उसका उत्कृष्ट होता है। इस प्रकार सोलह वर्गणा सिद्ध हुई। उससे ऊपर प्रत्येक शरीर वर्गणा है। एक जीवके एक शरीरके विस्रसोपचय सहित कर्म-नोकर्मके स्कन्धको प्रत्येक शरीरवर्गणा कहते हैं। शून्यवर्गणाके उत्कृष्टसे एक परमाणु अधिक जघन्य प्रत्येक शरीरवर्गणा होती है। जिसके कर्मके अंश क्षयरूप हुए हैं ऐसा कोई क्षपितकर्मांश जीव एक पूर्वकोटि वर्ष आयु लेकर मनुष्य जन्म धारण करके अन्तर्मुहूर्त अधिक आठ वर्षके ऊपर सम्यक्त्व और संयमको एक साथ स्वीकार करके सयोगकेवली हुआ। वह कुछ कम एक पूर्व कोटी पर्यन्त औदारिक शरीर और तैजसशरीरको अवस्थिति गणनाके अनुसार निर्जरा करता हुआ और कार्मणशरीरकी गुणश्रेणिनिर्जरा करता हुआ अयोगकेवलीके चरमसमयको प्राप्त हुआ। उसके आयुकर्म औदारिक और तैजस शरीरके साथ नाम गोत्र वेदनीय कर्मके परमाणुओंका समूह रूप जो तीन शरीरोंका स्कन्ध होता है यह जघन्य प्रत्येक शरीरवर्गणा है। इस जघन्यको पल्यके असंख्यातवें भागसे गुणा करनेपर उत्कृष्ट प्रत्येक शरीर वर्गणा होती है। नन्दीश्वर द्वीपके अकृत्रिम महाचैत्यालयोंके धूपघटोंमें और स्वयम्भूरमणद्वीपमें उत्पन्न दवाग्निमें असंख्यात

ष्यसंख्येयभागमात्र पुळविगळोळिरुतिर्दं गुणितकर्म्मांशानंतानंतजीवंगळ सविस्रसोपचय त्रिशरीर संचयमं कोळुत्तिरलक्कुं :—

उ स ३२ ७ ७ ख ख १२–१६ ख १३ ≡ ७ ८ ७
बादरनिगोद ९≡ ७।५ ७

ज स ७ ७ ख ख १२–१६ ख १३ ≡ ७ ८ प
९ ≡ ७ ५ प
७

ई बादरनिगोदोत्कृष्टवर्ग्गणेयोळेकरूपमनधिकं माडुत्तिरलु तृतीयशून्यवर्ग्गणेगळोळु जघन्यवर्ग्गणेयक्कुं

तृतीय शून्यः ०

ज स ३२ ७ ७ ख ख १२– १६ ख १३–≡ ७ ८ ७
७
९≡७।५

सूक्ष्मनिगोदजघन्यवर्ग्गणेयावेडेयोळु संभविसुगुमें दोडे जलदोळु स्थलदोळमाकाशदोळमेंदु

कर्मांशानन्तानन्तबादरनिगोदजीवानां सविस्रसोपचयत्रिशरीरसंचयः उत्कृष्टबादरनिगोदवर्गणा भवति—

उ ० स ३२ ७ ७ ख ख १२—१६ ख १३— ≡ ७ ८ ७
७
बादरणिगोदसरीर ० ९ ≡ ७ ५

ज ० स ७ ७ ख ख १२—१६ ख १३— ≡ ७ ८ प
७ ७
९ ≡ ७ ५ प
७

इयमेकरूपाधिका तृतीयशून्यवर्गणाजघन्यं भवति—

वियसुण्णवग्गणा ज स ३२ ७ ७ ख ख १२—१६ ख १३— ≡ ७ ८ ७
७
९ ≡ ७ ५

एक परमाणु हीन करनेपर उत्कृष्ट ध्रुव शून्यवर्गणा होती है। तथा इस जघन्यको जगत् श्रेणिके असंख्यातवें भागसे गुणा करनेपर उत्कृष्ट बादरनिगोदवर्गणा होती है। स्वयम्भूरमणद्वीपमें जो मूलक आदि सप्रतिष्ठित प्रत्येक वनस्पतियोंके शरीर हैं उनमें एक बन्धनबद्ध जगत्श्रेणिके असंख्यातवें भागप्रमाण पुलवियोंमें रहनेवाले गुणितकर्मांश अनन्तानन्त बादर निगोद जीवोंका जो विस्रसोपचय सहित औदारिक तैजस कार्मणशरीरका उत्कृष्ट संचय है

दुत्कृष्टवर्गणेगे संभवमावेडेयोळ्यकुमें वोडे महामत्स्यशरीरवोळु एकबंधनबद्धावल्यसंख्यातेकभाग-मात्रपुळविगळोळिरुतिर्व गुणितकर्मांशानंतानंतजीवंगळसविस्रसोपचयत्रिशरीरसंचयमं प्रहि-सुत्तिरलक्कुं :— उ स ३२ ० ० स स १२– १६ स १३–८ ≡ ० ८ सू २ ०

सूक्ष्मनिगोव ९ ≡ ० ५ ० ०

मेलणेरडुंवर्गणेगळु सुगमंगळवें तें वोडे सूक्ष्मनिगोवुत्कृष्टवर्गणेयोळेकरूपं कूडिवोडे नभोवर्गंके-गळोळु जघन्यवर्गणेयक्कुं :—

ज स ३२ ० ० स स १२– १६ स १३–८ ≡ ० ८ सू २ ०

नभोवर्गणा ९ ≡ ० ५ ०

ई जघन्यवर्गणेयं प्रतरासंख्येयभागदिवं गुणिसुत्तिरलु नभोवर्गणगळोळुत्कृष्टवर्गणेयक्कुं :—

उ स ३२ ० ० स स १२– १६ स १३–८ ≡ ० ८ सू २ ० ०

नभोवर्गणा ९ ≡ ० ५

निगोदवर्गणोत्कृष्टं महामत्स्यशरीरे एकबन्धनबद्धावल्यसंख्यातैकभागमात्रपुलविस्थितगुणितकर्मांशानन्तानन्त-जीवानां सविस्रसोपचयत्रिशरीरसंचयो भवति—

सुहमणि उ० स ३२ ० ० स स १२—१६ स १३—८ ≡ ० ८ सू २ ०

९ ≡ ० ५ ० ०

इदं एकरूपयुतं नभोवर्गणाजघन्यं भवति—

णभवग्ग ज स ३२ ० ० स स १२—१६ स १३—८ ≡ ० ८ सू २ ०

९ ≡ ० ५ ० ०

इदं प्रतरासंख्येयभागगुणितं नभोवर्गणोत्कृष्टं भवति—

णभवग्ग उ स ३२ ० ० स स १२—१६ स १३—८ ≡ ० ८ सू २ ० ०

९ ≡ ० ५ ० ०

समाधान—नहीं, क्योंकि बादरनिगोदवर्गणाके शरीरोंसे सूक्ष्मनिगोदवर्गणाके शरीरों-का प्रमाण सूच्यंगुलके असंख्यातवें भाग गुणित है। इससे वहाँ जीव भी बहुत हैं। अतः उन जीवोंके तीन शरीर सम्बन्धी परमाणु भी बहुत हैं। जघन्य सूक्ष्मनिगोदवर्गणाको पल्यके

उक्तार्थोपसंहारमं माडुत्तं त्रयोविंशतिवर्गणेगळोळजघन्योत्कृष्टानुत्कृष्टाजघन्य भेदमुमं तदल्पबहुत्वमुमं गाथाषट्कदिदं पेळ्दपं :—

परमाणुवग्गणम्मि ण अवरुक्कस्सं च सेसगे अत्थि ।
गेज्झमहाक्खंधाणं वरमहियं सेसगं गुणियं ॥५९६॥

परमाणुवर्गणायां नावरोत्कृष्टं च शेषकेऽस्ति । ग्राह्यमहास्कंधानां वरमधिकं शेषकं गुणितं ॥

परमाणुवर्गणेयोळु जघन्योत्कृष्टविशेषमिल्लेकेंदोडे परमाणुगळु निर्व्विकल्पंगळप्पुदरिदं शेषसंख्यातवर्गणादि महास्कंधावसानमाद द्वाविंशतिवर्गणेगळोळु जघन्योत्कृष्टाविविशेषं वक्ति उंटु । आ द्वाविंशतिवर्गणेगळोळु ग्राह्यमहास्कंधानां आहारतेजोभाषामनःकार्म्मणवर्गणेगळु ग्राह्यमें बुदक्कुमवरुत्कृष्टवर्गणेगळुं महास्कंधोत्कृष्टवर्गणेयुमें बोयारु वर्गणेगळु तंतम्म जघन्यमं नोडलु विशेषाधिकंगळु, चुळिद पदिनारुं वर्गणेगळुत्कृष्टवर्गणेगळु तंतम्म जघन्यमं नोडलु गुणितंगळप्पुवु ।

सिद्धाणंतिमभागो पडिभागो गेज्झगाण जेट्ठट्ठं ।
पल्लासंखेज्जदिमं अंतिमखंधस्स जेट्ठट्ठं ॥५९७॥

सिद्धानामनंतैकभागः प्रतिभागो ग्राह्याणां ज्येष्ठार्थं । पल्यासंख्येयभागोंऽतिमस्कंधस्य ज्येष्ठार्थं ॥

ई ग्राह्यवर्गणापंचकोत्कृष्टवर्गणानिमित्तमागि प्रतिभागहारं सिद्धानंतैकभागमात्रमक्कुमा भागहारदिदं तंतम्म जघन्यमं भागिसिदेकभागमना जघन्यद मेले कूडिदोडे तंतम्मुत्कृष्टवर्गणेगळप्पुवें बुदत्थं । अंतिममहास्कंधोत्कृष्टवर्गणानिमित्तमागि प्रतिभागहारं पल्यासंख्यातैकभागमात्रमक्कुमा पल्यासंख्यातैकभागदिदं जघन्यवर्गणेयं भागिसिदेकभागमना जघन्यदोळु कूडिदोडे

उक्तार्थमुपसंहरन् तासामेव जघन्योत्कृष्टानुत्कृष्टाजघन्यानि तदल्पबहुत्वं च गाथाषट्केनाह—

परमाणुवर्गणायां जघन्योत्कृष्टे न स्तः, अणूनां निर्विकल्पकत्वात् शेषद्वाविंशतिवर्गणानां तु स्तः। तत्र ग्राह्याणां आहारतेजोभाषामनःकार्मणवर्गणानां महास्कन्धवर्गणायाश्च उत्कृष्टानि स्वस्वजघन्याद्विशेषाधिकानि शेषषोडशवर्गणानां गुणितानि भवन्ति ॥५९६॥

तत्र पञ्चग्राह्यवर्गणानामुत्कृष्टनिमित्तं प्रतिभागहारः सिद्धानन्तैकभागः, तेन स्वस्व-जघन्ये भक्ते एकभागे स्वस्वजघन्ये निक्षिप्ते स्वस्वोत्कृष्टं भवतीत्यर्थः। अन्तिममहास्कन्धोत्कृष्टनिमित्तं प्रतिभागहारः पल्यासं-

उक्त कथनका उपसंहार करते हुए उन्हीं वर्गणाओंके जघन्य, उत्कृष्ट, अनुत्कृष्ट और अजघन्य भेदों तथा अल्पबहुत्वको छह गाथाओंसे कहते हैं—

परमाणुवर्गणामें जघन्य-उत्कृष्ट भेद नहीं है क्योंकि परमाणु निर्विकल्प-भेद रहित होते हैं। शेष बाईस वर्गणाओंमें तो जघन्य-उत्कृष्ट हैं। उनमें-से जो ग्राह्यवर्गणा, आहारवर्गणा, तैजसशरीरवर्गणा, भाषावर्गणा, मनोवर्गणा, कार्मणवर्गणा तथा महास्कन्धवर्गणा हैं इनके उत्कृष्ट अपने-अपने जघन्यसे विशेष अधिक हैं, शेष सोलह वर्गणाओंके गुणित हैं ॥५९६॥

इनमें-से पाँच ग्राह्यवर्गणाओंका उत्कृष्ट लानेके लिए प्रतिभागहार सिद्धराशिका अनन्तवाँ भाग है। उससे अपने-अपने जघन्यमें भाग देकर जो लब्ध आवे उसे उन्हीं

सर्व्वजीवराशियं नोडलनंतगुणितमप्प गुणकारं ध्रुवादि मूरु वर्गणेगळुत्कृष्टवर्गणानिमित्त गुणकारप्रमाणमक्कुमा गुणकारदिदं तंतम्म जघन्यवर्गणेयं गुणिसुत्तं विरलु तंतम्मुत्कृष्टवर्गणेगळप्पुवें बुदत्थं। तु मत्ते ततः मल्लिदं मेलण प्रत्येकशरीरवर्गणेगळुत्कृष्टवर्गणानिमित्तमाद गुणकारं पल्यासंख्यातेकभागमक्कुमा गुणकारगुणित तज्जघन्यवर्गणेये प्रत्येकशरीरवर्गणोत्कृष्टवर्गणेयक्कुमें बुदर्थमिल्लि पल्यासंख्यातेकभागगुणकारमें तें दोडे :—प्रत्येकशरीरस्यजीवकार्म्मणशरीरसमयप्रबद्धं गुणितकर्मांशजीवप्रतिबद्धमप्पुदरिंदमुत्कृष्टयोगार्ज्जितमप्पुदरिदं। तज्जघन्यसमयप्रबद्धमं नोडलु पल्यच्छेदासंख्यातेकभागगुणितमक्कुमदक्के संदृष्टि द्वात्रिंशदंकमक्कुमप्पुदरिदं तज्जघन्यवर्गणेयं तद्गुणकारदिदं गुणिसुत्तिरलु तदुत्कृष्टवर्गणेयक्कुमें बुदत्थं। ततः इल्लिदं मेलण ध्रुवशून्यवर्गणेगळोळु तदुत्कृष्टवर्गणानिमित्तगुणकारमसंख्यातलोकविभक्तसर्व्वमिथ्यादृष्टिराशियक्कु १ ३ ≡ a / ९ ≡ a ५ मी गुणकारदिदं गुणिसिद तज्जघन्यराशि ध्रुवशून्यवर्गणोत्कृष्टवर्गणाप्रमाणमें बुदर्थं।

सेढीसूईपल्लाजगपदरासंखभागगुणगारा।
अप्पप्पण अवरादो उक्कस्सा होंति णियमेण ॥६००॥

श्रेणीसूचीपल्यजगत्प्रतरासंख्यभागगुणकाराः। स्वस्वावरायाः उत्कृष्टा भवंति नियमेन॥

श्रेण्यसंख्यातेकभागमुं सूच्यंगुलासंख्यातेकभागमुं पल्यासंख्यातेकभागमुं जगत्प्रतरासंख्यातेकभागमुं यथासंख्यमागि बादरनिगोदशून्य—सूक्ष्मनिगोदनभोवर्गणेगळुत्कृष्टवर्गणानिमित्तगुणकारंगळप्पुवु।

सर्वजीवराशितोऽनन्तगुणो ध्रुवादित्रिसूणां वर्गणानां उत्कृष्टनिमित्तं गुणकारो भवति। तु पुनः उपरितनप्रत्येकशरीरवर्गणोत्कृष्टनिमित्तं पल्यासंख्यातैकभागः। कुतः? प्रत्येकशरीरस्यकार्मणसमयप्रबद्धा गुणितकर्मांशजीवप्रतिबद्धत्वेन जघन्यसमयप्रबद्धात् छेदासंख्येयगुणितत्वात्। तत्संदृष्टिः द्वात्रिंशत्। तथा सर्वे गुणिते तदुत्कृष्टं भवतीत्यर्थः। ततः ध्रुवशून्यवर्गणोत्कृष्टनिमित्तं गुणकारः असंख्यातलोकभक्तसर्वमिथ्यादृष्टिराशिः १३— ≡ a / ९ ≡ a ५ ॥५९९॥

श्रेणिसूच्यङ्गुलपल्यजगत्प्रतराणामसंख्यातैकभागाः क्रमशः बादरनिगोदशून्यसूक्ष्मनिगोदनभोवर्गणानां उत्कृष्टनिमित्तं गुणकारा भवन्ति। तत्र शून्यवर्गणायां सूच्यङ्गुलासंख्यातगुणकारस्तु सूक्ष्मनिगोदवर्गणाजघन्ये ...

ध्रुव आदि तीन वर्गणाओंके उत्कृष्टके लिए गुणकार समस्त राशिसे अनन्तगुना है। उससे ऊपरकी प्रत्येक शरीरवर्गणाका उत्कृष्ट लानेके लिए पल्यका असंख्यातवाँ भाग गुणकार है। क्योंकि प्रत्येक शरीरवर्गणामें जो कार्मण शरीरके समयप्रबद्ध हैं वे गुणितकर्मांश जीवसम्बन्धी हैं अतः जघन्य समयप्रबद्धसे पल्यके अर्धच्छेदोंके असंख्यातवें भाग गुणे हैं। उनकी संदृष्टि बत्तीस है। उससे जघन्यमें गुणा करनेपर उसका उत्कृष्ट होता है। ध्रुवशून्यवर्गणाके उत्कृष्टके लिए गुणकार सब मिथ्यादृष्टियोंकी राशिमें असंख्यातलोकसे भाग देनेपर जो प्रमाण आवे उतना है ॥५९९॥

बादरनिगोदवर्गणा, शून्यवर्गणा, सूक्ष्मनिगोदवर्गणा और नभोवर्गणाके उत्कृष्ट लानेके लिए गुणकार क्रमसे श्रेणिका असंख्यातवाँ भाग, सूच्यंगुलका असंख्यातवाँ भाग, पल्यका

संख्यातेकभागमात्रंगळप्पुवु। सूक्ष्मनिगोदजघन्यवर्गणेगळु सद्दशघनिकंगळु जलदोळं स्थलदोळमा काशदोळं मेणु आवल्यसंख्यातेकभागमात्रंगळप्पुवु। उत्कृष्टवर्गणेगळु सूक्ष्मनिगोदसंबंधिगळु मत्ते वर्त्तमानकालदोळु महामत्स्यंगळोळावल्यसंख्यातेकभागमात्रंगळप्पुवु। ई मूरु सचित्तवर्गणेगळोळु जघन्यानुत्कृष्टवर्गणेगळु वर्त्तमानकालदोळसंख्यातलोकमात्रंगळप्पुवु। महास्कंधवर्गणेगळु वर्त्तमानकालदोळु तु मत्ते एकमेयक्कुं। महास्कंधमेंबुदावुदेंदोडे भवनंगळुं विमानंगळुमष्टपृथ्विगळुं मेरुगळुं कुलशैलादिगळुमेकीभावमक्कुमदाव तेरदिंदमसंख्यातयोजनंगळनंतरिसिदुवक्कयमेंदोडे एकबंधनबद्धसूक्ष्मपुद्गलस्कंधंगळिंदं समवेतंगळ्गंतराभावमक्कुमप्पुदरिंदं।

हेट्ठिमउक्कस्सं पुण रूवहियं उवरिमं जहण्णं खु।
इदि तेवीसवियप्पा पोग्गलदव्वा हु जिणादिट्ठा ॥६०१॥

अधस्तनोत्कृष्टाः पुनः रूपाधिका उपरितनजघन्याः खलु। इति त्रयोविंशतिविकल्पपुद्गलद्रव्याणि खलु जिनदृष्टानि॥

ई त्रयोविंशतिवर्गणेगळोळु परमाणुवर्गणेयुळ्ळियलुळिद द्वाविंशतिवर्गणेगळ अधस्तनोत्कृष्टवर्गणेगळु रूपाधिकमागुत्तिरलु तत्तदुपरितनवर्गणेगळजघन्यवर्गणेगळप्पुवु खलु नियमदिंदमितु त्रयोविंशतिवर्गणाविकल्पंगळु पुद्गलद्रव्यंगळेंदु जिनरुगळिंदं पेळल्पट्टुवु [illegible]

[illegible] आवल्यसंख्यातैकभागः। सूक्ष्मनिगोदजघन्यानि वर्तमानकाले जले स्थले आकाशे वा [illegible]। उत्कृष्टान्यपि महामत्स्येषु तावन्मात्राणि। अस्मिन् सचित्तवर्गणात्रये अजघन्यानुत्कृष्टं वर्तमानकाले असंख्यातलोकमात्राणि भवन्ति। महास्कन्धवर्गणा वर्तमानकाले एका सा तु भवनविमानाष्टपृथ्वीमेरुकुलशैलादीनामेकता। कथं संख्यातासंख्यातयोजनान्तरितानामेकत्वं? एकबन्धनबद्धसूक्ष्मपुद्गलस्कन्धैः [illegible] ॥६००॥

[illegible]वर्गणानामनुवर्तमानाः शेषाणां अधस्तनवर्गणोत्कृष्टानि रूपाधिकानि भूत्वा [illegible] [illegible] भवन्ति खलु नियमेन इति त्रयोविंशतिवर्गणाविकल्पानि पुद्गलद्रव्याणि [illegible]

[illegible] आदिमें आवलीके असंख्यातवें भागमात्र पायी जाती है। [illegible] वर्गणाका जघन्य वर्तमानकालमें क्षीणकषाय गुणस्थानके अन्तिम समयमें [illegible] जाता है। उत्कृष्ट बादरनिगोदवर्गणा महामत्स्य आदिमें आवलीके असंख्यातवें भाग [illegible] जाती है। सूक्ष्मनिगोदवर्गणाका जघन्य वर्तमानकालमें जल, स्थल अथवा आकाशमें आवलीके असंख्यातवें भाग पाया जाता है। उसका उत्कृष्ट भी महामत्स्योंमें आवलीके असंख्यातवें भाग पाया जाता है। प्रत्येक शरीर, बादरनिगोद और सूक्ष्मनिगोद [illegible] वर्गणाके अजघन्य और अनुत्कृष्ट अर्थात् मध्यमभेद वर्तमानकालमें असंख्यात लोकमात्र पाये जाते हैं। वर्तमानकालमें महास्कन्धवर्गणा एक है वह भवनवासी [illegible], [illegible] विमान, आठ पृथिवियाँ, सुमेरु कुलाचल आदिका एक स्कन्धरूप है।

शंका—इनमें तो संख्यात-असंख्यात योजनका अन्तराल है ये एक कैसे हैं?

समाधान—इनके मध्यमें जो सूक्ष्म पुद्गल स्कन्ध हैं वे सब [illegible] [illegible] एक बन्धनसे बद्ध होनेसे इनमें अन्तराल नहीं है॥६००॥

[illegible] अनुवर्तनाको छोड़कर शेष नीचेकी वर्गणाओंके उत्कृष्ट [illegible] [illegible] ऊपरकी वर्गणाओंके जघन्य होते हैं। इस प्रकार जिनदेवने [illegible]

…णु उत्कृष्टदिदमावल्यसंख्यातैकभागमात्रंगळु क्रमदिदमनंतवर्गणेगळु सलुत्तं विरलु वळिक्कमावुवो दनंतवर्गणेयवरोळु वर्गणेगळु कथंचिदुंटु कथंचिदिल्ल एत्तलानुमुंटक्कुमप्पोडागळु एकं मेणु द्वयं मेणु त्रयं मेणुत्कृष्टदिदमावल्यसंख्यातैकभागमात्रंगळु सदृशधनिकंगळु संभविसुवविंतवस्थितसदृशधनिकंगळु घटियिसुगुमंतु घटिसुवोडं विशेषमुंटावुदें दोडे पूर्व्ववर्गणेगळं नोडलिदेकरूपवर्गणेयिदं विशेषाधिकंगळप्पुवु $\frac{८}{a}$

मत्तमी विधानदिदमेयनंतवर्गणेगळु नडेववु । मत्तावुवो दनंतरोपरितनवर्गणेगळोळधस्तनाधस्तनवर्गणेगळं नोडलेकैकरूपवर्गणेगळिदं विशेषाधिकंगळप्पुविंतु । ई विधानदिदं नडसल्पडुवुदेन्नेवरं यवमध्यमन्नेवरं मत्ता यवमध्यवर्गणेगळु क्वचिदस्ति क्वचिन्नास्ति यद्यस्ति तदा एकं मेणु द्वयं मेणु त्रयं मेणु उत्कृष्टदिदमावल्यसंख्यातैकभागमात्रंगळप्पुवंतागुत्तलुं पूर्व्वोक्तक्रमदिदमनंतराधस्तन सदृशधनिकवर्गणेगळं नोडलेकवर्गणेयिदं विशेषाधिकंगळप्पुवु मत्तमिंतुमनंतवर्गणेगळवस्थितक्रमदिदं नडेववु । वळिक्क मल्लिदं मेले यावुवो दनंतरवर्गणेयदु स्यादस्ति स्यान्नास्ति यद्यस्ति तदा एकं मेणु द्वयं मेणु त्रयं मेणुत्कृष्टदिदमावल्यसंख्यातैकभागमात्रंगळप्पु-

---

क्रमेण अनन्तरवर्गणा अतीत्य अनन्तरवर्गणाद्रव्यं कथञ्चिदस्ति कथञ्चिन्नास्ति यद्यस्ति तदा एकं वा द्वयं वा त्रयं उत्कृष्टेन आवल्यसंख्यातैकभागः । अयं पूर्वस्मादेकरूपाधिकः $\frac{२}{a}$ एवमनन्तवर्गणा अतीत्य अनन्तरोपरितनवर्गणासु अधस्तनाधस्तनवर्गणाभ्यः एकैकाधिका भवन्ति । एवं यावत् यवमध्यं तावन्नेतव्यम् । यवमध्यसदृशधनिकद्रव्यं क्वचिदस्ति क्वचिन्नास्ति यद्यस्ति तदा एकं वा द्वयं वा त्रयं वा उत्कृष्टेन आवल्यसंख्यातैकभागः । अयं ततोऽप्येकरूपाधिकः । एवमनन्तवर्गणा अतीत्य अनन्तरवर्गणाद्रव्यं स्यादस्ति स्यान्नास्ति, यद्यस्ति तदा एकं वा द्वयं वा त्रयं वा उत्कृष्टेन आवल्यसंख्यातैकभागः । अयं पूर्वस्मादेकरूपहीनः । एवं यावदुत्कृष्टं प्रत्येकवर्गणा तावन्नेयम् । तदुत्कृष्टमपि स्यादस्ति स्यान्नास्ति यद्यस्ति तदा एकं वा द्वयं वा त्रयं वा उत्कृष्टेन

वर्गणासे एक परमाणु अधिक जो प्रत्येक वर्गणा है वह लोकमें होती भी है और नहीं भी होती। यदि है तब एक या दो या तीन या उत्कृष्टसे आवलीके असंख्यातवें भाग होती है। इसी क्रमसे एक-एक परमाणु बढ़ाते-बढ़ाते अनन्त वर्गणा बीतनेपर उससे एक परमाणु अधिक अनन्तरवर्गणा कथंचित् है, कथंचित् नहीं है। यदि है तब एक या दो या तीन उत्कृष्टसे आवलीके असंख्यातवें भाग होती है। पहलेसे इसका प्रमाण एक अधिक है। इस प्रकार अनन्त वर्गणा बीतनेपर अनन्तरकी ऊपरकी वर्गणाओंमें नीचे-नीचेकी वर्गणासे एक-एक अधिक परमाणु होता है। इस प्रकार जबतक यवमध्य आये तब तक ले जाना चाहिए। यवमध्यमें जितने परमाणुओंके स्कन्धरूप प्रत्येक वर्गणा होती है उतने-उतने परमाणुओंके स्कन्धरूप प्रत्येक वर्गणा लोकमें होती भी है या नहीं भी होती ? यदि है तो एक या दो या तीन उत्कृष्टसे आवलीके असंख्यातवें भाग प्रमाण होती हैं। यह उससे भी एक अधिक है। ऐसे अनन्त वर्गणा बीतनेपर अनन्तर जो वर्गणा है वह कथंचित् है कथंचित् नहीं है। यदि है तो एक दो या तीन या उत्कृष्टसे आवलीके असंख्यातवें भाग है।

गदिठाणोग्गहकिरियासाधणभूदं खु होदि धम्मतियं।
वत्तणकिरियासाहणभूदो णियमेण कालो दु ॥६०५॥

गतिस्थानावगाहक्रियासाधनभूतं खलु भवति धर्मत्रयं। वर्तनक्रियासाधनभूतो नियमेन कालस्तु ॥

देशान्तरप्राप्तिहेतुवं गतियें बुदु। तद्विपरीतमं स्थानमें बुदु। अवकाशदानमनवगाहमें बुदु। [illegible] गतिक्रियासाधनभूतं धर्म्मद्रव्यमाकुं। [illegible] स्थानक्रियावंतंगळप्प जीवपुद्गलंगळ्गे स्थानक्रियासाधनभूतमधर्म्मद्रव्यमाकुं [illegible] स्थानक्रियेयोळ् [illegible] येंतेंते।

[illegible] जीवपुद्गलादिद्रव्यंगळ्गे अवगाहक्रियेयोळ् साधनभूतमाकाशमक्कु [illegible] इल्लियेनेवं क्रियावंतंगळप्प अवगाहिजीवपुद्गलंगळ्गे अवका[illegible] निष्क्रियंगळ्ं नित्यसंबंधंगळुमप्पवक्कें तदवगाहुदानमें तें [illegible] तर्त्तिक्रियानुमप्पुदरिदं। येंतोगळ् गमनाभावमागुत्तिरलु सर्व्वगतमाका[illegible] सद्भावमप्पुदरिदमंते धर्म्मादिगळ्गे अवगाहनक्रियाभावदोळ [illegible] गळ्गुमप्पुदरिदं। [illegible]

[illegible] स्थानम्। अवकाशदानमवगाहः। [illegible] गतिक्रियासाधनभूत[illegible] [illegible] निष्क्रियाणां नित्यसंबंधा[illegible] [illegible] अवगाह[illegible] ॥

[illegible] देशको प्राप्त होनेमें जो कारण है वह गति है। [illegible] अवगाह कहते हैं। जैसे मछलीको गमनमें सहायक [illegible] और पुद्गलोंको गतिक्रियामें सहायक धर्मद्रव्य है। [illegible] ठहरनेमें [illegible] पुद्गल [illegible] क्रियामें [illegible]

[illegible] और पुद्गलोंको ही अवकाश देना [illegible] अवकाशदान कैसे सम्भव है?

[illegible]

अण्णोण्णुवयारेण य जीवा वट्टंति पोग्गलाणि पुणो।
देहादीणिव्वत्तणकारणभूदा हु णियमेण ॥६०६॥

अन्योन्योपकारेण च जीवा वर्त्तते पुद्गलाः पुनः। देहादीनां निर्वर्त्तनकारणभूताः स्युः नियमेन ॥

अन्योन्योपकारदिदं स्वामिभृत्यनाचार्य्यशिष्यनें दितेवमादिभावदिदं वर्त्तनं परस्परोपग्रहमक्कुं। अन्योन्योपकारमेंदुदक्कुमेंदुदत्थमवेंतेंदोडे स्वामि येंबं भृत्यरुगळ्गे वित्तत्यागाद्युपकारदोळ् वर्त्तिसुगुं। भृत्यरुगळ् हितप्रतिपादनदिंदमुमहितप्रतिषेधनदिंदमुं वर्त्तिसुवरं। आचार्य्यंगुभयलोक[illegible]उपदेशदर्शनदिदं तदुपदेशविहितक्रियानुष्ठानदिंदमुं शिष्यरुगळुपकारदोळु वर्त्तिसुवरु। शिष्यरुगळुं तदानुकूल्यवृत्तियिदमुपकाराधिकारंगळोळु वर्त्तिसुगुं। इंतन्योन्योपकारदिदं जीवंगळु वर्त्तिसुववु। [illegible] अनुपकारदिंदमुं वर्त्तिसुवु। अनुभयदिंदमुं वर्त्तिसुवु। पुद्गलाः पुनर्द्देहादीनां निर्वर्त्तनकारणभूताः नियमेन पुद्गलंगळु मत्ते जीवंगळ देहादिगळनिर्वर्त्तनकारणभूतंगळप्पुवदि[illegible] कर्म्मनोकर्म्मंगळगे ग्रहणमक्कुं। नोकर्म्मंकर्म्मंवाग्मनउच्छ्वासनिःश्वासंगळ निर्वर्त्तनकारणभूतं[illegible] पुद्गलंगळप्पुवें बुदत्थंमिल्लि पूर्व्वपक्षमं माडिदपं कर्म्मंमपौद्गलिकमे[illegible] [illegible]। आकारवंतंगळप्पौदारिकादिगळ्गे पौद्गलिकत्वं युक्तमें[illegible] [illegible] पौद्गलिकमें[illegible] तद्विपाकक्के मूर्त्तिमत्संबंधनिमित्तत्वदिदं काणल्पट्टुदु [illegible] [illegible] पौद्गलिकत्वमंते कार्म्मणमुं लगुडकंटकादिमूर्त्तिम[illegible]

[illegible] जीवा वर्तन्ते यथा स्वामी भृत्य वित्तदानादिना, भृत्यश्च हित[illegible] [illegible], [illegible] उभयलोक[illegible]तक्रियानुष्ठानाभ्यां, शिष्यश्च आनुकूल्य[illegible] [illegible] अनु[illegible]नाभ्यामपि वर्तन्ते। पुद्गलाः पुनः देहादीनां कर्मनोकर्मवाङ्मनउच्छ्वास[illegible] [illegible] नियमेन [illegible]। ननु कर्मापौद्गलिकं अनाकारत्वात्—आकारवतामौदारिकादी[illegible] [illegible], कर्मापि पौद्गलिकमेव लगुडकण्टकादिमूर्तिमत्[illegible] पच्यमानत्वात्। [illegible] [illegible] [illegible] तथा [illegible]। तत आगतम् [illegible]

[illegible] परस्परमें एक दूसरेका उपकार करते हैं। जैसे स्वामी अपने धन आदिके [illegible] [illegible] करता है और सेवक हितकी बात कहने तथा अहितसे रोकने आदिके [illegible] [illegible] करता है। गुरु उभय लोक और परलोकमें फल देनेवाले [illegible] [illegible] अनुष्ठानके द्वारा शिष्यका उपकार करता है और शिष्य गुरुके अनुकूल [illegible] [illegible] करता है। पुद्गल शरीर आदि तथा कर्म-नोकर्म, वचन, मन, उच्छ्वास, [illegible] [illegible] नियमसे कारण होते हैं।

शंका—कर्म पौद्गलिक नहीं है क्योंकि उसका कोई आकार नहीं है। [illegible] [illegible] है अतः उन्हें पौद्गलिक मानना युक्त है?

समाधान—नहीं, कर्म भी पौद्गलिक होते हैं क्योंकि [illegible], [illegible] [illegible] है जैसे धान्य आदि मूर्तिमान सम्बन्धसे पकनेवाले धान्य [illegible] [illegible] [illegible] होता है। [illegible] [illegible]

मदक्के पौद्गलिकत्वमयुक्तमें दितु पेळ्दाचार्य्यनें दपं—आ इंद्रियवोडनात्मंगे संबंधमुंटो मेणु संबंधमिल्लमो ? येत्तलानुं संबंधमिल्लें बेयप्पोडवल्तेकें दोडे आत्मंगुपकारमागल्वेळ्कुमाउपकारमं माडदु इंद्रियक्कं साचिव्यमं सचिवत्वमुमं माडदु अथवा संबंधमुंटें बेयप्पोडे एकप्रदेशसंबंधमप्पुदरिंदमा अणुवुमितरप्रदेशंगळोळुपकारमं माडदु। अदृष्टवशाविना मनक्कलातचक्रदंते परिभ्रमणमुंटें बेयप्पोडवुयुं संभविसदेकें दोडे अणुमात्रक्के तत्सामर्थ्याभावमप्पुदरिंदं।

अमूर्त्तनप्पात्मंगे निष्क्रियंगे अदृष्टमप्प गुणमन्यत्रक्रियारंभदोळु समर्थमल्तु अहंगे कारल्पट्टुदु। वायुद्रव्यविशेषं क्रियावंतमुं स्पर्शनवंतमुं प्राप्तमागुत्तु वनस्पतियोळु परिस्पंदहेतुवक्कुं तद्विपरीतलक्षणमो मणुमें दितु क्रियाहेतुत्वाभावमक्कुं। वीर्यांतरायज्ञानावरणक्षयोपशमांगोपांगनामोदयापेक्षेयिंदमात्मनिंदुदस्यमानकोष्ठ्यमप्प वायुउच्छ्वासलक्षणमप्पुत्तु प्राणमें दु पेळल्पट्टुदु। आ वायुविंदमेयात्मंगे पोरगण वायुवनभ्यंतरीक्रियमाणनिश्वासलक्षणमपानमें दु पेळल्पट्टुदु। इंता येरडुमात्मंगे अनुग्राहिगळप्पुवेकें दोडे जीवितहेतुत्वदिंदमा मनःप्राणापानंगळ्गे मूर्त्तिमत्वमरियल्पडुवुवेकें दोडे प्रतिघातादिदर्शनदिंदं प्रतिभयहेतुगळप्पअशनिपातादिगळिंदं मनक्के प्रतिघातं कारल्पट्टुदु। सुरादिगळि स्वादिगळिंदमप्प पूतिगंधिप्रतिभयदिंद हस्ततलपुटादिगळिंदमास्यसवर्णदिं

सम्बन्धः स्यात् न वा ? यदि न, तन्न आत्मनः उपकारेण भाव्यं तन्नोपकुर्वीत, इन्द्रियस्य साचिव्यं सचिवत्वं न कुर्यात्। अथ स्यात्, तदा एकदेशसम्बन्धेन सोऽणुः इतरप्रदेशेषु नोपकुर्यात्। अथादृष्टवशेन तस्यालातचक्रवत्परिभ्रमणं तदप्यसंभाव्यं, अणुमात्रस्य तत्सामर्थ्याभावात्, अमूर्तस्य आत्मनो निष्क्रियस्यादृष्टगुणः अन्यत्र क्रियारम्भे समर्थो न। वायुद्रव्यं हि क्रियावत् स्पर्शवत् प्राप्तवनस्पतौ परिस्पन्दहेतुः तद्विपरीतलक्षणोऽयमणुः स्तादृक् क्रियाहेतुर्न स्यात्। वीर्यान्तरायज्ञानावरणक्षयोपशमाङ्गोपाङ्गनामोदयापेक्षेणात्मनोदस्यमानकोष्ठ्यवायुः उच्छ्वासलक्षणः स प्राणः। तेनैव वायुना आत्मनो बाह्यवायुरभ्यन्तरीक्रियमाणो निश्वासलक्षणः अपानः। तौ च आत्मनोऽनुग्राहिणो जीवितहेतुत्वात्, ते च मनःप्राणापाना मूर्तिमन्तः, मनसः प्रतिभयहेत्वशनिपातादिभिः

नहीं है तथा वह परमाणु बराबर है, पौद्गलिक नहीं है। आचार्य कहते हैं—उस अणुरूप मनका सम्बन्ध आत्माके साथ है या नहीं है। यदि नहीं है तो वह आत्माका उपकार नहीं कर सकता और न इन्द्रियोंकी ही सहायता कर सकता है। यदि सम्बन्ध है तो उस अणुरूप मनका सम्बन्ध आत्माके एक देशके साथ ही हो सकता है और ऐसी स्थितिमें वह अन्य प्रदेशोंमें उपकार नहीं कर सकता। यदि कहोगे कि अदृष्टवश वह अणुरूप मन समस्त आत्मामें अलातचक्रकी तरह भ्रमण करता है इससे उसका सर्वत्र सम्बन्ध होता है। तो वह भी सम्भव नहीं है क्योंकि अणुमात्र मनमें ऐसी सामर्थ्यका अभाव है। तथा अमूर्त और क्रियारहित आत्माका गुण अदृष्ट अन्यमें क्रिया करानेमें समर्थ नहीं है। वायु क्रियावान् और स्पर्शवान् होनेसे प्राप्त वृक्षादिमें हलनचलन करनेमें कारण होती है। किन्तु यह अणुरूप मन तो उससे विपरीत लक्षणवाला है इसलिए उस प्रकारकी क्रियामें हेतु नहीं हो सकता। वीर्यान्तराय और ज्ञानावरणके क्षयोपशम और अंगोपांग नामकर्मके उदयकी अपेक्षासे आत्माके द्वारा जो अन्दरकी वायु बाहर निकाली जाती है उसे उच्छ्वास रूप प्राण कहते हैं। और उसी आत्माके द्वारा जो बाहरकी वायु भीतरकी ओर ली जाती है उसे निश्वास रूप अपान कहते हैं। ये प्राण अपान भी आत्माके उपकारी हैं क्योंकि उसके जीवनमें हेतु होते हैं। वे मन, प्राण अपान मूर्तिमान हैं क्योंकि भयके हेतु वज्रपात आदिसे मनका, और

कर्म्मोदयदिदं कार्म्मणवर्गणेयिदं कार्म्मणशरीरमक्कुं। स्वरनामकर्म्मोदयदिदं भाषावर्गणेयिदं वचनमक्कुं। नोइंद्रियावरणक्षयोपशमोपेतमप्प संज्ञिजीवक्कंगोपांगनामोदयदिदं मनोवर्गणेयिदं द्रव्यमनमक्कुमेंबुदत्थं। ई यत्थंमं मुंदण सूत्रद्वयदिदं पेळ्दपं।

आहारवग्गणादो तिण्णि सरीराणि होंति उस्सासो।
णिस्सासो वि य तेजोवग्गणखंधा दु तेजंगं ॥६०७॥

आहारवर्गणायाखोणि शरीराणि भवंति उच्छ्वासो। निश्वासोपि च तेजोवर्गणास्कंधाः तैजसांगं ॥

औदारिकवैक्रियिकाहारकमेंबो मूरु शरीरंगळु उच्छ्वासनिश्वासंगळुमाहारवर्गणेयिदमप्पुवु। तेजोवर्गणास्कंधदिदं तैजसशरीरमक्कुं।

भासमणवग्गणादो कमेण भासा मणं तु कम्मादो।
अट्ठविहकम्मदव्वं होदित्ति जिणेहि णिद्दिट्ठं ॥६०८॥

भाषामनोवर्गणातः क्रमेण भाषामनस्तु कार्म्मणात्। अष्टविधकर्म्मद्रव्यं भवतीति जिनैर्न्निर्द्दिष्टं ॥

भाषावर्गणास्कंधगळिदं चतुर्विधभाषेयक्कुं। मनोवर्गणास्कंधगळिदं द्रव्यमनमक्कुं। कार्म्मणवर्गणास्कंधंगळिदं अष्टविधकर्म्मद्रव्यमक्कुमेंदितु जिनस्वामिगळिदं पेळल्पट्टुदु।

णिद्धत्तं लुक्खत्तं बंधस्स य कारणं तु एयादी।
संखेज्जाऽसंखेज्जाणंतविहा णिद्धलुक्खगुणा ॥६०९॥

स्निग्धत्वं रूक्षत्वं बंधस्य कारणं त्वेकादयः। संख्येयासंख्येयानंतविधाः स्निग्धरूक्षगुणाः॥

कार्मणनामकर्मोदयात् कार्मणवर्गणया कार्मणशरीरम्। स्वरनामकर्मोदयात् भाषावर्गणया वचनं, नोइन्द्रियावरणक्षयोपशमोपेतसंज्ञिनोऽङ्गोपाङ्गनामकर्मोदयात् मनोवर्गणया द्रव्यमनश्च भवतीत्यर्थः ॥६०६॥ अमुमेवार्थं सूत्रद्वयेनाह—

औदारिकवैक्रियिकाहारकनामानि त्रीणि शरीराणि उच्छ्वासनिश्वासौ च आहारवर्गणया भवन्ति। तेजोवर्गणास्कन्धैः तैजसशरीरं भवति ॥६०७॥

भाषावर्गणास्कन्धैश्चतुर्विधभाषा भवन्ति। मनोवर्गणास्कन्धैः द्रव्यमनः, कार्मणवर्गणास्कन्धैरष्टविधकर्मेति जिनैर्निर्दिष्टम् ॥६०८॥

तैजस वर्गणासे तैजस शरीर, कार्मण नामकर्मके उदयसे कार्मणवर्गणासे कार्मणशरीर, स्वरनामकर्मके उदयसे भाषावर्गणासे वचन और नोइन्द्रियावरणके क्षयोपशमसे युक्त संज्ञीके अंगोपांगनामकर्मके उदयसे मनोवर्गणासे द्रव्यमन बनता है ॥६०६॥

इसी अर्थको दो गाथाओंसे कहते हैं—

आहारवर्गणासे औदारिक, वैक्रियिक और आहारक ये तीन शरीर और उच्छ्वास-निश्वास होते हैं। तैजसवर्गणाके स्कन्धोंसे तैजसशरीर होता है ॥६०७॥

भाषावर्गणाके स्कन्धोंसे चार प्रकारकी भाषा होती है। मनोवर्गणाके स्कन्धोंसे द्रव्य-मन होता है और कार्मणवर्गणाके स्कन्धोंसे आठ प्रकारके कर्म होते हैं ऐसा जिनदेवने कहा है ॥६०८॥

एयगुणं तु जहण्णं णिद्धत्तं विगुणतिगुणसंखेज्जाऽ ।
संखेज्जाणंतगुणं होदि तहा रुक्खभावं च ॥६१०॥

एकगुणस्तु जघन्यं स्निग्धत्वं द्विगुणत्रिगुणसंख्येयासंख्येयानंतगुणो भवति तथा रूक्षभावश्च ॥

आ स्निग्धत्वगुणवलियोळु तु मत्ते एकगुणमप्प स्निग्धत्वं जघन्यमक्कुमवावियागि द्विगुण त्रिगुण संख्येयासंख्येयानंतगुणमक्कुमंते रूक्षत्वमुमरियल्पडुगुं ।

एवं गुणसंजुत्ता परमाणू आदिवग्गणम्हि ठिया ।
जोग्गदुगाणं बंधे दोण्हं बंधो हवे णियमा ॥६११॥

एवं गुणसंयुक्ताः परमाणवः आदिवर्गणायां स्थिताः । योग्यद्विकानां बंधे द्वयोर्बंधो भवेन्नियमात् ॥

ई पेळल्पट्ट स्निग्धरूक्षगुणसंयुक्तंगळप्प परमाणुगळु मोदल अणुवर्ग्गणेयोळिर्द्दतिरल्पट्टुवु । स्निग्धरूक्षत्वगुणनिमित्तमप्प योग्यद्विकंगळगे बंधमप्पेडेयोळा एरडक्कं बंधं नियमदिंदमक्कुं । बंधमविशेषदिंद प्रसक्तमादोडे अनिष्टगुणनिवृत्तिपूर्व्वकं विधियिसिदपरु ।

णिद्धणिद्धा ण बज्झंति रुक्खरुक्खा य पोग्गला ।
णिद्धलुक्खा य बज्झंति रूवारूवी य पोग्गला ॥६१२॥

स्निग्धस्निग्धा न बध्यंते रूक्षरूक्षाश्च पुद्गलाः । स्निग्धरूक्षाश्च बध्यंते रूप्यरूपिणश्च पुद्गलाः ॥

स्निग्धगुणपुद्गलंगळोडने स्निग्धगुणपुद्गलंगळु बंधमागल्पडवु । रूक्षगुणपुद्गलंगळोडने रूक्षगुणपुद्गलंगळुमंते बंधमागल्पडवु । इदुत्सर्गविधियक्कुमेकेंदोडे विशेषविधियं मुंदे पेळल्पडुवुदरिंदं स्निग्धगुणपुद्गलंगळोडने रूक्षगुणपुद्गलंगळु बंधमागल्पडुवुवंतप्प पुद्गलंगळु रूपि-

स्निग्धगुणावल्यां तु पुनः एकगुणं स्निग्धत्वं जघन्यं स्यात् । तदादिं कृत्वा द्विगुणत्रिगुणसंख्यातसंख्या-
नन्तगुणं भवति तथा रूक्षत्वमपि ॥६१०॥

एवं स्निग्धरूक्षगुणसंयुक्ताः परमाणवः अणुवर्गणायां तिष्ठति योग्यद्विकानां बन्धस्थाने तयोरेव द्वयोर्बन्धो नियमेन भवति ॥६११॥ स्निग्धरूक्षगुणनिमित्तं बन्धस्याविशेषेण प्रसक्तावनिष्टगुणनिवृत्तिपूर्वकं विधिं करोति—

स्निग्धगुणपुद्गलैः स्निग्धगुणपुद्गलाः न बध्यन्ते । तथा रूक्षगुणपुद्गलैः रूक्षगुणपुद्गला न बध्यन्ते अयमुत्सर्गविधिः । विशेषविधेर्वक्ष्यमाणत्वात् । स्निग्धगुणपुद्गलैः रूक्षगुणपुद्गलाः बध्यन्ते ते च पुद्ग

स्निग्ध गुणकी पंक्तिमें एक गुण स्निग्धताको जघन्य कहते हैं। उससे लेकर दो तीन गुण, संख्यात गुण, असंख्यात गुण और अनन्त गुण रूप स्निग्ध गुण होता है। प्रकार रूक्षगुण भी जानना ॥६१०॥

इस प्रकारके स्निग्ध और रूक्षगुणोंसे संयुक्त परमाणु अणुवर्गणामें विद्यमान हैं। से योग्य दो परमाणुओंके बन्धस्थानको प्राप्त होनेपर उन्हीं दोका बन्ध होता है ॥६११॥

स्निग्ध और रूक्ष गुणके निमित्तसे सर्वत्र बन्धका प्रसंग प्राप्त होनेपर अनिष्ट गुण बन्धका निषेध करते हुए बन्धका विधान करते हैं—स्निग्धगुण युक्त पुद्गलोंके साथ गुण युक्त पुद्गलोंका बन्ध नहीं होता। तथा रूक्ष गुण युक्त पुद्गलोंके साथ रूक्ष

दोत्तिगपभवदुउत्तरगदेसणंतरदुगाण बंधो दु ।
णिद्धे लुक्खे वि तहा वि जहण्णुभये वि सव्वत्थ ॥६१७॥

द्वित्रिप्रभवद्ध्युत्तरगतेष्वनंतरद्विकानां बंधस्तु । स्निग्धे रूक्षेपि तथा वि जघन्योभयस्मि सर्व्वत्र ॥

स्निग्धे स्निग्धवोळं रूक्षेपि रूक्षवोळं द्वित्रिप्रभवमु द्व्युत्तरमागि नडेयवरोळ् उपरि नंतरद्विकंगळगे स्निग्धद नाल्कवकं रूक्षद नाल्कवक्कं स्निग्धवेरडरोळं रूक्षवेरडरोळं बंधम स्निग्धदैदक्कं रूक्षदयिदक्कं स्निग्धद मूररोळं रूक्षद मूररोळं बंधमक्कु । मितागुत्तिरलु जघन्य युतदोळं बंधप्रसंगमादोडे जघन्यवर्ज्जितमप्पुभयदोळु स्निग्धरूक्षद्वयदोळु सर्वत्र बंधमरियल्प मेंबुदत्थं ।

णिद्धिदरवरगुणाणू सपरट्ठाणे वि णेदि बंधट्ठं ।
बहिरंतरंगहेदुहि गुणंतरं संगदे एदि ॥६१८॥

स्निग्धेतरावरगुणाणुः स्वपरस्थानेपि नैति बंधात्थं । बाह्याभ्यंतरहेतुभ्यां गुणांतरं एति ॥

स्निग्धजघन्यगुणाणुवु रूक्षजघन्यगुणाणुवुं स्वस्थानदोळं परस्थानदोळं बंधनिमित्त सल्लवु । बाह्याभ्यंतरहेतुगळिदं गुणांतरमं पोद्दि बंधक्के सल्गुं । तत्त्वात्थंदोळं "न जघन्यगुणा मेंदितु पेळल्पट्टुदु ।

स्निग्धे रूक्षेऽपि द्वित्रिप्रभवद्व्युत्तरक्रमेण गच्छन्ति तेषु उपरितनानन्तरद्विकानां स्निग्धचतु रूक्षचतुष्कस्य च स्निग्धद्वये रूक्षद्वये च बन्धः स्यात् । स्निग्धपञ्चकस्य रूक्षपञ्चकस्य च स्निग्धत्रये रू च बन्धः स्यात् । एवं जघन्यगुणयुतेऽपि बन्धप्रसक्तौ जघन्यवर्जिते उभयत्र स्निग्धरूक्षद्वये सर्वत्र बन्धो ज्ञा इत्यर्थः ॥६१७॥

स्निग्धजघन्यगुणाणुः रूक्षजघन्यगुणाणुश्च स्वस्थाने परस्थानेऽपि बन्धाय योग्यो न, बाह्याभ्यन्त भिर्गुणान्तरं प्राप्तस्तु योग्यः स्यात् । तत्त्वार्थेऽपि 'न जघन्यगुणानां' इत्युक्तत्वात् ॥६१८॥

इसीको अन्य प्रकारसे कहते हैं—

स्निग्ध और रूक्षमें भी दोको आदि लेकर तथा तीनको आदि लेकर दो-दो ब जाते हैं। उनमें ऊपरके अनन्तरवर्ती दोका बन्ध होता है। जैसे चार गुण स्निग्धवाले दो गुण स्निग्धवाले दो गुण रूक्षवालेके साथ तथा चार गुण रूक्षवालेका दो गुण रूक्षवाले दो गुण स्निग्धवालेके साथ बन्ध होता है। इसी तरह पाँच गुण स्निग्ध या पाँच गुण रूक्षवा का तीन गुण स्निग्ध या तीन गुण रूक्षवालेके साथ बन्ध होता है। इस प्रकार एक अंश जघन्य गुणवालोंका भी बन्ध प्राप्त होनेपर निषेध करते हैं कि जघन्यको छोड़कर स्नि और रूक्ष दोनोंमें सर्वत्र बन्ध जानना ॥६१७॥

जघन्य स्निग्ध गुणवाला या जघन्य रूक्ष गुणवाला परमाणु स्वस्थान और परस्थान भी बन्धके योग्य नहीं है।

जीवाजीवाः जीवंगळुमजीवंगळु तेषां अवर पुण्यपापद्वयं पुण्यमुं पापमुमेंबेरडुं आस्रवसंवरनिर्ज्जराबंधमोक्षाः आस्रवमुं संवरमुं निर्ज्जरयुं बंधमुं मोक्षमुमेंदितु नवपदार्त्थंगळप्पुवु। पदार्त्थंशब्दं सर्व्वत्र संबंधिसल्पडुगुं। जीवपदार्त्थः अजीवपदार्त्थः इत्यादि।

जीवदुगं उत्तत्थं जीवा पुण्णा हु सम्मगुण सहि दा।
वदसहिदा वि य पावा तव्विवरीया हवंतित्ति ॥६२२॥

जीवद्वयमुक्तार्त्थं जीवाः पुण्याः खलु सम्यक्त्वगुणसहिताः। व्रतसहिताः अपि च पापास्तद्विपरीता भवंतीति ॥

जीवपदार्त्थमुमजीवपदार्त्थमुं मुन्नं जीवसमासेयोळं षड्द्रव्याधिकारदोळं पेळल्पट्टुवल्लि सम्यक्त्वगुणयुक्तजीवंगळु व्रतयुक्तजीवंगळुं पुण्यजीवंगळप्पुवु। तद्विपरीतंगळु तद्द्वयरहितंगळुं पापजीवंगळेंदरियल्पडुवुवु खलु नियमदिदं। चतुर्द्दशगुणस्थानंगळोळु जीवसंख्येयं पेळुत्तं मिथ्यादृष्टिगळुं सासादनरुं पापजीवंगळेंदु पेळ्दपं :—

मिच्छाइट्ठी पावाणंताणंता य सासणगुणा वि।
पल्लासंखेज्जदिमा अणअण्णदरुदयमिच्छगुणा ॥६२३॥

मिथ्यादृष्टयः पापाः अनंतानंताश्च सासादनगुणा अपि। पल्यासंख्येयभागाः अनंतानुबंध्यन्यतरोदयमिथ्यागुणाः ॥

पापरूपरुगळप्प मिथ्यादृष्टिजीवंगळु किंचिदून संसारिराशिप्रमाणरप्परेके दोडे सासादनादितरगुणस्थानजीवसंख्येयिद होनरप्पुदरिदं। अदु कारणदिदमनंतानंतगळप्पुवु ॥ १३ ॥ सासादनगुण

जीवा अजीवाः तेषां पुण्यपापद्वयं आस्रवः संवरो निर्जरा बन्धो मोक्षश्चेति नवपदार्था भवन्ति। पदार्थशब्दः सर्वत्र सम्बन्धनीयः,-जीवपदार्थः अजीवपदार्थः इत्यादिः ॥६२१॥ जीवाजीवपदार्थौ द्वौ पूर्वं जीवसमासे षड्द्रव्याधिकारे चोक्तार्थौ। पुण्यजीवाः सम्यक्त्वगुणयुक्ता व्रतयुक्ताश्च स्युः। तद्विपरीतलक्षणाः पापजीवाः खलु-नियमेन ॥६२२॥ चतुर्दशगुणस्थानेषु जीवसंख्या मिथ्यादृष्टिसासादनौ च पापजीवाविति आह—

मिथ्यादृष्टयः पापाः—पापजीवाः। ते चानन्तानन्ता एव इतरगुणस्थानजीवसंख्योनसंसारिमात्रत्वात्

जीव, अजीव, उनके पुण्य और पाप दो तथा आस्रव, बन्ध, संवर, निर्जरा, और मोक्ष ये नौ पदार्थ होते हैं। पदार्थ शब्द प्रत्येकके साथ लगाना चाहिए। जैसे जीवपदार्थ, अजीवपदार्थ इत्यादि ॥६२१॥

पहले जीवसमासमें तथा छह द्रव्योंके अधिकारमें जीवपदार्थ और अजीवपदार्थका कथन कर दिया है। जो जीव सम्यक्त्वगुणसे युक्त हैं और व्रतोंसे युक्त हैं वे जीव पुण्यरूप होते हैं। उनसे विपरीत लक्षणवाले अर्थात् जो न सम्यक्त्वयुक्त हैं और न व्रतोंसे युक्त हैं वे नियमसे पापरूप हैं ॥६२२॥

आगे चौदह गुणस्थानोंमें जीवोंकी संख्या और मिथ्यादृष्टि तथा सासादन गुणस्थानवाले जीवोंको पापी कहते हैं—

मिथ्यादृष्टि जीव पापी हैं और वे अनन्तानन्त हैं; क्योंकि संसारी जीवोंकी राशिमेंसे शेष तेरह गुणस्थानवर्ती जीवोंकी संख्या घटानेपर मिथ्यादृष्टि जीवोंकी संख्या होती है।

तिरधियसयणवणउदी छण्णउदी अप्पमत्त बे कोडी ।
पंचेव य तेणउदी णवट्ठबिसयंच्छउत्तरं पमदे ॥६२५॥

त्रिभिरधिकशतं नवनवतिः षण्णवतिरप्रमत्ते द्विकोटी पंचैव च त्रिनवतिर्नवाष्टद्विशतं षडुत्तरं प्रमत्ते ॥

प्रमत्तरोळु संख्ये अय्दु कोटियुं तो भत्तमूरुलक्षेयुं तो भत्तेंटु सासिरद इन्नूरारुं ॥ ५९३९८२०६ ॥ अप्रमत्तरोळु संख्ये येरडुकोटियुं तो भत्ताऱु लक्षेयुं तो भत्तो भत्तु सासिरद नूरमूरप्पुवु ॥ २९६९९१०३ ॥

तिसयं भणंति केई चउरुत्तरमत्थपंचयं केई ।
उवसामगपरिमाणं खवगाणं जाण तद्दुगुणं ॥६२६॥

त्रिशतं भणंति केचित् चतुरुत्तरमस्तपंचकं केचित् । उपशमकपरिमाणं क्षपकाणां जानीहि तद्द्विगुणं ॥

केलंबराचार्य्यरुगळु उपशमकरप्रमाणमं त्रिशतमेंदु पेळ्वरु । मत्तं केलंबराचार्य्यरु चतुरुत्तरत्रिशतमेंदु पेळ्वरु । मत्तं केलंबराचार्य्यरुगळु अय्दु गुंदिद चतुरुत्तरत्रिशतमेंदु पेळ्व ॥ २९९ ॥ व ओंदु गुंदे मूनूरेंबुदत्थं । क्षपकर प्रमाणमं तद्विगुणमं नीनरियेंदु शिष्यसंबोधनमक्कुमी संख्येगळोळु प्रवाह्योपदेशमप्प संख्येयं निरंतराष्टसमयंगळोळु विभागिसि पेळ्वरः—

सोलसयं चउवीसं तीसं छत्तीस तह य बादालं ।
अडदालं चउवण्णं चउवण्णं होंति उवसमगे ॥६२७॥

षोडशकं चतुर्विंशतिः त्रिंशत् षट्त्रिंशत्तथा च द्विचत्वारिंशदष्टचत्वारिंशच्चतुःपंचाशच्चतुःपंचाशद्भवंत्युपशमके ॥

प्रमत्ते पञ्चकोट्यः त्रिनवतिलक्षाण्यष्टानवतिसहस्राणि द्विशतं षट् च भवन्ति । ५, ९३, ९८, २०६ । अप्रमत्ते द्विकोटिषण्णवतिलक्षनवनवतिसहस्रैकशतत्रयो भवन्ति । २, ९६, ९९, १०३ ॥६२५॥
केचिदुपशमकप्रमाणं त्रिशतं भणन्ति । केचिच्च चतुरुत्तरत्रिशतं भणन्ति । केचित् पुनः पञ्चोनचतुरुत्तरत्रिशतं भणन्ति । एकोनत्रिशतमित्यर्थः । क्षपकप्रमाणं ततो द्विगुणं जानीहि ॥६२६॥ अथ प्रवाह्योपदेशं निरन्तराष्टसमयेषु विभजति—

प्रमत्तगुणस्थानमें पाँच कोटि तिरानवे लाख, अट्ठानवे हजार दो सौ छह ५९३९८२०६ जीव हैं। तथा अप्रमत्तगुणस्थानमें दो कोटि छियानवे लाख, निन्यानवे हजार एक सौ तीन २९६९९१०३ जीव हैं ॥६२५॥

आठवें, नौवें, दसवें, ग्यारहवें गुणस्थानवर्ती उपशमश्रेणिवालोंका प्रमाण कोई आचार्य तीन सौ कहते हैं, कोई आचार्य तीन सौ चार कहते हैं और कोई आचार्य तीन सौ चार में से पाँच कम अर्थात् दो सौ निन्यानवे कहते हैं। तथा आठवें, नौवें, दसवें और बारहवें गुणस्थानवर्ती क्षपकश्रेणिवाले जीवोंका प्रमाण उपशमवालोंसे दूना जानना ॥६२६॥

आचार्य परम्परासे आगत प्रवाही उपदेश तीन सौ चारकी संख्याका निरन्तर आठ समयोंमें विभाग करते हैं—

सयोगिजिनरुगळसंख्ये लक्षाष्टकमुमष्टानवतिसहस्रंगळुं द्व्युत्तरपंचशतप्रमितमक्कु । ८९८५०२ । मिनिवरं सर्व्वदा वंदिसुवें । इल्लि निरंतर अष्टसमयंगळोळु संचिसल्पट्ट सयोगजिनरुगळाचार्य्यांतरापेक्षेयिवं सिद्धांतवाक्यदोळु "छसु सुद्धसमयेसु तिण्णि तिण्णि जीवा केवळमुप्पायंति । वोसु समयेसु वोद्दो जीवा केवळमुप्पाययंति एवमट्ठसमयसंचिदजीवा बावीसा हवंति" येंदितु पेळल्पट्टवारु समयंगळोळु मूरु मूरुमेरडु समयंगळोळ्यरडेरडागलु जिनरुगळुं मोक्षगामिगळुमर्प्पदिगळ मेळेंदु समयंगळोळेनिवरप्परेंबो विशेषकथनदोळु त्रैराशिकरूपट्कमक्कुमवें तें दोडे संदृष्टि :—

प्र के २२	फ का ८/६	इ के = ८९८५०२	लब्ध मिश्रकाल ८ लब्ध का ४०८४१।६
प्र का ८/६	फ स ८।	इ का ४०८४१।८/६	लब्ध समयाशुद्धा ३२६७२८
प्र स ८	फ के २२	इ स ३२६७२८ ॥	लब्ध केवलिन: लब्ध के ८९८५०२
प्र स ८	फ के ४४	इ स ३२६७२८ । २	लब्ध ८९८५०२
प्र स ८	फ के ८८	इ स ३२६७२८ २।२	लब्ध के ८९८५०२
प्र स ८	फ के १७६	इ स ३२६७२८ २।२।२	लब्ध के ८९८५०२

सयोगिजिनसंख्या अष्टलक्षाष्टनवतिसहस्रद्व्युत्तरपञ्चशतानि ८, ९ ८, ५०२ तान् सदा वन्दे। अत्र निरन्तराष्टसमयेषु संचितसयोगिजिनाः आचार्यान्तरापेक्षया सिद्धान्तवाक्ये—छसु सुद्धसमयेसु तिण्णि तिण्णि जीवा केवलमुप्पायन्ति, दोसु समयेसु दो दो जीवा केवलमुप्पाययन्ति एवमट्ठसमयसंचिदजीवा बावीसा हवन्ति

विशेषकथने त्रैराशिकषट्कम् । तद्यथा—प्र के २२ । फ का ८/६ । इ के ८, ९ ८, ५०२ । ल का ४०८४१, ।।

पुनः प्र का ८/६ । फ स ८ । इ का ४०८४१, ८/६ । ल स ३, २६, ७२८ । पुनः प्र स ८ । फ के २२ । ।।,

सयोगी जिनोंकी संख्या आठ लाख अट्ठानवे हजार पाँच सौ दो है उन्हें सदा नमस्कार करता हूँ। यहाँ निरन्तर आठ समयोंमें संचित सयोगि जिनोंकी संख्या अन्य आचार्योंकी अपेक्षा सिद्धान्तमें इस प्रकार कही है—छह शुद्ध समयोंमें तीन-तीन जीव केवलज्ञानको उत्पन्न करते हैं और दो समयोंमें दो-दो जीव केवलज्ञानको उत्पन्न करते हैं। इस प्रकार आठ समयोंमें संचित जीव बाईस होते हैं। यहाँ विशेष कथन छह त्रैराशिकोंके द्वारा करते हैं—

१. यदि बाईस केवली छह मास आठ समयमें होते हैं तो आठ लाख अट्ठानवे हजार पाँच सौ दो केवली कितने कालमें होंगे ऐसा त्रैराशिक करनेपर प्रमाणराशि २२ केवली, फलराशि छह मास आठ समयकाल, इच्छाराशि आठ लाख अट्ठानवे हजार पाँच सौ दो केवली। सो प्रमाणका भाग इच्छाराशिमें देनेसे चालीस हजार आठ सौ इकतालीस आये। इस संख्याको छह मास आठ समयसे गुणा करनेपर कालका प्रमाण आता है। २. छह मास

जेट्ठावरबहुमज्झिम ओगाहणगा दु चारि अट्ठेव ।
जुगवं हवंति खवगा उवसमगा अद्धमेदेसिं ॥६३२॥

ज्येष्ठावरबहुमध्यमावगाहनकाः द्विचतुरष्टैव। युगपद्भवंति क्षपकाः उपशमकाः अर्द्धमेतेषां॥

बोधितबुद्धरु क्षपकरेकसमयदोळु युगपन्नूरें दु उपशमकरु तवर्द्धमप्परु १०८/५४ पुंवेदिगळ् क्षपकरु नूरें दुपशमकरु तदर्द्धमप्परु । १०८/५४ स्वर्गदिदं बंद क्षपकरु युगपन्नूरें दुपशमकरु तदर्द्ध-

---

इ ३, २६, ७२८/२ । ल के ८, ९८, ५०२/२ । तथा प्र स ८ । फ के १७६ । इ ३, २६, ७२८/२।२।२ । ल के ८, ९८, ५०२ । इदमेकपक्षान्तरम् ॥६२९॥ अथैकसमये युगपत्संभवतीं क्षपकोपशमकविशेषसंख्यां गाथात्रयेणाह—

युगपदुत्कृष्टेन एकसमये बोधितबुद्धाः पुंवेदिनः स्वर्गच्युताश्च प्रत्येकं क्षपकाः अष्टोत्तरशतम् उपशम-

---

आठ लाख अट्ठानवे हजार पाँच सौ दो आता है। नीचे इन छह त्रैराशियोंको अंकित किया जाता है—

प्रमाणराशि	फलराशि	इच्छाराशि	लब्धराशि
केवली २२	काल छह मास ८ समय	केवली ८९८५०२	काल ४०८४१ × छह मास आठ समय
काल छह मास ८ समय	समय ८	काल ४०८४१ × छहमास आठ समय	समय ३२६७२८
समय ८	केवली २२	समय ३२६७२८	केवली ८९८५०२
समय ८	केवली ४४	समय ३२६७२८ का आधा	केवली ८९८५०२
समय ८	केवली ८८	समय ३२६७२८ का चौथाई	केवली ८९८५०२
समय ८	केवली १७६	समय ३२६७२८ का आठवाँ भाग	केवली ८९८५०२

आगे एक समयमें एक साथ होनेवाली क्षपकों और उपशमकोंकी विशेष संख्या तीन गाथाओंसे कहते हैं—

एक साथ उत्कृष्टसे एक समयमें बोधित बुद्ध क्षपक, पुरुषवेदी क्षपक, और स्वर्गसे च्युत होकर मनुष्य जन्म लेकर क्षपकश्रेणी चढ़नेवाले प्रत्येक एक सौ आठ, एक सौ आठ

८९९९९९९७ ळिवरोळ् प्रमत्तादिसयोगिकेवल्यवसानमाद गुणस्थानवर्तिगळ संख्येयनें दु कोटियुं तो भत्तो भत्तु लक्षमुं तो भत्तो भत्तु सासिरव मुन्नूरतो भत्तो भत्तं ८९९९९३९९ कळेयुत्तिरलु शेषम- योगिकेवलिगलसंख्ये येरडुगुंदिदरुनूरवतु ५९८ ॥ मितो पदि नाल्कुं गुणस्थानंगळोळु पेळ्द संख्येगे संदृष्टिरचनेयिदु :—

सि		अ
अ	०	५९८
स	०	८९८५०२
क्षी	०	५९८
उ	०	२९९।०
सू	०	२९९।५९८।।
अ	०	२९९।५९८।।
अ	०	२९९।५९८।।
अ	०	२९९९९१०३
प्र	०	५९३९८२०६
दे	०	प ३ ४ ० ॥ १३ को / ७
अ	०	प ७०० को / ७
मि	०	प १०४ को / ७
सा		प ५२ को / ७
मि		१३—

अनंतरं चतुर्गतिगळोळु मिथ्यादृष्टि सासादनमिश्रासंयतर संख्येयं साधिसुव पल्यद भाग- ५ हारविशेषंगळं पेळ्दपं :—

> ओघासंजदमिस्सयसासणसम्माण भागहारा जे ।
> रूऊणावलियासंखेज्जेणिह भजिय तत्थ णिक्खित्ते ॥६३४॥

ओघासंयतमिश्रकसासादनसम्यग्दृष्टीनां भागहारा ये । रूपोनावल्यसंख्यातेनेह विभज्य तत्र निक्षिप्ते ॥

१०
> देवाणं अवहारा होंति असंखेण ताणि अवहरिय ।
> तत्थेव य पक्खित्ते सोहम्मीसाण अवहारा ॥६३५॥

देवानामवहारा भवंति असंख्येन तानपहृत्य तत्रैव च निक्षिप्ते सौधर्मेशानावहाराः ॥

प्रमत्तादिसयोग्यवसानसंख्यायां ८९९९९३९९ अपनीतायां शेषं द्व्यूनपट्शतं अयोगिसंख्या भवति। ५९८ ॥६३३॥ अथ चतुर्गतिमिथ्यादृष्टिसासादनमिश्रासंयतसंख्यासाधकपल्यभागहारविशेषानाह—

१५ अंक दिखानेपर ८९९९९९९७ तीन कम नौ करोड़ संख्या प्रमाण सब संयमियोंको मैं हाथोंकी अंजलि मस्तकसे लगाकर मन, वचन, कायकी शुद्धिसे नमस्कार करता हूँ। यहाँ प्रमत्त गुण- स्थानसे लेकर सयोग केवली पर्यन्त संख्या ८९९९९३९९ है। इस संख्याको सब संयमियोंकी संख्यामें घटानेपर शेष दो कम छह सौ ५९८ अयोगियोंकी संख्या होती है ॥६३३॥

आगे चारों गतिके मिथ्यादृष्टि, सासादनसम्यग्दृष्टि, मिश्र और असंयतसम्यग्दृष्टियों- २० की संख्याके साधक पल्यके भागहार विशेषोंको कहते हैं—

स्थानावसानमाद गुणस्थानत्रयदोळु आवुदोंदु सासादनर हारमदं नोडलु मुंवल्लेतेडेयोळ् असंयत-मिश्रर हारंगळु संख्यातगुणितक्रमंगळु सासादनर हारंगळु संख्यातगुणंगळप्पुवु।

सप्तमपृथ्विय गुणस्थानत्रयपर्य्यंतमदो व्याप्तियं पेळ्दपं :—

सोहम्मसाणहारमसंखेण य संखरूवसंगुणिदे।
उवरि असंजदमिस्सयसासणसम्माण अवहारा ॥६३६॥

सौधर्म्मसासादनहारमसंख्येन च संख्यरूपसंगुणिते। उपर्य्यसंयतमिश्रसासादनसम्यग्दृष्टीनामवहाराः ॥

सौधर्म्मकल्पद्वयदसासादन सम्यग्दृष्टिगळ भागहारम $\frac{a\,a\,a\,a\,4}{a-1\,a-1}$ निदनसंख्यातदिदं च शब्ददिदं मत्तमसंख्यातदिदं संख्यातरूपुगळिदं गुणितं माडुत्तिरलु यथासंख्यमागि मेले सानत्कुमारद्वयदोळऽसंयतादि अधस्तनगुणस्थानत्रयद हारंगळप्पुवु। सानत्कुमारद्वयद असंयतहारंगळु $\frac{a\,a\,a\,a\,4\,a}{a-1\,a-1}$ मिश्रहारंगळु $\frac{a\,a\,a\,a\,4\,a\,a}{a-1\,a-1}$ सासादनर हारंगळु $\frac{a\,a\,a\,a\,4\,a\,a\,4}{a-1\,a-1}$

अनंतरमी गुणितक्रमदव्याप्तियं पेळ्दपं :—

मिश्रसासादनानां भागहारा भवन्ति

$\frac{a\,a\,a}{a-1,\,a-1}$ $\frac{a\,a\,a\,a}{a-1,\,a-1}$ $\frac{a\,a\,4\,a\,a}{a-1,\,a-1}$

ततसौधर्मद्वयसासादनभागहारे $\frac{a\,a\,a\,a\,4}{a-1-a-1}$ असंख्यातेन चशब्दात् पुनरसंख्यातेन संख्यातरूपेण गुणिते यथासंख्यमुपरिसानत्कुमारद्वये असंख्यातमिश्रसासादनहारा भवन्ति। $\frac{a\,a\,a\,a\,4\,a}{a-1\,a-1}$ $\frac{a\,a\,a\,a\,4\,a\,a}{a-1\,a-1}$ $\frac{a\,a\,a\,a\,4\,a\,a\,4}{a-1-a-1}$ ॥६३६॥ अथास्य गुणितक्रमस्य व्याप्तिमाह—

असंख्यात और एक बार संख्यातरूप भागहार कहा था। उसको एक कम आवलीके असंख्यातवें भागसे भाग देनेसे जो प्रमाण आवे उतना-उतना उनमें मिलानेपर देवगतिमें मिश्र तथा सासादनगुणस्थानवालोंका प्रमाण लानेके लिए भागहार होता है। देवगतिमें असंयत मिश्र और सासादनके लिए जो-जो भागहारका प्रमाण कहा उसे एक कम आवलीके असंख्यातवें भागसे भाग देनेपर जो प्रमाण आवे उतना-उतना उन-उन भागहारोंमें मिलानेसे सौधर्म ऐशान स्वर्गमें अविरत मिश्र और सासादनसम्बन्धी भागहार होता है ॥६३४-६३५॥

सौधर्म और ऐशानमें सासादनका जो भागहार है उससे असंख्यातगुणा भागहार सानत्कुमार, माहेन्द्र स्वर्गमें असंयतसम्बन्धी है। 'च' शब्दसे इस असंयतके भागहारसे असंख्यातगुणा मिश्रगुण सम्बन्धी भागहार है और उससे संख्यातगुणा सासादनसम्बन्धी भागहार है ॥६३६॥

आगे इस गुणितक्रमको व्याप्ति कहते हैं—

शातारकल्पद्वयासंयतहारमसंख्यातगुणमक्कु a a a a ४ a a ४ । ४ a / a – a१ – १ मदं नोडलु तन्मिश्रहारम संख्यातमक्कु a a a a ४ a a ४ । ४ a a / a – १a – १ मदं नोडलु तत्रत्यसासादनहारं संख्यातगुणमक्कु a a a a ४ a a ५ । ४ a a ४ / a – १a – १ मदं नोडलु ज्योतिष्कासंयतहारमसंख्यातगुणमक्कु a a a a ४ a a ४ । ५ a / a – १a – १ मदं नोडलु तन्मिश्रहारमसंख्यातगुणमक्कु a a a a ४ a a ४ । ५ a a / a – १a – १ मदं नोडलु तत्रत्य सासादनहारं संख्यातगुणमक्कु a a a a ४ a a ४ । ५ a a ४ / a – १a – १ मदं नोडलु व्यंतरासंयतहारमसंख्यातगुणमक्कु a a a a ४ a a ४ । ६ a / a – १a – १ मदं नोडलु तन्मिश्रहारमसंख्यातगुणमक्कु a a a a ४ a a ४ । ६ a a / a – १a – १ मदं नोडलु तत्रत्यसासादनहारं संख्यातगुणमक्कु aaa a४aa४।६aa४ / a–१a–१ मदं नोडलु भवनवासिकासंयतहारमसंख्यातगुणमक्कु a a a a ४ a a ४ । ७ / a – १a – १ मदं नोडलु तन्मिश्रहारमसंख्यातगुणमक्कु a a a a ४ a a ४ ७ a a / a – १a – १ मदं नोडलु तत्रत्यसासादनहारं संख्यातगुणमक्कु a a a a ४ a a ४ । ७ । a a ४ / a – १a – १ मदं नोडलु तिर्य्यंचासंयतहारमसंख्यातगुणमक्कु a a a a ४ a a ४ । ८ / a – १a – १ मदं नोडलु तन्मिश्रहारमसंख्यातगुणमक्कु a a a a ४ a a ४ । ८ a a / a – १a – १ मदं नोडलु तत्रत्यसासादनहारं संख्यातगुणमक्कु aaaa४aa४८।aa४ / a – १a – १ मदं नोडला तिर्य्यग्देशसंयतहारमसंख्यातगुणमक्कुं तिर्य्यग्देशसंयतर (हारं नोडलु) प्रथमपृथ्विनारका-

संयतहारः असंख्यातगुणः । ततो मिश्रहारः असंख्यातगुणः । ततः सासादनहारः संख्यातगुणः । तत सासादने- संयतहारः असंख्यातगुणः । ततः मिश्रहारः असंख्यातगुणः । ततः सासादनहारः संख्यातगुणः । ततः ज्योति- ष्कासंयतहारः असंख्यातगुणः । ततः मिश्रहारः असंख्यातगुणः । ततः सासादनहारः संख्यातगुणः । ततः व्यन्तरासंयतहारः असंख्यातगुणः । ततः मिश्रहारः असंख्यातगुणः । ततः सासादनहारः संख्यातगुणः । ततः भवनवास्यसंयतहारः असंख्यातगुणः । ततः मिश्रहारः असंख्यातगुणः । ततः सासादनहारः संख्यातगुणः । ततस्तिर्यगसंयतहारः असंख्यातगुणः । ततः मिश्रहारः असंख्यातगुणः । सासादनहारः संख्यातगुणः । ततस्ति-

असंख्यातगुणा है । उससे मिश्रका भागहार असंख्यातगुणा है । उससे सासादनका भागहार संख्यातगुणा है । उससे ज्योतिषीदेवोंमें असंयतका भागहार असंख्यातगुणा है । उससे मिश्रका भागहार असंख्यातगुणा है । उससे सासादनका भागहार संख्यातगुणा है । उससे व्यन्तरोंमें असंयतका भागहार असंख्यातगुणा है । उससे मिश्रका भागहार असंख्यातगुणा है । उससे सासादनका भागहार संख्यातगुणा है । उससे भवनवासियोंमें असंयतका भागहार असंख्यातगुणा है । उससे मिश्रका भागहार असंख्यातगुणा है । उससे सासादनका भागहार संख्यातगुणा है । उससे तिर्यंचोंमें असंयतका भागहार असंख्यातगुणा है । उससे मिश्रका भागहार असंख्यातगुणा है । उससे सासादनका भागहार संख्यातगुणा है । उससे तिर्यंचोंमें ही देशसंयतका भागहार असंख्यातगुणा है । जो तिर्यंचोंमें देशसंयतका भागहार

मक्कु a a a a ४ । १३ a a ४ / a – १a – १ मदं नोडलु षष्ठधराऽसंयतहारमसंख्यातगुणमक्कुं। a a a a ४ a a ४ । १४ a / a – १a – १ मदं नोडलु तन्मिश्रहारमसंख्यातगुणमक्कु a a a a ४ a a ४ । १४ a a / a – १a – १ मदं नोडलु तत्रत्यसासावनहारं संख्यातगुणमक्कुं a a a a ४ a a ४ । १४ । a a ४ / a – १a – १ मदं नोडलु सप्तमधराऽसंयतहारमसंख्यातगुणमक्कु a a a a ४ a a ४ । १५ a / a – १a – १ मदं नोडलु तन्मिश्रहारम-संख्यातगुणमक्कु a a a a ४ a a ४ । १५ । a a / a – १a – १ मदं नोडलु तत्रत्यसासावनहारं संख्यातगुण-मक्कु a a a a ४ a a ४ । १५ । a a ४ / a – १ a – १ मनंतरमानतादिगळोळु हारमं पेळ्दपं :—

चरमधरासाणहरा आणदसम्माण आरणप्पहुडिं ।
अंतिमगेवेज्जंतं सम्माणमसंखसंखगुणहारा ॥६३८॥

चरमधरासासादनहाराः आनतसम्यग्दृष्टिनामारणप्रभृत्यंतिमग्रैवेयकांतं सम्यग्दृष्टीनाम-संख्यसंख्यगुणहाराः ॥

तत्तो ताणुत्ताणं वामाणमणुद्दिसाण विजयादी ।
सम्माणं संखगुणो आणदमिस्से असंखगुणो ॥६३९॥

ततस्तेषामुक्तानां वामानामनुदिशानां विजयादिसम्यग्दृष्टीनां संख्यगुणः आनतमिश्रे-संख्यगुणः ॥

असंख्यातगुणः । ततः सासादनहारः संख्यातगुणः । ततः षष्ठधरासंयतहारः असंख्यातगुणः । ततः मिश्रहार असंख्यातगुणः । ततः सासादनहारः संख्यातगुणः । ततः सप्तमधरासंयतहारः असंख्यातगुणः । ततः मिश्रहार असंख्यातगुणः । ततः सासादनहारः संख्यातगुणः ॥६३७॥ अथानतादिषु गाथात्रयेणाह—

ततसप्तमपृथ्वीसासादनहारात् आनतद्वयासंयतहारः असंख्यातगुणः । ततः आरणद्वयाद्यन्तिमग्रैवेयकान्तपदासंयतानां दशहाराः संख्यातगुणक्रमाः स्युः । अत्र संख्यातस्य संदृष्टिः पञ्चाङ्कः ॥६३८॥

ततोऽन्तिमग्रैवेयकासंयतहारात् आनतद्वयादिनवुक्तैकादशपदमिथ्यादृष्टीनां एकादशहाराः संख्यातगुणक्रमाः । अत्र संख्यातस्य संदृष्टिः पञ्चाङ्कः । ततः तदन्तिमग्रैवेयकवामहारात् नवानुदिशविजयादिचतुर्विमा...

भागहार संख्यातगुणा है। उससे छठी पृथ्वीमें असंयतका भागहार असंख्यातगुणा है। उससे मिश्रका भागहार असंख्यातगुणा है। उससे सासादनका भागहार संख्यातगुणा है। उससे सातवें नरकमें असंयतका भागहार असंख्यातगुणा है। उससे मिश्रका भागहार असंख्यातगुणा है। उससे सासादनका भागहार संख्यातगुणा है ॥६३७॥

आगे आनतादिमें तीन गाथाओंसे कहते हैं—

सप्तम पृथ्वीसम्बन्धी सासादनके भागहारसे आनत-प्राणत सम्बन्धी असंयतका भागहार असंख्यातगुणा है। उससे आरण-अच्युतसे लेकर अन्तिम ग्रैवेयक पर्यन्त स्थानोंमें असंयतोंका भागहार क्रमसे संख्यातगुणा संख्यातगुणा है। यहाँ संख्यातकी संदृष्टि पाँचका अंक है ॥६३८॥

उस अन्तिम ग्रैवेयक सम्बन्धी असंयतोंके भागहारसे आनत-प्राणत युगलसे

मक्कु ə ə ə ə ४ । १३ ə ə ४ / ə – १ə – १ मदं नोडलुं षष्ठधराऽसंयतहारमसंख्यातगुणमक्कुं। ə ə ə ə ४ ə ə ४ । १४ ə / ə – १ə – १ मदं नोडलु तन्मिश्रहारमसंख्यातगुणमक्कु ə ə ə ə ४ ə ə ४ । १४ ə ə / ə – १ə – १ मदं नोडलु तत्रत्यसासादनहारं संख्यातगुणमक्कुं ə ə ə ə ४ ə ə ४ । १४ । ə ə ४ / ə – १ə – १ मदं नोडलु सप्तमधराऽसंयतहारमसंख्यातगुणमक्कु ə ə ə ə ४ ə ə ४ । १५ ə / ə – १ə – १ मदं नोडलु तन्मिश्रहारम-संख्यातगुणमक्कु ə ə ə ə ४ ə ə ४ । १५ । ə ə / ə – १ə – १ मदं नोडलु तत्रत्यसासादनहारं संख्यातगुण-मक्कु ə ə ə ə ४ əə ४ । १५ । ə ə ४ / ə – १ ə – १ मनंतरमानतादिगळोळु हारमं पेळ्दपं :—

चरमधरासाणहरा आणदसम्माण आरणप्पहुडिं ।
अंतिमगेवेज्जंतं सम्माणमसंखसंखगुणहारा ॥६३८॥

चरमधरासासादनहाराः आनतसम्यग्दृष्टिनामारणप्रभृत्यंतिमग्रैवेयकांतं सम्यग्दृष्टीनाम् संख्यसंख्यगुणहाराः ॥

तत्तो ताणुत्ताणं वामाणमणुद्दिसाण विजयादी ।
सम्माणं संखगुणो आणदमिस्से असंखगुणो ॥६३९॥

ततस्तेषामुक्तानां वामानामनुदिशानां विजयादिसम्यग्दृष्टीनां संख्यगुणः आनतमिश्रे संख्यगुणः ॥

असंख्यातगुणः । ततः सासादनहारः संख्यातगुणः । ततः षष्ठधरासंयतहारः असंख्यातगुणः । ततः मिश्रहारः असंख्यातगुणः । ततः सासादनहारः संख्यातगुणः । ततः सप्तमधरासंयतहारः असंख्यातगुणः । ततः मिश्रहारः असंख्यातगुणः । ततः सासादनहारः संख्यातगुणः ॥६३७॥ अथानतादिषु गाथात्रयेणाह—

तत्सप्तमपृथ्वीसासादनहारात् आनतद्वयासंयतहारः असंख्यातगुणः । ततः आरणद्वयादन्तिमग्रैवेयकान्तसंयतानां तद्धाराः संख्यातगुणक्रमाः स्युः । अत्र संख्यातस्य संदृष्टिः पञ्चाङ्कः ॥६३८॥

ततोऽन्तिमग्रैवेयकासंयतहारात् आनतद्वयादिचतुष्कैकादशचरमिथ्यादृष्टीनां एकादशहाराः संख्यातगुणक्रमाः । अत्र संख्यातस्य संदृष्टिः पञ्चाङ्कः । ततः तदन्तिमग्रैवेयकवामहारात् नवानुदिशविजयादिचतुर्विमा-

---

भागहार संख्यातगुना है। उससे छठी पृथ्वीमें असंयतका भागहार असंख्यातगुना है। उससे मिश्रका भागहार असंख्यातगुना है। उससे सासादनका भागहार संख्यातगुना है। उससे सातवें नरकमें असंयतका भागहार असंख्यातगुना है। उससे मिश्रका भागहार असंख्यातगुना है। उससे सासादनका भागहार संख्यातगुना है ॥६३७॥

आगे आनतादिमें तीन गाथाओंसे कहते हैं—

सप्तम पृथ्वीसम्बन्धी सासादनके भागहारसे आनत-प्राणत सम्बन्धी असंयत भागहार असंख्यातगुना है। उससे आरण-अच्युतसे लेकर अन्तिम ग्रैवेयक पर्यन्त स्थानोंमें असंयतोंका भागहार क्रमसे संख्यातगुना संख्यातगुना है। यहाँ संख्यातकी पाँचका अंक है ॥६३८॥

उस अन्तिम ग्रैवेयक सम्बन्धी असंयतोंके भागहारसे आनत-प्राणत

जीविदरे कम्मचये पुण्णं पावोत्ति होदि पुण्णं तु ।
सुहपयडीणं दव्वं पावं असुहाण दव्वं तु ॥६४३॥

जीवेतरस्मिन् कर्म्मचये पुण्यं पापमिति भवति पुण्यंतु । शुभप्रकृतीनां द्रव्यं पापमशुभानां द्रव्यं तु ॥

जीवपदार्त्थमं पेळ्वल्लि सामान्यदिदं गुणस्थानंगळोळु मिथ्यादृष्टिगुणस्थानवर्त्तिगळुं सासादनगुणस्थानवर्त्तिगळुं पापजीवंगळु । मिश्रगुणस्थानवर्त्तिगळु पुण्यपापमिश्रजीवंगळें दोडे सम्यक्त्वमिथ्यात्वमिश्रपरिणामिगळप्पुदरिंदमसंयतगुणस्थानवर्त्तिगळु पुण्यजीवंगळें दोडे सम्यक्त्वसंयुक्तजीवंगळप्पुदरिंदं देशसंयतगुणस्थानवर्त्तिगळुं सम्यक्त्वमुमेकदेशव्रतंगळोळु कूडि-दप्पुदरिंदं पुण्यजीवंगळप्परु । प्रमत्ताद्ययोगिकेवलिगुणस्थानवर्त्तिगळनितुं पुण्यजीवंगळें दितु पेळ्दनंतरमजीवपदार्त्थमं पेळ्वल्लि कर्म्मचयदोळु कार्म्मणस्कंधदोळु पुण्यमें दुं पापमें दुमजीवपदार्त्थ-मेरडु भेदमक्कुमल्लि पुण्यमें बुदावुदें दोडे मत्ते शुभप्रकृतिगळ द्रव्यमक्कुमा शुभप्रकृतिगळावुवें दोडे सद्वेद्यमुं शुभायुष्यंगळुं शुभनामकर्म्मप्रकृतिगळुमुच्चैर्ग्गोत्रमें बिवु शुभप्रकृतिगळें बुवक्कुं । पापमें बुदा-वुदें दोडे अशुभकर्म्मप्रकृतिगळ द्रव्यमक्कुमा अशुभप्रकृतिगळेंवुवावुवें देंदोडे अतोन्यत्पापमें बी सूत्राभिप्रायदिदमसद्वेद्यमुं नरकायुष्यमुं नीचैर्ग्गोत्रमुमशुभनामकर्म्मप्रकृतिगळुमें बिवशुभप्रकृति-गळें बुवक्कुं ।

आसवसंवरदव्वं समयपबद्धं तु णिज्जरादव्वं ।
तत्तो असंखगुणिदं उक्कस्सं होदि णियमेण ॥६४४॥

आस्रवसंवरद्रव्यं समयप्रबद्धस्तु निर्ज्जराद्रव्यं । ततोऽसंख्यगुणितमुत्कृष्टं भवति नियमेन ॥

जीवपदार्थप्रतिपादने सामान्येन गुणस्थानेषु मिथ्यादृष्टयः सासादनाश्च पापजीवाः । मिश्राः पुण्यपाप-मिश्रजीवाः सम्यक्त्वमिथ्यात्वमिश्रपरिणामपरिणतत्वात् । असंयताः सम्यक्त्वेन, देशसंयताः सम्यक्त्वेन देशव्रतेन च प्रमत्तादयः सम्यक्त्वेन व्रतेन च युतत्वात् पुण्यजीवा एव इत्युक्ताः । अनन्तरं अजीवपदार्थप्ररूपणे कर्मचये—कार्मणस्कन्धे पुण्यं पापमिति अजीवपदार्थो द्वेधा । तत्र शुभप्रकृतीनां सद्वेद्यशुभायुर्नामगोत्राणां द्रव्यं पुण्यं भवति । अशुभानां असद्वेद्यादिसर्वाप्रशस्तप्रकृतीनां द्रव्यं तु पुनः पापं भवति ॥६४३॥

जीवपदार्थ सम्बन्धी सामान्य कथनके अनुसार गुणस्थानोंमें मिथ्यादृष्टि और सासादन तो पापी जीव हैं। मिश्रगुणस्थानवाले पुण्यपापरूप मिश्र जीव हैं क्योंकि उनके सम्यक् मिथ्यात्वरूप मिश्र परिणाम होते हैं। असंयत सम्यक्त्वसे युक्त हैं, देशसंयत सम्यक्त्व और देशव्रतसे युक्त हैं इसलिए ये तो पुण्यात्मा जीव ही हैं और प्रमत्तादि तो पुण्यात्मा हैं ही। इसके अनन्तर अजीव पदार्थका प्ररूपण करते हैं—कार्मण-स्कन्ध पुण्यरूप भी होता है और पापरूप भी होता है इस प्रकार अजीव पदार्थके दो भेद हैं। उनमें सातावेदनीय, शुभ आयु, शुभनाम और उच्चगोत्र ये शुभ प्रकृतियाँ हैं इनका द्रव्य पुण्यरूप है। असातावेदनीय आदि सब अप्रशस्त प्रकृतियोंका द्रव्य पाप है ॥६४३॥

दर्शनमोहं क्षपिसल्पड्डुत्तिरलु तद्भववोळे सिद्धिसुगुं मेणु तृतीयचतुर्थभवंगळोळु कर्म्मक्षयमं माळ्कुं। नाल्कनेय भवमनतिक्रमिसुवुदल्ल शेषसम्यक्त्वगळंते किडुवुदुमल्लमदु कारणदिदं नित्यमेंदु पेळल्पट्टुदु साद्यक्षयानंतमें बुदर्थमनंतरमीयर्थमने पेळ्दपं :—

वयणेहि वि हेदूहि वि इंदियभयआणएहि रूवेहिं।
वीभच्छजुगुंछाहि य तेलोक्केण वि ण चालेज्जो ॥६४७॥

वचनैरपि हेतुभिरपींद्रियभयानकैः रूपैः। वीभत्सजुगुप्साभिश्च त्रैलोक्येनापि न चालनीयं॥

कुत्सितोक्तिगळिंदमुं कुहेतुदृष्टांतंगळिंदमुं इंद्रियंगळ्गे भयंकरंगळिदमुं विकृतवेषंगळिंदमुं वीभत्संगळत्तणिदप्प जुगुप्सिगळिंदमुं किं बहुना त्रैलोक्येनापि मूरुं लोकदिदमुं क्षायिकसम्यक्त्वं चलिसल्पडदु। अंतप्प क्षायिकसम्यग्दर्शनमार्ग्गक्कुमें बोडे पेळ्दपरु :—

दंसणमोहक्खवणापट्ठवगो कम्मभूमिजादो हु।
मणुसो केवलिमूले णिट्ठवगो होदि सव्वत्थ ॥६४८॥

दर्शनमोहक्षपणाप्रस्थापकः कर्म्मभूमिजातस्तु मनुष्यः केवलिमूले निष्ठापको भवति सर्वत्र॥

दर्शनमोहक्षपणाप्रारंभकं मत्तें कर्म्मभूमिजनक्कुमिल्लियुं मनुष्यनेयक्कुमावोडं केवलिश्रीपादमूलदोळु दर्शनमोहक्षपणाप्रारंभमं माळ्कुं। चतुर्गतिगळोळेल्लियावोडं निष्ठापिसुगु।

अनंतरं वेदकसम्यक्त्वस्वरूपमं पेळ्दपं—

दर्शनमोहे क्षपिते सति तस्मिन्नेव भवे वा तृतीयभवे वा चतुर्थभवे कर्मक्षयं करोति चतुर्थभवं नातिक्रमति। शेषसम्यक्त्ववन्न विनश्यति। तेन नित्यमित्युक्तं। साद्यक्षयानन्तमित्यर्थः। अमुमेवार्थमाह—

कुत्सितोक्तिभिः—कुहेतुदृष्टान्तैः इन्द्रियभयोत्पादकविकृतवेषैः वीभत्सवस्तूत्पन्नजुगुप्साभिः किं बहुना त्रैलोक्येनापि क्षायिकसम्यक्त्वं न चालयितुं शक्यम् ॥६४७॥ तत्सम्यग्दर्शनं कस्य भवेत् ? इति चेदाह—

दर्शनमोहक्षपणाप्रारम्भकः कर्मभूमिज एव सोऽपि मनुष्य एव तथापि केवलिश्रीपादमूले एव भवति। निष्ठापकस्तु सर्वत्र चतुर्गतिषु भवति ॥६४८॥ अथ वेदकसम्यक्त्वस्वरूपमाह—

निर्जराका कारण होता है। कहा है—दर्शन मोहका क्षय होनेपर उसी भवमें या तीसरे अथवा चौथे भवमें कर्मोंका क्षय करके मुक्ति प्राप्त करता है। चतुर्थ भवका अतिक्रमण नहीं करता। और न अन्य सम्यक्त्वोंकी तरह नष्ट ही होता है। इसीसे इसे नित्य कहा है। अर्थात् यह सादि अक्षयानन्त होता है ॥६४६॥

इसी भावको कहते हैं—

कुत्सित वचनोंसे, मिथ्याहेतु और दृष्टान्तोंसे, इन्द्रियोंको भय उत्पन्न करनेवाले भयंकर रूपोंसे, घिनावनी वस्तुओंसे उत्पन्न हुई ग्लानिसे, बहुत कहनेसे क्या, तीनों लोकोंके द्वारा भी क्षायिक सम्यक्त्वको विचलित नहीं किया जा सकता ॥६४७॥

यह क्षायिक सम्यग्दर्शन किसके होता है यह कहते हैं—

दर्शनमोहको क्षपणाका प्रारम्भ कर्मभूमिमें उत्पन्न हुआ मनुष्य ही केवलीके पादमूलमें ही करता है। किन्तु निष्ठापक चारों गतियोंमें होता है ॥६४८॥

आगे वेदक सम्यक्त्वका स्वरूप कहते हैं—

१. म °मक्कु।

साधारणंगळप्पुवु। करणलब्धि भव्यनोळेयप्पुदर्दु सम्यक्त्वग्रहणदोळं चारित्रग्रहणदोळमक्कुं।

अनंतरमुपशमसम्यक्त्वमं कैकोळ्व जीवनं पेळ्दपरु :—

चदुगदि भव्वो सण्णी पज्जत्तो सुज्झगो य सागारो।
जागारो सल्लेस्सो सलद्धिगो सम्ममुवगमई ॥६५२॥

चतुर्गतिभव्यः संज्ञिपर्याप्तः शुद्धश्च साकारः। सल्लेश्यो जागरितः सलब्धिकः सम्यक्त्वमुपगच्छति ॥

चतुर्गतिय भव्यनुं संज्ञियुं पर्य्याप्तकनुं विशुद्धनुं भेदग्रहणमाकारमें बुदरिंदं कूडिदनुमप्पुदरिंदं साकारनुं स्त्यानगृद्ध्यादिनिद्रात्रयरहितनुं भावशुभलेश्यात्रयदोळन्यतमलेश्यायुतनुं करणलब्धिपरिणतनुमितप्प जीवं यथासंभवमप्प सम्यक्त्वमं पोर्द्दुगुं।

चत्तारि वि खेत्ताइं आउगबंधेण होइ सम्मत्तं।
अणुवदमहव्वदाइं ण लहइ देवाउगं मोत्तुं ॥६५३॥

चतुर्णां क्षेत्राणामायुर्बंधेन भवति सम्यक्त्वं। अणुव्रतमहाव्रतानि न लभते देवायुष्कं मुक्त्वा ॥

नारकायुष्यमुमं तिर्य्यगायुष्यमुमं मनुष्यायुष्यमुमं देवायुष्यमुमं परभवायुष्यंगळं कट्टिद बद्धायुष्यरुगळप्प जीवंगळु सम्यक्त्वमं स्वीकरिसुवरल्लि दोषमिल्लमणुव्रतमहाव्रतंगळं पडेयल् नेरेयरल्लि, देवायुर्बंधमाद जीवंगळु अणुव्रतमहाव्रतंगळं स्वीकरिसुवरु।

चतस्रोऽपि साधारणाः भव्याभव्ययोः संभवात्। करणलब्धिस्तु भव्य एव स्यात् तथापि सम्यक्त्वग्रहणे चारित्रग्रहणे च ॥६५१॥ अथोपशमसम्यक्त्वग्रहणयोग्यजीवमाह—

यः चतुर्गतिभव्यः संज्ञी पर्याप्तकः विशुद्धः आकारेण भेदग्रहणेन सहितः स्त्यानगृद्ध्यादिनिद्रात्रयरहितः भावशुभलेश्यात्रये अन्यतमलेश्यः करणलब्धिपरिणतः स जीवो यथासंभवं सम्यक्त्वमुपगच्छति ॥६५२॥

चतुर्णां परभवायुषां एकतमबन्धेन जातबद्धायुष्कस्य सम्यक्त्वं भवत्यत्र दोषो नास्ति। अणुव्रतमहाव्रतानि तु एकं बद्धदेवायुष्कं मुक्त्वा नान्ये लभन्ते ॥६५३॥

हैं भव्य और अभव्य दोनोंके होती हैं। किन्तु अधःकरण, अपूर्वकरण, अनिवृत्तिकरण परिणाम रूप करणलब्धि भव्यके ही होती है। वह भी सम्यक्त्व और चारित्र ग्रहणके समय होती है ॥६५१॥

उपशमसम्यक्त्वको ग्रहण करनेके योग्य जीवको कहते हैं—

जो चारों गतियोंमें-से किसी भी गतिमें वर्तमान है किन्तु भव्य, पर्याप्तक, विशुद्ध साकार उपयोगवाला, स्त्यानगृद्धि आदि तीन निद्राओंसे रहित अर्थात् तीन शुभ भाव लेश्याओंमें-से किसी एक लेश्याका धारक और करणलब्धि रूप परिणत होता है वह जीव यथासम्भव सम्यक्त्वको प्राप्त करता है ॥६५२॥

परभव सम्बन्धी चारों आयुओंमें-से किसी भी एक आयुका बन्ध कर लेनेपर जो जीव बद्धायु हो गया है उसके सम्यक्त्व उत्पन्न होनेमें कोई दोष नहीं है। किन्तु अणुव्रत और महाव्रत एक बद्धदेवायु—जिसने परभव सम्बन्धी देवायुका बन्ध किया है—को छोड़कर अन्य आयुका बन्ध कर लेनेवाले बद्धायुष्कके नहीं होते ॥६५३॥

अनंतरं सम्यक्त्वमार्गणेयोळु जीवसंख्येयं गाथात्रर्याददं पेळ्वपं—

वासपुधत्ते खयिया संखेज्जा जइ हवंति सोहम्मे ।
तो संखपल्लठिदिए केवडिया एवमणुपादे ॥६५७॥

वर्षपृथक्त्वे क्षायिकाः संख्येया भवंति सौधर्म्मे । तर्हि संख्यपल्यस्थितिके कियन्त एवमनुपाते ॥

वर्षपृथक्त्वदोळु क्षायिकसम्यग्दृष्टिगळु संख्यातप्रमितरु सौधर्म्मकल्पद्वयदोळु पुट्टुवरंतादोडे संख्यातपल्यस्थितिकनोळु एनितरु क्षायिकसम्यग्दृष्टिगळप्परॆंदितनुपातत्रैराशिकमं माडुतिरलु प्रवर्ष ७ फ । क्षा = ७ । इ । प ७ । बंद लब्धमेनितक्कुमॆंदोडे :—
८

संखावलिहिदपल्ला खइया तत्तो य वेदगुवसमया ।
आवलि असंखगुणिदा असंखगुणहीणया कमसो ॥६५८॥

संख्यातावलिहृतपल्याः क्षायिकाः ततश्च वेदकोपशमकाः । आवल्यसंख्यगुणिताः असंख्यगुणहीनकाः क्रमशः ॥

संख्यातावलिगळिदं भागिसल्पट्ट पल्यप्रमितरु क्षायिकसम्यग्दृष्टिगळप्परु प मा क्षायिक-
२७
सम्यग्दृष्टिगळं नोडलु वेदकसम्यग्दृष्टिगळुमुपशमसम्यग्दृष्टिगळुं क्रमदिंदमावल्यसंख्यातगुणितप्रमाणरुमसंख्यातगुणहीनरुमप्परु वे प ० उ = प
२ १ ० २ १ ०

यदि वर्षपृथक्त्वे क्षायिकसम्यग्दृष्टयः संख्याताः सौधर्मद्वये उत्पद्यन्ते तर्हि संख्यातपल्यस्थितिके कति इत्यनुपाते त्रैराशिके कृते प्रवर्ष ७ फ क्षा = १ । इ प १ लब्धाः ॥६५७॥
८

संख्यातावलिभक्तपल्यमात्रकाः क्षायिकसम्यग्दृष्टयो भवन्ति प । तेभ्यः वेदकोपशमसम्यग्दृष्टयः क्रमेण
२ १
आवल्यसंख्यातगुणितासंख्यातगुणहीना भवन्ति । वे = प ० उ = प ॥६५८॥
२ १ २ १ । ०

सम्यक्त्वमार्गणामें जीवोंकी संख्या तीन गाथाओंसे कहते हैं—

यदि वर्षपृथक्त्व कालमें सौधर्मयुगलमें क्षायिक सम्यग्दृष्टि संख्यात उत्पन्न होते हैं तो संख्यात पल्यकी स्थितिमें कितने उत्पन्न होते हैं ऐसा त्रैराशिक करनेपर प्रमाणराशि वर्षपृथक्त्व, फलराशि संख्यात जीव और इच्छाराशि संख्यात पल्य । सो फलराशिसे इच्छाराशिको गुणा करके उसमें प्रमाणराशिसे भाग देनेपर जो लब्ध आया वह कहते हैं ॥६५७॥

संख्यातआवलीसे भाजित पल्यप्रमाण क्षायिकसम्यग्दृष्टि होते हैं । क्षायिकसम्यग्दृष्टियोंकी संख्याको आवलीके असंख्यातवें भागसे गुणा करनेपर वेदकसम्यग्दृष्टियोंकी संख्या होती है । तथा क्षायिकसम्यग्दृष्टियोंसे असंख्यातगुणे हीन उपशमसम्यग्दृष्टि होते हैं ॥६५८॥

भागमात्रमक्कुं स १२ ९ आस्रवपदार्थं समयप्रबद्धप्रमाणमक्कुं स ॰ संवरद्रव्यमुं समयप्रबद्ध प्रमितमक्कुं। स ॰। निर्ज्जराद्रव्यमितु स ॰ १२ । ६४ प । ८९ बंधद्रव्यं समयप्रबद्धमक्कुं। स ॰ मोक्षद्रव्यं द्व्यर्द्धगुणहानिप्रमितमक्कुं स ॰ १२-। संदृष्टिः—

सामान्यजीव १६ | अजी=सा ३ ≡ १६ स | बंध स ॰

५ पुण्यजीव ॰ प ॰ ॰ ४ / ९ ९ ९ ४ | पु स ॰ १२ । १ | मोक्ष सं ॰ १२

पापजीव १३= | पाप ॰ १२-९ | आस्र स ॰ | संव स ॰ | निर्ज्ज स ॰ १२=६४ प । ८९ ।

अजीवपापं द्व्यर्धगुणहानिसंख्यातबहुभागः स ॰ १२- ९ आस्रवपदार्थः समयप्रबद्धः स ॰। संवरद्रव्यं समयप्रबद्धः स ॰। निर्जराद्रव्यमेतावत्— स ॰ १२-। ६४ / ऊ प ८९ बन्धद्रव्यं समयप्रबद्धः स ॰। मोक्षद्रव्यं किंचिदूनद्व्यर्धगुणहानिः स ॰ १२- ॥६५१॥

१० समय प्रबद्धोंमें-से संख्यातवें भाग अजीवपुण्यका परिमाण है। संसारी राशिमें-से मिश्रकी अपेक्षा कुछ अधिक पुण्यजीवोंके प्रमाणको घटानेसे पापजीवोंका प्रमाण होता है। डेढ़ गुणहानिप्रमाण समयप्रबद्धोंमेंसे संख्यात बहुभाग अजीवपापका परिमाण है। आस्रव पदार्थ समयप्रबद्ध प्रमाण है। संवर द्रव्य समयप्रबद्ध प्रमाण है। निर्जराद्रव्य गुणश्रेणि निर्जराके उत्कृष्ट द्रव्यप्रमाण है। बन्धद्रव्य समयप्रबद्धप्रमाण है। मोक्षद्रव्य कुछ कम डेढ़ गुणहानि-प्रमाण है ॥६५१॥

विग्गहगदिमावण्णा केवलिणो समुग्घदो अजोगी य ।
सिद्धा य अणाहारा सेसा आहारया जीवा ॥६६६॥

विग्रहगतिमापन्नाः केवलिनः समुद्घातवंतोऽयोगी च सिद्धाश्चानाहाराः शेषा आहारका जीवाः ॥

विग्रहगतियं पोर्द्दिद जीवंगळु प्रतरलोकपूरणसमुद्घातसयोगकेवलिगळुमयोगकेवलिगळुं सिद्धपरमेष्ठिगळुमनाहारकमप्परु । शेषजीवंगळेनितोळवनितुमाहारकरेयप्परु । समुद्घातमेनितेंदोडे पेळ्दपरु ।

वेयणकसायवेगुव्वियो य मरणंतियो समुग्घादो ।
तेजाहारो छट्ठो सत्तमओ केवलीणं तु ॥६६७॥

वेदनाकषायवैगुर्व्विकाश्च मारणांतिकः समुद्घातश्च । तेजः आहारः षष्ठः सप्तमः केवलिनां तु ॥

वेदनासमुद्घातमें दुं कषायसमुद्घातमें दुं वैगूर्व्विकसमुद्घातमें दुं मारणांतिकसमुद्घातमें दुं तैजससमुद्घातमें दुमाहारकसमुद्घातमें दु केवलिसमुद्घातमें दु'मितु सप्तसमुद्घातंगळप्पुवु ।

अनंतरं समुद्घातमें बुदेनें दोडे पेळ्वपं :—

मूलसरीरमछंडिय उत्तरदेहस्स जीवपिंडस्स ।
णिग्गमणं देहादो होदि समुग्घादणामं तु ॥६६८॥

मूलशरीरमत्यक्त्वा उत्तरदेहस्य जीवपिंडस्य । निर्गमनं देहाद् भवति समुद्घातनाम तु ॥

मूलशरीरमं बिडदे कार्म्मणतैजसोत्तरदेहवजीवप्रदेशप्रचयक्के शरीरदिं पोरगल्लो निर्गमनं समुद्घातमें बुदक्कुं

विग्रहगत्याश्रितचतुर्गतिजीवाः प्रतरलोकपूरणसमुद्घातपरिणतसयोगिजिनाः अयोगिजिनाः सिद्धाश्च अनाहारा भवन्ति । शेषजीवाः सर्वेऽपि आहारका एव भवन्ति ॥६६६॥ समुद्घातः कतिधा ? इति चेदाह—

समुद्घातः वेदनाकषायवैगूर्विकमारणान्तिकतैजसाहारककेवलिसमुद्घातभेदात् सप्तधा भवति ॥६६७॥ स च किंरूपः ? इति चेदाह—

मूलशरीरमत्यक्त्वा कार्मणतैजसरूपोत्तरदेहयुक्तस्य जीवप्रदेशप्रचयस्य शरीराद्बहिर्निर्गमनं स समुद्घातो नाम भवति ॥६६८॥

विग्रहगतिमें आये चारों गतियोंके जीव, प्रतर और लोकपूरण समुद्घात करनेवाले सयोगी जिन, और सिद्ध अनाहारक हैं। शेष सब जीव आहारक हैं ॥६६६॥

समुद्घातके भेद कहते हैं—

वेदना, कषाय, विक्रिया, मारणान्तिक, तैजस, आहार और केवली समुद्घातके भेदसे समुद्घात सात प्रकारका होता है ॥६६७॥

समुद्घातका स्वरूप कहते हैं—

मूल शरीरको छोड़कर कार्मण और तैजस रूप उत्तर शरीरसे युक्त जीवके प्रदेश समूहका शरीरसे बाहर निकलना समुद्घात है ॥६६८॥

१. ब कर्त पं ।

विग्गहगदिमावण्णा केवलिणो समुग्घदो अजोगी य ।
सिद्धा य अणाहारा सेसा आहारया जीवा ॥६६६॥

विग्रहगतिमापन्नाः केवलिनः समुद्घातवंतोऽयोगी च सिद्धाश्चानाहाराः शेषा आहारका जीवाः ॥

विग्रहगतियं पोर्द्दिद जीवंगळु प्रतरलोकपूरणसमुद्घातसयोगकेवलिगळुमयोगकेवलिगळुं सिद्धपरमेष्ठिगळुंमनाहारकमप्परु । शेषजीवंगळेनितोळवनितुमाहारकरेयप्परु । समुद्घातमेनितें दोडे पेळ्दपरु ।

वेयणकसायवेगुव्वियो य मरणंतियो समुग्घादो ।
तेजाहारो छट्ठो सत्तमओ केवलीणं तु ॥६६७॥

वेदनाकषायवैगुर्व्विकाश्च मारणांतिकः समुद्घातश्च । तेजः आहारः षष्ठः सप्तमः केवलिनां तु ॥

वेदनासमुद्घातमें दुं कषायसमुद्घातमें दुं वैगूर्व्विकसमुद्घातमें दुं मारणांतिकसमुद्घातमें दुं तैजससमुद्घातमें दुमाहारकसमुद्घातमें दु केवलिसमुद्घातमें दु मितु सप्तसमुद्घातंगळप्पुवु ।

अनंतरं समुद्घातमें बुदेनें दोडे पेळ्दपं :—

मूलसरीरमछंडिय उत्तरदेहस्स जीवपिंडस्स ।
णिग्गमणं देहादो होदि समुग्घादणामं तु ॥६६८॥

मूलशरीरमत्यक्त्वा उत्तरदेहस्य जीवपिंडस्य । निर्ग्गमनं देहाद् भवति समुद्घातनाम तु ॥

मूलशरीरमं बिडदे कार्म्मणतैजसोत्तरदेहवज्जीवप्रदेशप्रचयक्के शरीरदिं पोरगल्दो निर्ग्गमनं समुद्घातमें बुदक्कुं

विग्रहगत्याश्रितचतुर्गतिजीवाः प्रतरलोकपूरणसमुद्घातपरिणतसयोगिजिनाः अयोगिजिनाः सिद्धाश्च अनाहारा भवन्ति । शेषजीवाः सर्वेऽपि आहारका एव भवन्ति ॥६६६॥ समुद्घातः कतिधा ? इति चेदाह—

समुद्घातः वेदनाकषायवैगूर्विकमारणान्तिकतैजसाहारककेवलिसमुद्घातभेदात् सप्तधा भवति ॥६६७॥ स च किंरूपः ? इति चेदाह—

मूलशरीरमत्यक्त्वा कार्मणतैजसरूपोत्तरदेहयुक्तस्य जीवप्रदेशप्रचयस्य शरीराद्बहिर्निर्गमनं स समुद्घातो नाम भवति ॥६६८॥

विग्रहगतिमें आये चारों गतियोंके जीव, प्रतर और लोकपूरण समुद्घात करनेवाले सयोगी जिन, और सिद्ध अनाहारक हैं। शेष सब जीव आहारक हैं ॥६६६॥

समुद्घातके भेद कहते हैं—

वेदना, कषाय, विक्रिया, मारणान्तिक, तैजस, आहार और केवली समुद्घातके भेदसे समुद्घात सात प्रकारका होता है ॥६६७॥

समुद्घातका स्वरूप कहते हैं—

मूल शरीरको छोड़कर कार्मण और तैजस रूप उत्तर शरीरसे युक्त जीवके प्रदेश समूहका शरीरसे बाहर निकलना समुद्घात है ॥६६८॥

---

१. म बदि पें ।

विग्गहगदिमावण्णा केवलिणो समुग्घदो अजोगी य ।
सिद्धा य अणाहारा सेसा आहारया जीवा ॥६६६॥

विग्रहगतिमापन्नाः केवलिनः समुद्घातवंतोऽयोगो च सिद्धाश्चानाहाराः शेषा आहारका जीवाः ॥

विग्रहगतियं पोद्दिद जीवंगळु प्रतरलोकपूरणसमुद्घातसयोगकेवलिगळुमयोगकेवलिगळुं सिद्धपरमेष्ठिगळुमनाहारकरप्पर । शेषजीवंगळेनितोळवनितुमाहारकरेयप्पर । समुद्घातमेनितें दोडे पेळ्दपद ।

वेयणकसायवेगुव्वियो य मरणंतियो समुग्घादो ।
तेजाहारो छट्ठो सत्तमओ केवलीणं तु ॥६६७॥

वेदनाकषायवैगुर्व्विकाश्च मारणांतिकः समुद्घातश्च । तेजः आहारः षष्ठः सप्तमः केवलिनां तु ॥

वेदनासमुद्घातमें दुं कषायसमुद्घातमें दुं वैगूर्व्यिकसमुद्घातमें दुं मारणांतिकसमुद्घातमें दुं तैजससमुद्घातमें दुमाहारकसमुद्घातमें दु केवलिसमुद्घातमें दु मितु सप्तसमुद्घातंगळप्पुवु ।

अनंतरं समुद्घातमें बुदेनें दोडे पेळ्वपं :—

मूलसरीरमछंडिय उत्तरदेहस्स जीवपिंडस्स ।
णिग्गमणं देहादो होदि समुग्घादणामं तु ॥६६८॥

मूलशरीरमत्यक्त्वा उत्तरदेहस्य जीवपिंडस्य । निर्गमनं देहाद् भवति समुद्घातनाम तु ॥

मूलशरीरमं बिडदे कार्म्मणतैजसोत्तरदेहदजीवप्रदेशप्रचयक्के शरीरदिं पोरगल्लो निर्गमनं समुद्घातमें बुदक्कुं

विग्रहगत्याश्रितचतुर्गतिजीवाः प्रतरलोकपूरणसमुद्घातपरिणतसयोगिजिनाः अयोगिजिनाः सिद्धाश्च अनाहारा भवन्ति । शेषजीवाः सर्वेऽपि आहारका एव भवन्ति ॥६६६॥ समुद्घातः कतिधा ? इति चेदाह— समुद्घातः वेदनाकषायवैगूर्विकमारणान्तिकतैजसाहारककेवलिसमुद्घातभेदात् सप्तधा भवति ॥६६७॥ स च किंरूपः ? इति चेदाह—

मूलशरीरमत्यक्त्वा कार्मणतैजसरूपोत्तरदेहयुक्तस्य जीवप्रदेशप्रचयस्य शरीराद्बहिर्निर्गमनं समुद्घातो नाम भवति ॥६६८॥

विग्रहगतिमें आये चारों गतियोंके जीव, प्रतर और लोकपूरण समुद्घात करनेवाले सयोगी जिन, और सिद्ध अनाहारक हैं। शेष सब जीव आहारक हैं ॥६६६॥

समुद्घातके भेद कहते हैं—

वेदना, कषाय, विक्रिया, मारणान्तिक, तैजस, आहार और केवली समुद्घातके भेदसे समुद्घात सात प्रकारका होता है ॥६६७॥

समुद्घातका स्वरूप कहते हैं—

मूल शरीरको छोड़कर कार्मण और तैजस रूप उत्तर शरीरसे युक्त जीवके प्रदेश समूहका शरीरसे बाहर निकलना समुद्घात है ॥६६८॥

---

१. ब बर्ति पें ।

विग्गहगदिमावण्णा केवलिणो समुग्घदो अजोगी य ।
सिद्धा य अणाहारा सेसा आहारया जीवा ॥६६६॥

विग्रहगतिमापन्नाः केवलिनः समुद्घातयंतोऽयोगी च सिद्धाश्चानाहाराः शेषा आहारका जीवाः ॥

विग्रहगतियं पोर्द्दिद जीवंगळु प्रतरलोकपूरणसमुद्घातसयोगकेवलिगळुमयोगकेवलिगळुं सिद्धपरमेष्ठिगळुमनाहारकमप्परु । शेषजीवंगळेनितोळवनितुमाहारकरेयप्परु । समुद्घातमेनितें दोडे पेळ्दपरु ।

वेयणकसायवेगुव्वियो य मरणंतियो समुग्घादो ।
तेजाहारो छट्ठो सत्तमओ केवलीणं तु ॥६६७॥

वेदनाकषायवैगुर्विकाश्च मारणांतिकः समुद्घातश्च । तेजः आहारः षष्ठः सप्तमः केवलिनां तु ॥

वेदनासमुद्घातमें दुं कषायसमुद्घातमें दुं वैगूर्विकसमुद्घातमें दुं मारणांतिकसमुद्घातमें दुं तैजससमुद्घातमें दुमाहारकसमुद्घातमें दु केवलिसमुद्घातमें दुमितु सप्तसमुद्घातंगळप्पुवु ।

अनंतरं समुद्घातमें बुदेनें दोडे पेळ्दपं :—

मूलसरीरमछंडिय उत्तरदेहस्स जीवपिंडस्स ।
णिग्गमणं देहादो होदि समुग्घादणामं तु ॥६६८॥

मूलशरीरमत्यक्त्वा उत्तरदेहस्य जीवपिंडस्य । निर्गमनं देहाद् भवति समुद्घातनाम तु ॥

मूलशरीरमं बिडदे कार्म्मणतैजसोत्तरदेहवजीवप्रदेशप्रचयक्के शरीरदिं पोरगल्पे निर्गमनं समुद्घातमें बुदक्कुं

विग्रहगत्याश्रितचतुर्गतिजीवाः प्रतरलोकपूरणसमुद्घातपरिणतसयोगिजिनाः अयोगिजिनाः सिद्धाश्च अनाहारा भवन्ति । शेषजीवाः सर्वेऽपि आहारका एव भवन्ति ॥६६६॥ समुद्घातः कतिधा ? इति चेदाह—

समुद्घातः वेदनाकषायवैगूर्विकमारणान्तिकतैजसाहारककेवलिसमुद्घातभेदात् सप्तधा भवति ॥६६७॥ स च किरूपः ? इति चेदाह—

मूलशरीरमत्यक्त्वा कार्मणतैजसरूपोत्तरदेहयुक्तस्य जीवप्रदेशप्रचयस्य शरीराद्बहिर्निर्गमनं स समुद्घातो नाम भवति ॥६६८॥

विग्रहगतिमें आये चारों गतियोंके जीव, प्रतर और लोकपूरण समुद्घात करनेवाले सयोगी जिन, और सिद्ध अनाहारक हैं। शेष सब जीव आहारक हैं ॥६६६॥

समुद्घातके भेद कहते हैं—

वेदना, कषाय, विक्रिया, मारणान्तिक, तैजस, आहार और केवली समुद्घातके भेदसे समुद्घात सात प्रकारका होता है ॥६६७॥

समुद्घातका स्वरूप कहते हैं—

मूल शरीरको छोड़कर कार्मण और तैजस रूप उत्तर शरीरसे युक्त जीवके प्रदेश समूहका शरीरसे बाहर निकलना समुद्घात है ॥६६८॥

१. [illegible]

काम्मणकाययोगिगळु अनाहारकर्परिमाणमक्कुं । तद्राशिविरहितमप्प संसारिराशि आहारकर परिमाणमक्कुमदेंतेंदोडे कार्म्मणकाययोगकालं समयत्रयमक्कुं । औदारिकमिश्रकालमंतर्म्मुहूर्त्तमक्कुं । तत्कायकालं संख्यातगुणमक्कुं । कूडि त्रिसमयाधिकसंख्यातगुणितांतर्म्मुहूर्त्तमक्कु ३ मिदु प्रक्षेपकयोगमक्कुमंतागुत्तं विरलु 'प्रक्षेपकयोगोद्धृतमिश्रपिंडः

२ १ ४

प्रक्षेपकाणां गुणको भवेत्सः । यंबी सूत्राभिप्रायदिदं त्रैराशिकं माडल्पडुगुं । प्र २ १ । ५ । (३)

फ १३– । इ स ३ । लब्धमनाहारकर प्रमाणमक्कुं । १३–। ३ मत्तं प्र २ १ । ५ । फ १३– । इ
(३ / २ १ । ५)

२ १ । ५ । लब्धमाहारकर प्रमाणमक्कुं १३– । २ १ । ५ वैक्रियिकाहारकंगळ्गं यथायोग्यमरि-
(३ / २ १ । ५)

यल्पडुगुं ।

कार्मणकाययोगिजीवराशिः अनाहारकपरिमाणं भवति । तद्विरहितसंसारिराशिः आहारकपरिमाणं भवति । तद्यथा—योगकालः कार्मणस्य त्रिसमयाः । औदारिकमिश्रस्य अन्तर्मुहूर्तः । औदारिकस्य ततः संख्यातगुणः । मिलित्वा त्रिसमयाधिकसंख्यातगुणितान्तर्मुहूर्तः । ३– २– "प्रक्षेपयोगोद्धृतमिश्रपिण्डः प्रक्षेपकाणां
२ १ ४

गुणको भवेदिति प्र २ १ ५ । फ १३– । इ स ३ । लब्धमनाहारकजीवप्रमाणं १३– ३ पुनः २ १ । ५ ।
(३– / २ १ । ५)

फ १३– । इ २ १ । ५ । लब्धमाहारकजीवप्रमाणं १३– । २ १ । ५ वैक्रियिकाहारकयोर्यथायोग्यं
(३– / २ १ । ५)

ज्ञातव्यम् ॥६७१॥

योगमार्गणामें कार्मणकाय योगियोंका जितना प्रमाण कहा है उतना ही अनाहारकोंका प्रमाण है । संसारीराशिमें-से अनाहारकोंका प्रमाण घटानेपर आहारकोंका परिमाण होता है । जो इस प्रकार है—कार्मणयोगका काल तीन समय है । औदारिक मिश्र काययोगका काल अन्तर्मुहूर्त है । औदारिक काययोगका काल उससे संख्यातगुणा है । सब मिलानेपर तीन समय अधिक संख्यात गुणित अन्तर्मुहूर्त काल होता है । करण सूत्रमें कहा है प्रक्षेपको मिलाकर मिले हुए पिण्डसे भाग देनेपर जो प्रमाण आवे उसे प्रक्षेपकसे गुणा करनेपर अपना अपना प्रमाण होता है । सो उक्त तीनों योगोंके कालोंको मिलानेपर तीन समय अधिक संख्यात अन्तर्मुहूर्त काल हुआ । इसका भाग कुछ हीन संसारीराशिमें देनेपर जो प्रमाण आवे उसे तीनसे गुणा करनेपर अनाहारक जीवोंका प्रमाण होता है । शेष सब संसारी आहारक जीव हैं । वैक्रियिक और आहारकवालोंका यथायोग्य जानना । उनके अल्प होनेसे यहाँ उनकी मुख्यता नहीं है ॥६७१॥

उपयोगाधिकारः ॥२०॥

अनंतरंमुपयोगाधिकारमं पेळ्वपं :—

वत्थुणिमित्तं भावो जादो जीवस्स जो दु उवजोगो ।
सो दुविहो णायव्वो सायारो चेव णायारो ॥६७२॥

वस्तुनिमित्तं भावो जातो जीवस्य यस्तूपयोगः। स द्विविधो ज्ञातव्यः साकारश्चैवानाकारः॥

वसतो गुणपर्य्यायावस्मिन्निति वस्तु—ज्ञेयपदार्त्थंस्तद्ग्रहणाय प्रवृत्तं ज्ञानं वस्तुनिमित्तं भावः अर्त्थग्रहणव्यापार इत्यर्त्थः। अर्त्थप्रकाशननिमित्तमागि जातः प्रवृत्तमप्प जीवस्य जीवन यस्तु आवुदोंदु भावः परिणामः। क्रियाविशेषमदुपयोगमें बुदु, अदु मत्ते साकारोपयोगमें बुमना-कारोपयोगमें बु द्विप्रकारमें दे ज्ञातव्यमक्कु।

अनंतर साकारोपयोगमें टु प्रकारमें बु पेळ्दपं :—

णाणं पंचविहंपि य अण्णाणतियं च सागरुवजोगो ।
चदुदंसणमणगारो सव्वे तल्लक्खणा जीवा ॥६७३॥

ज्ञानं पंचविधमपि च अज्ञानत्रयं च साकारोपयोगः। चतुर्द्दर्शनमनाकारः सर्व्वे तल्लक्षणा जीवाः॥

मतिश्रुतावधिमनःपर्य्ययकेवलमें ब सम्यग्ज्ञानपंचकमुं कुमतिकुश्रुतविभंगमें ब मूरु तेरद ज्ञानमुं साकारोपयोगमें बुदक्कुं। चक्षुर्द्दर्शनमचक्षुर्द्दर्शनमवधिदर्शनं केवलदर्शनमें बी नाल्कुं दर्शनमना-

---

सुव्रतः सुव्रतैः सेव्यः सुव्रतः सुव्रताय सः ।
प्राप्तार्हन्त्यपदो दद्यात् स्वकीयां सुव्रतश्रियम् ॥२०॥

अथोपयोगाधिकारमाह—

वसतः गुणपर्यायौ अस्मिन्निति वस्तु ज्ञेयपदार्थः— तद्ग्रहणाय जातः-प्रवृत्तः यो भावः-परिणाम-क्रियाविशेषः जीवस्य स उपयोगो नाम। स च साकारोऽनाकारश्चेति द्वेधा ज्ञातव्यः ॥६७२॥ अथ साकारो-पयोगोऽष्टधा इत्याह—

मतिश्रुतावधिमनःपर्ययकेवलज्ञानानि कुमतिकुश्रुतविभङ्गाज्ञानानि च साकारोपयोगः। चक्षुरचक्षु-

---

उपयोगाधिकार कहते हैं—

जिसमें गुण और पर्यायोंका वास है वह वस्तु अर्थात् ज्ञेय पदार्थ है। उसको ग्रहण करनेके लिए जीवका जो भाव अर्थात् परिणाम होता है वह उपयोग है। वह दो प्रकारका है—साकार और अनाकार ॥६७२॥

आगे इनके भेद कहते हैं—

मति, श्रुत, अवधि, मनःपर्यय और केवल ये पाँच ज्ञान तथा कुमति, कुश्रुत, विभंग ये

ज्ञानोपयोगयुक्तरुगळ परिमाणं ज्ञानमार्ग्गणेयोळु पेळ्दंतेयक्कुं। दर्शनोपयोगिगळ परिमाणं दर्शनमार्ग्गणेयोळु पेळ्द क्रममेयक्कुमदें तें दोडे कुमतिज्ञानिगळु किंचिदून संसारिराशिप्रमाणमक्कुं। १३—कुश्रुतज्ञानिगळुमंनिवरेयक्कुं ।१३–॥ विभंगज्ञानिगळु ॥/ =१ ४।६५=१ मतिज्ञानिगळु प/a श्रुतज्ञानिगळु प/a अवधिज्ञानिगळु प a/a a (०) मनःपर्य्ययज्ञानिगळु १ केवलज्ञानिगळु १/३ तिर्य्यंचविभंगज्ञानिगळु—६ प/a मनुष्यविभंगज्ञानिगळु । १ । नारकविभंगज्ञानिगळु –२– देवविभंगज्ञानिगळु = १ ४।६५=१ इंतिवु चक्षुर्द्दर्शनिगळु । प्र । वि । ति । च । प । ४ । फ । ४/a (=) इ प । प । २ । लब्ध प्र

[illegible]उपयोगिप्रमाणं ज्ञानमार्गणावत् । दर्शनोपयोगिप्रमाणं दर्शनमार्गणावत् भवेत् । तद्यथा—कुमतिज्ञानिनः [illegible] किंचिदूनसंसारिराशिः १३– विभङ्गज्ञानिनः ॥/ =१ ४६५=१ । मतिज्ञानिनः प/a श्रुतज्ञानिनः प/a [illegible] प a/a a (२) मनःपर्ययज्ञानिनः १ केवलज्ञानिनः १/३ तिर्यग्विभङ्गज्ञानिनः –६ प/a मनुष्यविभङ्गज्ञानिनः १ [illegible] –२ – देवविभङ्गज्ञानिनः ॥/ =१ ४।६५=१ । चक्षुर्दर्शनिनः प्र–वि । ति । च । [illegible]

ओघादेशप्ररूपणाधिकारः ॥२१॥

अनंतरमुक्तविंशतिप्ररूपणेगळं यथासंभवमागि गुणस्थानंगळोळं मार्गणास्थानंगळोळं प्रत्येकं पेळ्दपं—

गुणजीवा पज्जत्ती पाणा सण्णा य मग्गणुवजोगो ।
जोग्गा परूविदव्वा ओघादेसेसु पत्तेयं ॥६७७॥

गुणजीवाः पर्य्याप्तयः प्राणाः संज्ञाश्च मार्ग्गणा उपयोगे योग्याः प्ररूपयितव्याः ओघादेशेषु प्रत्येकं ॥

गुणस्थानमार्ग्गणास्थानंगळोळु प्रत्येकं । गुणस्थानंगळुं जीवसमासेगळुं पर्य्याप्तिगळुं प्राणंगळुं संज्ञेगळुं मार्ग्गणेगळुमुपयोगंगळुमें दोविंशतिप्रकारंगळु प्ररूपिसल्पडुववु । यथायोग्यमागि । अदें तें दोडे—

चउ पण चोद्दस चउरो णिरयादिसु चोद्दसं तु पंचक्खे ।
तसकाये सेसिंदियकाये मिच्छं गुणट्ठाणं ॥६७८॥

चतुः पंच चतुर्द्दश चत्वारि नरकादिषु चतुर्द्दश तु पंचाक्षे । त्रसकाये शेषेंद्रियकाये मिथ्यादृष्टिगुणस्थानं ॥

नरकतिर्य्यग्मनुष्यदेवगतिगळोळु यथासंख्यमागि नाल्कुमय्दुं पदिनाल्कुं नाल्कुं गुणस्थानंगळप्पुववें तें दोडे—नरकगतियोळु मिथ्यादृष्टिसासादनमिश्रासंयतगुणस्थानचतुष्टयमक्कुं । तिर्य्यग्गतियोळु मिथ्यादृष्टिसासादनमिश्रऽसंयतदेशसंयतगुणस्थानपंचकमक्कुं । मनुष्यगतियोळु सामान्य

नमिर्नमत्सुराधीशोऽनन्तज्ञानादिवैभवः ।
हतघातिचतुष्को जीयाद्धाम्नः शाश्वतं पदम् ॥

अथोत्तरमभिधेयं ज्ञापयति—

उक्तविंशतिप्ररूपणासु गुणस्थानमार्गणास्थानयोः प्रत्येकं गुणस्थानानि जीवसमासाः पर्याप्तयः प्राणाः संज्ञाः, मार्गणाः उपयोगाश्च यथायोग्यं प्ररूपयितव्याः ॥६७७॥ तद्यथा—

नारकादिगतिषु क्रमेण गुणस्थानानि मिथ्यादृष्ट्यादीनि चत्वारि पञ्च चतुर्दश चत्वारि भवन्ति। इन्द्रियमार्गणायां पञ्चेन्द्रिये तु पुनः कायमार्गणायां त्रसकाये च, चतुर्दश, शेषेन्द्रियकायेषु एकं मिथ्यादृष्टिगुणस्थानं । जीवसमासास्तु नरकगतौ संज्ञिपर्याप्तनिर्वृत्त्यपर्याप्तौ द्वौ । तिर्यग्गतौ चतुर्दश । मनुष्यगतौ संज्ञिपर्याप्त

बीस प्ररूपणाओंका कथन करनेके पश्चात् जो कुछ अभिधेय है उसे कहते हैं—

ऊपर कही बीस प्ररूपणाओंमें-से गुणस्थान और मार्गणास्थानमें गुणस्थान, जीवसमास, पर्याप्ति, प्राण, संज्ञा और उपयोगोंका यथायोग्य प्ररूपणा करना चाहिये ॥६७७॥ वही कहते हैं—

गतिमार्गणामें क्रमसे गुणस्थान, मिथ्यादृष्टि आदि नरक गतिमें चार, तिर्यंचगतिमें पाँच, मनुष्यगतिमें चौदह और देवगतिमें चार होते हैं। इन्द्रियमार्गणामें, पंचेन्द्रियमें, और कायमार्गणामें त्रसकायमें चौदह गुणस्थान होते हैं। शेष एकेन्द्रियादिमें और स्थावरकायमें

मज्झिमचउमणवयणे सण्णिप्पहुडिं तु जाव खीणोत्ति ।
सेसाणं जोगित्ति य अणुभयवयणं तु वियलादो ॥६७९॥

मध्यमचतुर्म्मनोवचनेषु संज्ञिप्रभृतिस्तु यावत् । क्षीणकषायस्तावत्पर्य्यंतं शेषाणां योगिपर्य्यंतं च अनुभयवचनं तु विकलात् ॥

मनोवचनयोगंगळोळु मध्यमंगळप्प असत्यमनोयोगमुभयमनोयोगमसत्यवचनयोगमुभयवचनयोगमेंबी नाल्करोळं मिथ्यादृष्टिसंज्ञिपंचेंद्रियमादियागि क्षीणकषायगुणस्थानपर्य्यंतमप्प पन्नेरडु गुणस्थानंगळुमों दो दे संज्ञिपंचेंद्रियपर्य्याप्तजीवसमासेगळु प्रत्येकमप्पुवु । शेषसत्यमनोयोगदोळुमनुभयमनोयोगदोळं सत्यवचनयोगदोळं संज्ञिपंचेंद्रियपर्य्याप्तमिथ्यादृष्टिगुणस्थानमादियागि सयोगिकेवलिगुणस्थानपर्य्यंतं पदिमूरुं गुणस्थानंगळं पंचेंद्रियसंज्ञिपर्य्याप्तजीवसमासेगळो दोंदु प्रत्येकमप्पुवु । अनुभयवचनयोगदोळु विकलत्रयमिथ्यादृष्टिगुणस्थानमादियागि सयोगकेवलिगुणस्थानपर्य्यंतमाद पदिमूरुं गुणस्थानंगळं द्वींद्रियत्रींद्रियचतुरिंद्रियसंज्ञिपंचेंद्रियासंज्ञिपंचेंद्रियपर्य्याप्त जीवसमासगळुमय्दप्पुवु :— मनोयोग

	स	अ	उ	अ
गु	१३	१२	१२	१३
जी	१	१	१	१

वाग्योग

स	अ	उ	अ
१३	१२	१२	१३
१	१	१	५

ओरालं पज्जत्ते थावरकायादि जाव जोगित्ति ।
तम्मिस्समपज्जत्ते चदुगुणठाणेसु णियमेण ॥६८०॥

औदारिकः पर्य्याप्ते स्थावरकायादि यावद्योगिपर्य्यंतं । तन्मिश्रः अपर्य्याप्ते चतुर्गुणस्थानेषु नियमेन ॥

औदारिककाययोगमेकेंद्रियस्थावरकायपर्य्याप्तमिथ्यादृष्टिगुणस्थानमादियागि सयोगकेवलिपर्य्यंतमाद पदिमूरुं गुणस्थानंगळक्कुमल्लि एकेंद्रियबादरसूक्ष्मद्वींद्रियत्रींद्रियचतुरिंद्रियसंज्ञिपंचेंद्रियासंज्ञिपंचेंद्रियपर्य्याप्तजीवसमासेगळुमेळप्पुवु ।७। औदारिकमिश्रयोगमपर्य्याप्तचतुर्गुणस्थानंगळोळु

मध्यमेषु असत्योभयमनोवचनयोगेषु चतुर्षु संज्ञिमिथ्यादृष्टयादीनि क्षीणकषायान्तानि द्वादश । पुनः सत्यानुभयमनोयोगयोः सत्यवचनयोगे च संज्ञिपर्याप्तमिथ्यादृष्टयादीनि सयोगान्तानि त्रयोदश गुणस्थानानि भवन्ति । जीवसमासः संज्ञिपर्याप्त एकः । अनुभयवचनयोगे तु गुणस्थानानि विकलत्रयमिथ्यादृष्ट्यादीनि त्रयोदश । जीवसमासाः द्वित्रिचतुरिन्द्रियसंज्ञ्यसंज्ञिपर्याप्ताः पञ्च ॥६७९॥

औदारिककाययोगः एकेन्द्रियस्थावरकायपर्याप्तमिथ्यादृष्ट्यादिसयोगान्तत्रयोदशगुणस्थानेषु भवति ।

मध्यम अर्थात् असत्य और उभय मनोयोग और वचन योग इन चारमें संज्ञी मिथ्यादृष्टिसे लेकर क्षीणकषाय पर्यन्त बारह गुणस्थान होते हैं। तथा सत्य और अनुभय मनोयोग और सत्यवचनयोगमें संज्ञिपर्याप्त मिथ्यादृष्टिसे लेकर सयोगकेवली पर्यन्त तेरह गुणस्थान होते हैं। जीवसमास एक संज्ञिपर्याप्त ही होता है। अनुभयवचनयोगमें विकलत्रय मिथ्यादृष्टिसे लेकर तेरह गुणस्थान होते हैं। जीवसमास दो-इन्द्रिय, तेइन्द्रिय, चौइन्द्रिय संज्ञि-असंज्ञी, पंचेन्द्रिय पर्याप्त रूप पाँच होते हैं ॥६७९॥

औदारिक काययोग एकेन्द्रिय स्थावरकाय पर्याप्त मिथ्यादृष्टीसे लेकर सयोगकेवली पर्यन्त तेरह गुणस्थानोंमें होता है। औदारिक मिश्रकाययोग नियमसे अपर्याप्त अवस्थामें

कायथोगदोळु पंचेंद्रियसंज्ञिपर्य्याप्तजीवसमासमो देयक्कुं। तन्मिश्रदोळु संज्ञिपंचेंद्रियनिर्वृत्यपर्य्याप्तजीवसमासमो देयक्कुं वै मि

४। ३।

१ १।

आहारो पज्जत्ते इदरे खलु होदि तस्स मिस्सो दु।
अंतोमुहुत्तकाले छट्ठगुणे होदि आहारो ॥६८३॥

आहारः पर्य्याप्ते इतरस्मिन् खलु भवति तस्य मिश्रस्तु। अंतर्मुहूर्तकाले षष्ठगुणे भवति आहारः ॥

आहारककाययोगसंज्ञिपंचेंद्रियपर्य्याप्तषष्ठगुणस्थानवर्त्तिप्रमत्तसंयतनोळक्कुमाहारककाययोगकालमुमुत्कृष्टदिदमुं जघन्यदिदमुमंतर्म्मुहूर्त्तकालदोळेयक्कुं। तन्मिश्रकाययोगमुं तद्गुणस्थानदोळे प्रमत्तगुणस्थानदोळे अंतर्म्मुहूर्त्तकालदोळेयक्कुमदु कारणमागियाहारककाययोगदोळं गुणस्थानमुमो दे जीवसमासमुमक्कुं। तन्मिश्रदोळमंते यो देगुणस्थानमुमो दे जीवसमासमुमक्कुं
आहारककाययोगदोळु गु १। मि गु १
जी १। जी १

ओरालियमिस्सं वा चउगुणठाणेसु होदि कम्मइयं।
चदुगदिविग्गहकाले जोगिस्स य पदरलोगपूरणगे ॥६८४॥

औदारिकमिश्रवच्चतुर्गुणस्थानेषु भवति कार्म्मणं। चतुर्गतिविग्रहकाले योगिनः प्रतरलोकपूरणे ॥

ओदारिकमिश्रकाययोगदोळ्पेळ्दंते चतुर्गुणस्थानंगळोळु कार्म्मणकाययोगमक्कुं मत्तु चतुर्गतिविग्रहकालदोळं सयोगकेवलिय प्रतरलोकपूरणसमुद्घातकालदोळमक्कुमदु कारणमागि कार्म्मणकाययोगदोळु मिथ्यादृष्टिसासादनासंयतसम्यग्दृष्टि समुद्घातसयोगिभट्टारकरेंब गुण-

---

तन्मिश्रयोगः मिश्रगुणस्थाने तु न होति कारणात् देवनारकमिथ्यादृष्टिसासादनासंयतेष्वेव भवति। जीवसमासः तयोः क्रमेण संज्ञिपर्याप्तः तन्निर्वृत्त्यपर्याप्तः एकैकः ॥६८२॥

आहारककाययोगः संज्ञिपर्याप्तषष्ठगुणस्थाने जघन्योत्कृष्टेन अन्तर्मुहूर्तकाले एव भवति। तन्मिश्रयोगः इतरस्मिन् अपर्याप्तषष्ठगुणस्थाने तत्र जघन्योत्कृष्टेन तावत्काले एव भवति। तेन तयोर्योगयोः गुणस्थानं जीवसमासः स एव एकैकः ॥६८३॥

औदारिकमिश्रवच्चतुर्गुणस्थानेषु कार्मणकाययोगः स्यात् स चतुर्गतिविग्रहकाले सयोगस्य प्रतरलो-

---

मिथ्यादृष्टि, सासादन और असंयतगुणस्थानोंमें ही होता है। जीवसमास उनमें-से वैक्रियिकमें संज्ञीपर्याप्त और वैक्रियिकमिश्रमें संज्ञीअपर्याप्त होता है ॥६८२॥

आहारक काययोग संज्ञीपर्याप्त छठे गुणस्थानमें जघन्य और उत्कृष्टसे अन्तर्मुहूर्त कालमें ही होता है। आहारकमिश्रकाययोग संज्ञीअपर्याप्त अवस्थामें छठे गुणस्थानमें जघन्य उत्कृष्टसे अन्तर्मुहूर्त कालमें ही होता है। अतः इन दोनोंमें एक छठा ही गुणस्थान होता है। तथा जीवसमास भी यही संज्ञीपर्याप्त और संज्ञीअपर्याप्त एक-एक ही होता है ॥६८३॥

औदारिकमिश्रकी तरह कार्मणकाययोग चार गुणस्थानोंमें होता है। सो वह चार गति सम्बन्धी विग्रहगतिके कालमें और सयोगकेवलीके प्रतर और लोकपूरण समुद्घातमें

कषायमार्गणेयोळ् क्रोधमानमायाकषायत्रयंगळ् स्थावरकायमिथ्यादृष्टिगुणस्थानं मोदल्गोंडनिवृत्तिकरणगुणस्थानद्वित्रिचतुर्थभागपर्यंतमाद गुणस्थाननवकदोळप्पुवु। अदु कारण-मागि क्रोधादिकषायत्रयदोळ् प्रत्येकमों भत्तुमों भत्तुं गुणस्थानंगळुमेकेंद्रियबादरसूक्ष्मद्वित्रिचतुः संज्ञिपंचेंद्रिय संज्ञिपंचेंद्रियपर्य्याप्तापर्य्याप्तजीवसमासेगळ् पदिनाल्कुं पदिनाल्कुमप्पुवु। लोभ-कषायदोळमंते स्थावरकायमिथ्यादृष्टिगुणस्थानमादियागि सूक्ष्मसांपरायगुणस्थानपर्यंतमाद गुण-स्थानदशकमुं क्रोधादिगळ्गे पेळ्दंत चतुर्दशजीवसमासेगळुमप्पुवेंदु परमागमदोळरियल्पडुवुवु।

को	मा	मा	लो
९	९	९	१०
१४	१४	१४	१४

थावरकायप्पहुडी मदिसुदअण्णाणयं विभंगो दु।
सण्णीपुण्णप्पहुडी सासणसम्मोत्ति णायव्वो ॥६८७॥

स्थावरकायप्रभृति मतिश्रुताज्ञानकं विभंगस्तु। संज्ञिपूर्णप्रभृति सासादनसम्यग्दृष्टिपर्यंतं ज्ञातव्यं ॥

ज्ञानमार्गणेयोळ् मतिश्रुताज्ञानद्वयं स्थावरकायमिथ्यादृष्टिप्रभृतिसासादनसम्यग्दृष्टिगुण-स्थानपर्यंतमेरडेरडुगुणस्थानदोळप्पुवु। एकेंद्रियबादरसूक्ष्मद्वित्रिचतुः पंचेंद्रियसंज्ञसंज्ञिपर्य्याप्ता-पर्य्याप्तजीवसमासेगळु प्रत्येकं पदिनाल्कु पदिनाल्कुमप्पुवु। विभंगज्ञानमुं संज्ञिपूर्णमिथ्यादृष्टियादि-यागि सासादनसम्यग्दृष्टिपर्यंतमेरडुगुणस्थानदोळप्पुवु। संज्ञिपंचेंद्रियपर्य्याप्तजीवसमासेयोंदे-प्पुदु। एंदितु परमागमदोळरियल्पडुवुवु।

कषायमार्गणायां क्रोधमानमायाः स्थावरकायमिथ्यादृष्ट्याद्यनिवृत्तिकरणद्वित्रिचतुर्भागान्तम्। लोभः पुनः सूक्ष्मसांपरायान्तम्। तेन क्रोधत्रये गुणस्थानानि नव लोभे दश ज्ञेयानि। जीवसमासाः सर्वत्र चतुर्दशैव ॥६८६॥

ज्ञानमार्गणायां मतिश्रुताज्ञानद्वयं स्थावरकायमिथ्यादृष्ट्यादिसासादनान्तं ज्ञातव्यं तेन तत्र गुणस्थाने द्वे। जीवसमासाश्चतुर्दश। पुनः विभङ्गज्ञानं संज्ञिपूर्णमिथ्यादृष्ट्यादिसासादनान्तं तत्र गुणस्थाने द्वे। जीवसमासः संज्ञिपर्याप्त एवैकः ॥६८७॥

कषायमार्गणामें क्रोध, मान, माया, स्थावरकायमिथ्यादृष्टिसे लेकर अनिवृत्तिकरणके क्रमसे दूसरे, तीसरे और चौथे भागपर्यन्त होते हैं। लोभ सूक्ष्मसाम्पराय गुणस्थानपर्यन्त होता है। इससे क्रोध, मान, मायामें नौ और लोभमें दस गुणस्थान होते हैं। जीवसमास सर्वत्र चौदह होते हैं ॥६८६॥

ज्ञानमार्गणामें कुमति, कुश्रुतज्ञान स्थावरकायमिथ्यादृष्टिसे लेकर सासादनपर्यन्त जानना। इससे उनमें दो गुणस्थान होते हैं। जीवसमास चौदह होते हैं। विभंगज्ञान संज्ञिपर्याप्त मिथ्यादृष्टिसे लेकर सासादन पर्यन्त जानना। इससे उसमें भी दो गुणस्थान होते हैं। जीवसमास एक संज्ञीपर्याप्त ही होता है ॥६८७॥

---

१. म°दोळेल्लप्पुवु।

संयतमुमवकुमल्लि संज्ञिपंचेंद्रियपर्य्याप्तजीवसमासमों देयक्कुं। सामायिकच्छेदोपस्थापनसंयमंगळेरडुं प्रत्येकं प्रमत्त संयतगुणस्थानमादियागऽनिवृत्तिकरणगुणस्थानपर्य्यंतं नाल्कुं नाल्कुं गुणस्थानंगळप्पुवल्लि संज्ञिपंचेंद्रियपर्य्याप्तजीवसमासमुं आहारकापर्य्याप्तजीवसमासमुमितेरडेरडु जीवसमासंगळप्पुवु। परिहारविशुद्धिसंयमं प्रमत्तसंयतरोळमप्रमत्तसंयतरोळमक्कुमल्लि संज्ञिपंचेंद्रियपर्य्याप्तजीवसमासमों दे यक्कुमेकें दोडे परिहारविशुद्धिसंयमऋद्धियुमाहारकऋद्धियुमोब्बंनोळे संभविसल्पडुर्दरिवं। सूक्ष्मसांपरायसंयमं सूक्ष्मसांपरायगुणस्थानदोळेयक्कुमल्लि संज्ञिपंचेंद्रियपर्य्याप्तजीवसमासमों देयक्कुं। यथाख्यातचारित्रमुपशांतकषायगुणस्थानदोळं क्षीणकषायगुणस्थानदोळं सयोगिकेवलिगुणस्थानदोळमयोगिकेवलिगुणस्थानदोळमितु नाल्कुं गुणस्थानंगळोळमक्कुमल्लि संज्ञिपंचेंद्रियपर्य्याप्तजीवसमासमुं समुद्घातकेवलिय अपर्य्याप्तजीवसमासमुं कूडि जीवसमासद्वयमक्कुं। संयममार्गणाभेदंगळु सिद्धपरमेष्ठिगळोळु संभविसुवयल्तें दु परमागमदोळ्पेळल्पट्टुदु।

अ।	वे।	सा।	छे।	प।	सू।	य।
४।	१।	४।	४।	२।	१।	४।
१४।	१।	२।	२।	१।	१।	२।

चउरक्खथावरविरदसम्मादिट्ठी दु खीणमोहोत्ति।
चक्खु अचक्खू ओही जिणसिद्धे केवलं होदि ॥६९१॥

चतुरिंद्रियस्थावराविरतसम्यग्दृष्टितः क्षीणमोहपर्य्यंतं। चक्षुरचक्षुरवधयो जिनसिद्धे केवलं भवंति ॥

देशसंयतगुणस्थाने तत्र जीवसमासः संज्ञिपर्याप्त एव। सामायिकछेदोपस्थापनौ प्रमत्ताद्यनिवृत्तिकरणान्तचतुर्गुणस्थानेषु। तत्र जीवसमासौ संज्ञिपर्याप्ताहारकपर्याप्तौ द्वौ। परिहारविशुद्धिसंयमः प्रमत्ताप्रमत्तयोरेव। तत्र जीवसमासः संज्ञिपर्याप्त एव तेन सह आहारकर्द्धेरेकत्रासंभवात्। सूक्ष्मसांपरायसंयमः सूक्ष्मसांपरायगुणस्थाने तत्र जीवसमासः संज्ञिपर्याप्तः। यथाख्यातचारित्रं उपशान्तकषायादिचतुर्गुणस्थानेषु तत्र जीवसमासौ संज्ञिपर्याप्तसमुद्घातकेवल्यपर्याप्तौ द्वौ। संयममार्गणाभेदाः सिद्धे न संतीति परमागमे निर्दिष्टम् ॥६८९-६९०॥

है उसमें चौदह जीवसमास होते हैं। देशसंयम देशसंयत गुणस्थानमें होता है उसमें जीवसमास एक संज्ञिपर्याप्त ही होता है। सामायिक और छेदोपस्थापना प्रमत्तसे लेकर अनिवृत्तिकरणपर्यन्त चार गुणस्थानोंमें होते हैं। उनमें जीवसमास संज्ञिपर्याप्त और आहारक मिश्रकी अपेक्षा संज्ञिअपर्याप्त होते हैं। परिहारविशुद्धिसंयम प्रमत्त और अप्रमत्त गुणस्थानोंमें ही होता है। उसमें जीवसमास संज्ञिपर्याप्त ही होता है क्योंकि परिहारविशुद्धि संयमके साथ आहारकऋद्धि नहीं होती। सूक्ष्मसाम्परायसंयत सूक्ष्मसाम्पराय गुणस्थानमें होता है। उसमें जीवसमास संज्ञिपर्याप्त ही होता है। यथाख्यातचारित्र उपशान्तकषाय आदि चार गुणस्थानोंमें होता है। उसमें जीवसमास संज्ञिपर्याप्त तथा समुद्घात केवलीकी अपेक्षा अपर्याप्त इस तरह दो होते हैं। संयममार्गणाके भेद सिद्धोंमें नहीं होते ऐसा परमागममें कहा है ॥६८९-६९०॥

णवरि य सुक्का लेस्सा सजोगिचरिमोत्ति होदि णियमेण ।
गयजोगिम्मि वि सिद्धे लेस्सा णत्थित्ति णिद्दिट्ठं ॥६९३॥

विशेषोस्ति शुक्ललेश्या सयोगचरमपर्य्यंतं भवति नियमेन । गतयोगेऽपि सिद्धे लेश्या न संतीति निर्दिष्टं ॥

शुक्ललेश्येयोळु विशेषमुंटावुदें दोडे शुक्ललेश्यासंज्ञिपर्य्याप्तमिथ्यादृष्टिगुणस्थानमादियागि सयोगिकेवलिगुणस्थानपर्य्यंतं पदिमूरुं गुणस्थानंगळोळप्पुवें बुदल्लि संज्ञिपंचेंद्रियपर्य्याप्तापर्य्याप्तजीवसमासमुं समुद्घातकेवलिय औदारिकमिश्रकार्म्मणकाययोगकालकृतापर्य्याप्तजीवसमासमुं कूडि जीवसमासद्वयमक्कुं नियमदिदं । कृ । नी । क । ते । प । शु गतयोगरप्प अयोगिकेवलि-

४ । ४ । ४ । ७ । ७ । १३

१४ । १४ । १४ । २ । २ । २

गळोळं सिद्धपरमेष्ठिगळोळं लेश्येगळिल्लमें दितु परमागमदोळ्पेळल्पट्टुदु ।

थावरकायप्पहुडी अजोगिचरिमोत्ति होंति भवसिद्धा ।
मिच्छाइट्ठिट्ठाणे अभव्वसिद्धा हवंतित्ति ॥६९४॥

स्थावरकायप्रभृत्ययोगिचरमसमयपर्य्यंतं भवंति भव्यसिद्धाः । मिथ्यादृष्टिस्थाने अभव्यसिद्धा भवंतीति ॥

भव्यमार्गणेयोळु स्थावरकायमिथ्यादृष्टिगुणस्थानमादियागि अयोगिकेवलिचरमगुणस्थानपर्य्यंतं पदिनाल्कुं गुणस्थानंगळोळु भव्यसिद्धरुगळप्परल्लि पदिनाल्कुं जीवसमासेगळप्पुवु । अभव्यसिद्धरुगळु मिथ्यादृष्टिगुणस्थानमों दरोळेयप्परु । अल्लि पदिनाल्कुं जीवसमासेगळप्पुवु भ । अ

१४ । १

१४ । १४

मिच्छो सासणमिस्सो सगसगठाणम्मि होदि अयदादो ।
पढमुवसमवेदगसम्मत्तदुगं अप्पमत्तोत्ति ॥६९५॥

मिथ्यादृष्टिः सासादनो मिश्रः स्वस्वस्थाने भवति असंयतात्प्रथमोपशमवेदकसम्यक्त्वद्विकमप्रमत्तपर्य्यंतं ॥

शुक्ललेश्यायां विशेषः । स कः ? सा लेश्या संज्ञिपर्याप्तमिथ्यादृष्ट्यादिसयोगान्तं भवति तत्र जीवसमासौ संज्ञिपर्याप्तापर्याप्तौ द्वावेव नियमेन कैवल्यपर्याप्तस्य अपर्याप्ते एवान्तर्भावात् । अयोगिजिने सिद्धे च लेश्या न सन्तीति परमागमे प्रतिपादितम् ॥६९३॥

भव्यमार्गणायां भव्यसिद्धाः स्थावरकायमिथ्यादृष्ट्याद्ययोगान्तं भवन्ति । अभव्यसिद्धाः मिथ्यादृष्टिगुणस्थाने एव भवन्ति इत्युभयत्र जीवसमासाश्चतुर्दश ॥६९४॥

शुक्ललेश्यामें विशेष है । वह संज्ञिमिथ्यादृष्टिसे लेकर सयोगीपर्यन्त होती है । उसमें जीवसमास संज्ञिपर्याप्त और संज्ञिअपर्याप्त दो ही नियमसे होते हैं । केवलिसमुद्घातगत अपर्याप्तका अन्तर्भाव अपर्याप्तमें ही हो जाता है । अयोग केवली और सिद्धोंमें लेश्या नहीं होती ऐसा परमागममें कहा है ॥६९३॥

भव्यमार्गणामें भव्य स्थावरकाय मिथ्यादृष्टिसे लेकर अयोगकेवली पर्यन्त होते हैं । अभव्य मिथ्यादृष्टि गुणस्थानमें ही होते हैं । दोनोंमें जीवसमास चौदह ही होते हैं ॥६९४॥

द्वितीयोपशमसम्यक्त्वमसंयतादुपशांतकषायगुणस्थानपर्य्यंतमें दु गुणस्थानंगळोळक्कुमल्लि· युपशमश्रेण्यवरोहणवोळऽप्रमत्तप्रमत्तदेशसंयतासंयतरोळु द्वितीयोपशमसम्यक्त्वसंभवमें दरियुदें· वोडे उपशमश्रेण्यारोहणावरोहणकालमं नोडलु तदुपशमसम्यक्त्वकालं संख्यातगुणमक्कुमेतेंदोडे चारित्रावरणोदयदिदं देशसंयतासंयतरोळु पतनमुंटप्पुदरिदं। अल्लि संज्ञिपंचेंद्रियपर्य्याप्तजीवसमा· सेयुं देशसंयतापर्य्याप्तजीवसमासेयुमितेरडु जीवसमासेगळप्पुवु। क्षायिकसम्यक्त्वमसंयतादियु· योगिकेवलिगुणस्थानमवसानमागि पंनों दुं गुणस्थानंगळोळप्पुवल्लि। संज्ञिपंचेंद्रियपर्य्याप्तमुन्· मानजीवसमासेयुं बद्धायुष्यापेक्षेयिदं धर्म्मेय नारकापर्य्याप्तनु भोगभूमिजमनुष्यतिर्य्यंचासंयता· पर्य्याप्तरुं देवासंयतापर्य्याप्तनु संभविसुगुमप्पुदरिनपर्य्याप्तजीवसमासेयुमितेरडुजीवसमासे· गळप्पुवु। संदृष्टिरचने :— गुणस्थानातीतरप्प सिद्धपरमेष्ठिगळोळं

मि	सा	मि	द्वि	उ	प्र	वे	क्षा
१	१	१	८	।	४	४	११
१४	७	।१	२	।	१	२	२

क्षायिकसम्यक्त्वमक्कुमें दितु जिनस्वामिगळिंदं पेळल्पट्टुदु॥

सण्णी सण्णिप्पहुडी खीणकसाओत्ति होदि णियमेण।
थावरकायप्पहुडी असण्णित्ति हवे असण्णी दु ॥६९७॥

संज्ञी संज्ञिप्रभृति क्षीणकषायपर्यंतं भवति नियमेन। स्थावरकायप्रभृति असंज्ञिपर्यं भवेदसंज्ञी तु॥

संज्ञिमार्गणेयोळु संज्ञिजीवं संज्ञिमिथ्यादृष्टिगुणस्थानमादियागि क्षीणकषायगुणस्था पर्य्यंतं पन्नेरडुं गुणस्थानंगळोळप्पुवु अल्लि संज्ञिपंचेंद्रियपर्य्याप्तापर्य्याप्तजीवसमासद्वयमक्कुं। मत्ते असंज्ञिजीवस्थावरकायमिथ्यादृष्टिगुणस्थानमादियागि पंचेंद्रियासंज्ञिमिथ्यादृष्टिपर्य्यंतं मि·

द्वितीयोपशमसम्यक्त्वं असंयतादुपशान्तकषायान्तं भवति। अप्रमत्ते उत्पाद्य उपरि उपशान्तकषाय गत्वा अधोवतरणे असंयतान्तमपि तत्संभवात्। तत्र जीवसमासौ संज्ञिपर्याप्तदेवासंयतापर्याप्तौ द्वौ। क्षा सम्यक्त्वं असंयतादयोगान्तम्। तत्र जीवसमासौ संज्ञिपर्याप्तः बद्धायुष्कापेक्षया घर्मानारकभोगभूमिनरतिः मानिकापर्याप्तश्चेति द्वौ। सिद्धेऽपि क्षायिकसम्यक्त्वं स्यादिति जिनैरुक्तम् ॥६९६॥

संज्ञिमार्गणायां संज्ञिजीवः संज्ञिमिथ्यादृष्टयादिक्षीणकषायान्तं भवति तत्र जीवसमासौ संज्ञिपर्याप्ताप

द्वितीयोपशम सम्यक्त्व असंयतसे उपशान्तकषाय गुणस्थानपर्यन्त होता है; क्ष अप्रमत्त गुणस्थानमें इस द्वितीयोपशम सम्यक्त्वको उत्पन्न करके ऊपर उपशान्तकषाय प जाकर नीचे उतरनेपर असंयत पर्यन्त भी उसका अस्तित्व रहता है। उसमें जीवस संज्ञिपर्याप्त तथा देव असंयत अपर्याप्त दो होते हैं। क्षायिक सम्यक्त्व असंयतसे अ पर्यन्त होता है। उसमें जीवसमास संज्ञिपर्याप्त होता है। किन्तु परभवकी आयु बाँ अपेक्षा प्रथम नरक, भोगभूमिया मनुष्य तिर्यंच और वैमानिक सम्बन्धी अपर्याप्त होते होते हैं। सिद्धोंमें भी क्षायिक सम्यक्त्व जिनदेवने कहा है ॥६९६॥

संज्ञीमार्गणामें संज्ञीजीव संज्ञिमिथ्यादृष्टिसे लेकर क्षीणकषाय गुणस्थानपर्यन्त है। उसमें जीवसमास संज्ञिपर्याप्त और अपर्याप्त दो होते हैं। असंज्ञीजीव स्थावर

मिथ्यादृष्टिगुणस्थानदोळु पदिनाल्कुं जीवसमासेगळप्पुवु। सासादनसम्यग्दृष्टिगुणस्थानदोळं अविरतसम्यग्दृष्टिगुणस्थानदोळं प्रमत्तविरतनोळं च शब्ददिदं सयोगकेवलिगुणस्थानदोळमितु नाल्कुं गुणस्थानंगळोळु संज्ञिपंचेंद्रियपर्य्याप्तापर्य्याप्तजीवसमासद्वयं प्रत्येकमक्कुं। शेषमिश्रदेशसंयताप्रमत्तापूर्व्वकरणानिवृत्तिकरणसूक्ष्मसांपरायोपशांतकषायक्षीणकषायगुणस्थानाष्टकदोळमपि-शब्ददिदमयोगिगुणस्थानदोळमितु नवगुणस्थानंगळोळु प्रत्येकं संज्ञिपंचेंद्रियपर्य्याप्तजीवसमासेयो देयक्कुं:—

मि। सा। मि। अ। दे। प्र। अ। अ। अ। सू। उ। क्षी। स। अ
१४। २। १। २। १। २। १। १। १। १। १। १। २। १

अनंतरं मार्ग्गणास्थानंगळोळु जीवसमासेयं सूचिसिदपं:—

तिरियगदीए चोद्दस हवंति सेसेसु जाण दोद्दो दु।
मग्गणठाणस्सेवं णेयाणि समासठाणाणि ॥७००॥

तिर्य्यग्गतौ चतुर्द्दश भवंति शेषेषु जानीहि द्वौ द्वौ तु। मार्ग्गणास्थानस्यैवं ज्ञेयानि समासस्थानानि ॥

तिर्य्यग्गतियोळु जीवसमासंगळु पदिनाल्कुमप्पुवु। शेषनारकदेवमनुष्यगतिगळोळु संज्ञिपंचेंद्रियपर्य्याप्तापर्य्याप्तजीवसमासद्वयमक्कुं। तु मत्ते एवमी प्रकारदिदं मार्ग्गणास्थानंगळोळयनितक्कुं। जीवसमासस्थानंगळु यथायोग्यमागि मुंपेळ्द क्रमदिनरियल्पडुवुवु।

अनंतरं गुणस्थानंगळोळु पर्य्याप्तिप्राणंगळं निरूपिसिदपरु:—

पज्जत्ती पाणावि य सुगमा भाविंदियं ण जोगिम्हि।
तहि वाचुस्सासाउगकायत्तिगदुगमजोगिणो आऊ ॥७०१॥

पर्य्याप्तयः प्राणाः अपि च सुगमाः भावेंद्रियं न योगिनि। तस्मिन्वागुच्छ्वासायुःत्रिकद्विकमयोगिनः आयुः ॥

मिथ्यादृष्टौ जीवसमासाश्चतुर्दश, सासादने अविरते प्रमत्ते चशब्दात् सयोगे च संज्ञिपर्याप्तापर्याप्तौ। शेषाष्टगुणस्थानेषु 'दु'शब्दात् अयोगे च संज्ञिपर्याप्त एकः ॥६९९॥ अथ मार्गणास्थानेषु तान् सूचयति-तिर्यग्गतौ जीवसमासाश्चतुर्दश भवन्ति शेषगतिषु संज्ञिपर्याप्तापर्याप्तौ द्वौ। तु-पुनः सर्वमार्गणासु यथायोग्यं प्रागुक्तक्रमेण जीवसमासा ज्ञातव्याः ॥७००॥ अथ गुणस्थानेषु पर्याप्तिप्राणानाह—

मिथ्यादृष्टिमें चौदह जीवसमास होते हैं। सासादन, अविरत, प्रमत्त और च सयोगीमें संज्ञिपर्याप्त और अपर्याप्त दो जीवसमास होते हैं। शेष आठ गुणस्थानों अपि शब्दसे अयोगकेवलीमें एक संज्ञिपर्याप्त ही होता है ॥६९९॥

अब मार्गणाओंमें जीवसमास कहते हैं:—

तिर्यञ्चगतिमें चौदह जीवसमास होते हैं। शेष गतियोंमें संज्ञीपर्याप्त, अप जीवसमास होते हैं। इस प्रकार सब मार्गणास्थानोंमें यथायोग्य पूर्वोक्त क्रमसे जीव जानना ॥७००॥

गुणस्थानोंमें पर्याप्ति और प्राण कहते हैं—

१. मु. °पु अविरतात्।

एकेंद्रियादिजातिनामकर्म्मोदयजनितजीवपर्य्यायिंद्रियमक्कुमा इंद्रियमार्ग्गणेगळें दें एकेंद्रियादिपंचप्रकारमप्पुवु। मिथ्यादृष्टिगुणस्थानदोळु पर्य्याप्तापर्य्याप्तैकद्वित्रिचतुःपंचेंद्रियंगळप्पुवु।

सासादनसम्यग्दृष्टिगुणस्थानदोळु एकेंद्रियादिपंचेंद्रियपर्य्यंतमादपुवपर्य्याप्तजीवंगळं पर्य्याप्त पंचेंद्रियजीवंगळुमप्पुवु। मिश्रगुणस्थानदोळु पर्य्याप्तपंचेंद्रियमो देयक्कुं। असंयतसम्यग्दृष्टिगुणस्थानदोळु पर्य्याप्तापर्य्याप्तसंज्ञिपंचेंद्रियजीवंगळेयप्पुवु। देशसंयतगुणस्थानदोळु पर्य्याप्तपंचेंद्रियमो देयक्कुं। प्रमत्तगुणस्थानदोळु पर्य्याप्तपंचेंद्रियमो देयक्कुमल्लि आहारकऋद्धियुक्तनोळु तत्प्रकृतपदेशेदोंदिदं पर्य्याप्तापर्य्याप्ताहारकशरीरपंचेंद्रियमुमक्कुं। अप्रमत्तगुणस्थानदोळु मेले क्षीणकषायगुणस्थानपर्य्यंतमादवं गुणस्थानंगळोळु प्रत्येकं पर्य्याप्तपंचेंद्रियमेयक्कुं। सयोगकेवलिगुणस्थानदोळु पर्य्याप्तपंचेंद्रियमेयक्कुमल्लि समुद्घातकेवलियोळोंदिदं मुं पेळ्दंतपर्य्याप्तपंचेंद्रियमुमक्कुं। अयोगिकेवलिगुणस्थानदोळु पर्य्याप्तपंचेंद्रियमेयक्कुं—

मि	सा	मि	अ	दे	प्र	अ	अ	अ	सू	उ	क्षी	स	अ
५	५	१	१	१	१ २	१	१	१	१	१	१	१	१

पृथ्वीकायादिविशिष्टैकेंद्रियजातिस्थावरनामकर्म्मोदयदिंदमुं त्रसनामकर्म्मोदयदिंदमुमाद जीवपर्य्यायक्के कायव्यपदेशमक्कुमा कायमुं पृथ्विकायिकमुमप्कायिकमुं तेजस्कायिकमुं वातकायिकमुं वनस्पतिकायिकमुमेंबुं त्रसकायिकमेंदितु षड्भेदमक्कुं। मिथ्यादृष्टिगुणस्थानदोळु पर्य्याप्तापर्य्याप्त षड्जीवनिकायमक्कुं। सासादनगुणस्थानदोळु बादरपृथ्व्यप्वनस्पत्यपर्य्याप्तकायिकंगळं द्वित्रिचतुः पंचेंद्रियासंज्ञि अपर्य्याप्तत्रसकायिकंगळु संज्ञिपंचेंद्रियपर्य्याप्तापर्य्याप्तत्रसकायिकंगळुमितु षड्जीव-

एकेन्द्रियादिजातिनामोदयजनितजीवपर्यायः इन्द्रियं, तन्मार्गणाः एकेन्द्रियादयः पञ्च। ताः मिथ्यादृष्टौ पर्याप्तापर्याप्ताः पञ्च। सासादने अपर्याप्ताः पञ्च पर्याप्तपञ्चेन्द्रियश्च। मिश्रे पर्याप्तपञ्चेन्द्रिय एव। असंयते उभयः। देशसंयते पर्याप्तः। प्रमत्ते पर्याप्तः। साहारकर्धिस्तूभयः। अप्रमत्तादिक्षीणकषायान्तेषु पर्याप्त एव। सयोगे पर्याप्तः। समुद्घाते तूभयः। अयोगे पर्याप्त एव।

पृथ्वीकायादिविशिष्टैकेन्द्रियजातिस्थावरनामोदयत्रसनामोदयजाः षड्जीवपर्यायाः कायाः। ते मिथ्यादृष्टौ पर्याप्ता अपर्याप्ताश्च। सासादने बादरपृथ्व्यब्वनस्पतिस्थावरकायाः द्वित्रिचतुरिन्द्रियाऽसंज्ञित्रसकायास्च-

एकेन्द्रिय आदि जातिनामकर्मके उदयसे उत्पन्न हुई जीवकी पर्याय इन्द्रिय है। उसकी मार्गणा एकेन्द्रिय आदि पाँच हैं। वे पाँचों मिथ्यादृष्टि गुणस्थानमें पर्याप्त-अपर्याप्त होते हैं। सासादनमें अपर्याप्त तो पाँचों हैं पर्याप्त एक पंचेन्द्रिय ही है। मिश्रमें पर्याप्त पंचेन्द्रिय ही है। असंयतमें पंचेन्द्रिय पर्याप्त-अपर्याप्त दोनों है। देशसंयतमें पर्याप्त है। प्रमत्तमें पर्याप्त है आहारक ऋद्धिवाला दोनों है। अप्रमत्तसे लेकर क्षीणकषाय पर्यन्त पर्याप्त ही है। सयोगकेवलीमें पर्याप्त है किन्तु समुद्घातमें दोनों है। अयोगीमें पर्याप्त ही है।

पृथ्वीकाय आदि विशिष्ट एकेन्द्रियादि जाति और स्थावर नामकर्म तथा त्रसनामकर्मके उदयसे उत्पन्न हुई छह जीवपर्यायोंको काय कहते हैं। वे मिथ्यादृष्टिमें पर्याप्त और अपर्याप्त होते हैं। सासादनमें बादर पृथिवी जल और वनस्पति स्थावरकाय तथा दोइन्द्रिय,

मि । सा । मि । अ । दे । प्र । अ । अ । अ । सू । उ । क्षी । स । अ ।
२ २
१ । १ । १ । १ । १ । १ । १ । २ । २ । १ । १ । १ । १ । १ ।।।

चक्षुर्द्दर्शनावरणीयमचक्षुर्द्दर्शनावरणीयमवधिदर्शनावरणीयमेंबी मूरुं दर्शनावरणीयकर्म्म प्रकृतिगळ क्षयोपशमंगळिदं यथासंख्यमागि चक्षुर्द्दर्शनमुमचक्षुर्द्दर्शनमुमवधिदर्शनमुमेंब मूरुं दर्शनंगळप्पुवु। केवलदर्शनावरणीयकर्म्मप्रकृति निरवशेषक्षयदिदं क्षायिककेवलदर्शनमुमक्कुमिंतु दर्शनचतुष्टयमक्कुं। मिथ्यादृष्टिगुणस्थानमादियागि मिश्रगुणस्थानपर्य्यंतं प्रत्येकं चक्षुर्दर्शनमुमचक्षुर्दर्शनमुमेंबेरडुं दर्शनंगळक्कुं। मिश्रनोळु मते मिथ्यावधिदर्शनमुमक्कुमसंयतसम्यग्दृष्टिगुणस्थानं मोदल्गोंडु क्षीणकषायगुणस्थानपर्य्यंतमाद गुणस्थानंगळोळु प्रत्येकं चक्षुर्दर्शनमुमचक्षुर्द्दर्शनमुमवधिदर्शनमुमेंब मूरुं दर्शनमक्कुं। सयोगिभट्टारकरोळमयोगकेवलिभट्टारकरोळं गुणस्थानातीतसिद्धपरमेष्ठिगळोळं केवलदर्शनमक्कुं

मि । सा । मि । अ । दे । प्र । अ । अ । अ । सू । उ । क्षी । स । अ । सि
२ । २ । ३ । ३ । ३ । ३ । ३ । ३ । ३ । ३ । ३ । ३ । १ । १ । १

कषायोदयंगळिननुरंजिसल्पट्ट मनोवाक्काययोगप्रवृत्तियं लेश्येयेंबुदु मदशुभलेश्येयेंदु शुभलेश्येयेंदु द्विविधमक्कुमल्लि अशुभलेश्येयुं कृष्णनीलकपोतभेददिदं त्रिविधमक्कुं। शुभलेश्येयुं तेजः पद्मशुक्लभेददिदं त्रिविधमक्कुमिंतु षड्लेश्येगळप्पुवु।

मिथ्यादृष्टिगुणस्थानं मोदल्गोंडु असंयतसम्यग्दृष्टिगुणस्थानपर्य्यंतं नाल्कुं गुणस्थानंगळोळु प्रत्येकं षड्लेश्येगळप्पुवु। देशसंयतगुणस्थानं मोदल्गोंडु अप्रमत्तगुणस्थानपर्य्यंतं मूरुं गुणस्थानंगळोळु प्रत्येकं मूरु शुभलेश्येगळप्पुवु। अपूर्व्वकरणगुणस्थानमोदल्गोंडु सयोगिकेवलि भट्टारकरोळं

चक्षुरचक्षुरवधिदर्शनावरणीयक्षयोपशमैः केवलदर्शनावरणीयनिरवशेषक्षयेण तानि चत्वारि स्युः। तत्र मिश्रगुणस्थानान्तं चक्षुरचक्षुर्दर्शनद्वयम्। असंयतादिक्षीणकषायान्तं चक्षुरचक्षुरवधिदर्शनत्रयं। सयोगायोगयोः सिद्धे चैकं केवलदर्शनम्।

कषायोदयानुरञ्जितमनोवाक्कायप्रवृत्तिर्लेश्या सा च शुभाशुभभेदाद्द्वेधा। तत्र अशुभा कृष्णनीलकपोतभेदात् त्रेधा। शुभापि तेजःपद्मशुक्लभेदात्त्रेधा। असंयतान्तं षडपि। देशसंयतादित्रये शुभा त्रयः। अपूर्वकरणादिसयोगान्तं शुक्लैव। अयोगे योगाभावात् लेश्या नास्ति।

सामग्रीविशेषैः रत्नत्रयानन्तचतुष्टयस्वरूपेण परिणमितुं योग्यो भव्यः। तद्विपरीतोऽभव्यः। ईद

चक्षु-अचक्षु और अवधिदर्शनावरणोंके क्षयोपशमसे तथा केवल दर्शनावरणके क्षयसे चारों दर्शन होते हैं। उनमें-से मिश्र गुणस्थान पर्यन्त चक्षु और अचक्षु दर्शन होते हैं। असंयतसे क्षीणकषायपर्यन्त चक्षु, अचक्षु, अवधि तीन दर्शन होते हैं। सयोग, अयोग और सिद्धोंमें एक केवलदर्शन होता है। कषायके उदयसे अनुरंजित मन-वचन-कायकी प्रवृत्ति लेश्या है। वह शुभ और अशुभके भेदसे दो प्रकार है। उनमें-से अशुभ कृष्ण, नील, कापोतके भेदसे तीन प्रकार है। शुभ भी तेज, पद्म, शुक्लके भेदसे तीन प्रकार है। असंयत पर्यन्त छहों लेश्या होती हैं। देशसंयत आदि तीन गुणस्थानोंमें शुभलेश्या ही होती है। अपूर्वकरणसे सयोगी पर्यन्त शुक्ललेश्या ही होती है। अयोगीमें योगका अभाव होनेसे लेश्या नहीं है। सामग्री विशेषके द्वारा रत्नत्रय और अनन्तचतुष्टयस्वरूपसे परिणमन करनेके जो योग्य

मिथ्यात्वमिश्रसम्यक्त्वप्रकृतिरूपदिंदमसंख्यातगुणहीनक्रमदिंदमंतर्मुहूर्त्तकालं विभजिसि माळ्कुं। मिथ्यात्वमं मिथ्यात्वमागिये माळ्कुमें दोडे पूर्व्वस्थितियोळ अतिस्थापनावलिमात्र-स्थितिह्रासमं माळ्कुमें बुदर्त्थं अनंतरमा प्रथमोपशमसम्यक्त्वकालदोळु अप्रमत्तंगे प्रमत्ताप्रमत्त-परावृत्तिसंख्यातसहस्रंगळप्पुवप्पुदरिंद प्रमत्तगुणस्थानदोळं प्रथमोपशमसम्यक्त्वमक्कुमदरिनप्रम-त्ता नाल्कुं गुणस्थानत्रितयमोपशमसम्यक्त्वदोळु तत्सम्यक्त्वकालमंतर्मुहूर्त्तदोळु जघन्यदिंदमेक-समयमवशेषमागुत्तिरलुत्कृष्टदिंदमावलिषट्कमवशेषमागुत्तिरलनंतानुबंधिकषायंगळोळन्यतमोदयदिंदं सासादनरप्प-रक्कुं। जघन्यदिंदेकसमयमक्कुं। मध्यमसंख्यातविकल्पमक्कुं। मत्तमा भव्यतागुणविशेषदिंदं सम्यक्त्वविराधनेयिल्लदिर्दोडे तद्गुणस्थानस्थानकालं संपूर्णमागुत्तिरलु सम्यक्त्वप्रकृत्युदयदिंदं वेदकसम्यग्दृष्टिगळप्पर नाल्कुं गुणस्थानवर्त्तिगळप्पर। अथवा मिश्रप्रकृत्युदयदिंदमा नाल्वर मिश्र-रप्पर। मिथ्यात्वकर्म्मोदयमागुत्तिरला नाल्कुं गुणस्थानवर्त्तिगळु मिथ्यादृष्टिगळप्पर। द्वितीयोपशम-सम्यक्त्वमेंतेंदोडे विशेषमुंटदावुदें दोडे उपशमश्रेण्यारोहणार्त्थं सातिशयाप्रमत्तगुणस्थानवर्त्तिवेदक-सम्यग्दृष्टि करणत्रयपरिणामसामर्त्थ्यदिंदमनंतानुबंधिगळं प्रशस्तोपशमविधानदिंद-प्रशस्तोपशमदिंदमप्रशस्तोपशमविसंयोजनमनुत्कृष्टिसियें विवक्षितमल्ते केलवर्गे दर्शनमोहत्रयक्कंतर करण-दिंदमंतरमं माडि उपशमविधानदिंदमुपशमिसि अनंतरप्रथमसमयदोळु द्वितीयोपशमसम्यक्त्वं स्वीकरिसि उपशमश्रेणियं क्रमदिनेय्दि मेलुपशांतकषायगुणस्थानदोळंतर्मुहूर्त्तकालमिद्दिळिदु क्रमदिंदमिळिदु अप्रमत्तगुणस्थानमं पोर्द्दि मत्तमा प्रमत्ताप्रमत्तपरावृत्तिसहस्रंगळं द्वितीयोपश-

---

गुणस्थानं च अप्रमत्तसंयतो भवति। ते त्रयोऽपि तत्प्राप्तिप्रथमसमयात् प्रभृति गुणसंक्रमणविधानेन मिथ्यात्व-द्रव्यं गुणसंक्रमणभागहारेण अपकृष्यापकृष्य मिथ्यात्वमिश्रसम्यक्त्वप्रकृतिरूपेण असंख्यातगुणहीनक्रमेण अन्तर्मुहूर्तं कालं त्रिधा कुर्वन्ति। मिथ्यात्वस्य मिथ्यात्वकरणं तु पूर्वस्थितौ अतिस्थापनावलिमात्रमूनयतीत्यर्थः। तदप्रमत्तस्य प्रमत्ताप्रमत्तपरावृत्तिसंख्यातसहस्रसंभवात् प्रमत्तेऽपि तत् सम्यक्त्वं स्यात्। ते अप्रमत्तवर्जं त्रय एव तत्सम्यक्त्वकालान्तर्मुहूर्ते जघन्येन एकसमये उत्कृष्टेन च षडावलिमात्रेऽवशिष्टे अनन्तानुबन्ध्यन्यत-मोदये सासादना भवन्ति। अथवा ते चत्वारोऽपि यदि भव्यतागुणविशेषेण सम्यक्त्वविराधका न स्युः तदा तत्काले संपूर्णे जाते सम्यक्त्वप्रकृत्युदये वेदकसम्यग्दृष्टयः वा मिश्रप्रकृत्युदये सम्यग्मिथ्यादृष्टयः वा मिथ्यात्वोदये

प्रथमोपशमसम्यक्त्व और महाव्रतोंको एक साथ प्राप्त करके अप्रमत्तसंयत होता है। वे तीनों भी उसकी प्राप्तिके प्रथम समयसे लेकर गुणसंक्रमण विधानके द्वारा मिथ्यात्वके द्रव्यको गुणसंक्रमण भागहारके द्वारा घटा-घटाकर मिथ्यात्व मिश्र और सम्यक्त्व प्रकृतिरूपसे अन्तर्मुहूर्तकाल तक तीन रूप करता है। इनका द्रव्य उत्तरोत्तर असंख्यातगुणा हीन होता है। जो मिथ्यात्वका मिथ्यात्वकरण तो पूर्वस्थितिमें अतिस्थापनावली मात्र कम करता है। जो अप्रमत्तमें जाता है वह अप्रमत्तसे प्रमत्तमें और प्रमत्तसे अप्रमत्तमें संख्यात हजार बार आता-जाता है अतः प्रमत्तमें भी प्रथमोपशम सम्यक्त्व होता है। अप्रमत्तसंयतके बिना शेष तीनों ही प्रथमोपशम सम्यक्त्वके अन्तर्मुहूर्त कालमें जघन्यसे एक समय उत्कृष्टसे छह आवली काल शेष रहनेपर अनन्तानुबन्धी क्रोध-मान-माया-लोभमें-से किसी भी एकका उदय होनेपर सासादन होते हैं। अथवा वे चारों भी यदि भव्यत्वगुणकी विशेषतासे सम्यक्त्वकी विराधना नहीं करते तो उस सम्यक्त्व काल पूर्ण होनेपर सम्यक्त्व प्रकृतिके उदयमें वेदक सम्यग्दृष्टि हो जाते हैं या मिश्र प्रकृतिके उदय होनेपर सम्यक्मिथ्यादृष्टि होते हैं अथवा

अपूर्व्वकरणगुणस्थानं मोदलागि सिद्धपरमेष्ठिगळ्पर्य्यंतं क्षायिकसम्यक्त्वमक्कुं :—

मि	सा	मि	अ	दे	प्र	अ	अ	अ	सू	उ	क्षी	स	अ	सि
१	१	१	३	३	३	३	१	१	१	२	१	१	१	१

नो इंद्रियावरणक्षयोपशममुतज्जनितबोधनमुं संज्ञेयें बुदक्कुं अदनुळ्ळुदसंज्ञि एंबुदक्कुमितरेंद्रियज्ञानमनुळ्ळवसंज्ञियें बुदक्कुमितु संज्ञियुमसंज्ञियुमें बेरडु प्रकारद जीवंगळोळु संज्ञिजीवं मिथ्यादृष्टिगुणस्थानं मोदल्गोंडु क्षीणकषायगुणस्थानपर्य्यंतं पन्नेरडु गुणस्थानंगळोळक्कुं। असंज्ञिजीवं मिथ्यादृष्टिगुणस्थानदोळेयक्कुं । सयोगिकेवलिभट्टारकरुमयोगिकेवलिभट्टारकरु नोइंद्रियेंद्रियज्ञानरहितरप्पुदरिदं संज्ञिगळुमसंज्ञिगळुमल्तु :—

मि	सा	मि	अ	दे	प्र	अ	अ	अ	सू	उ	क्षी
२	१	१	१	१	१	१	१	१	१	१	१

शरीरांगोपांगनामकर्मोदयजनितशरीरवचनचित्तनोकर्म्मवर्ग्गणाग्रहणमाहारमें बुदक्कुं। विग्रहगतियोळु समुद्घातकेवलिगुणस्थानदोळमयोगिकेवलिगुणस्थानदोळं सिद्धपरमेष्ठिगळोळं शरीरांगोपांगनामकर्मोदयमिल्लप्पुदरिदं "कारणाभावे कार्य्यस्याप्यभावः एंबी न्यायदिदमनाहारमक्कुमिताहारानाहारमुं मिथ्यादृष्टिगुणस्थानदोळेरडुमक्कुं। सासादनगुणस्थानदोळमसंयतसम्यग्दृष्टिगुणस्थानदोळं सयोगकेवलिभट्टारकगुणस्थानदोळमाहारानाहारमेरडुमक्कु मुळिद मिश्रगुणस्थानं मोदलागि ओंभत्तु

च कर्मभूमिवेदकसम्यग्दृष्टीनामेव केवलिश्रुतकेवलिद्वयश्रीपादोपान्ते सप्तप्रकृतिनिरवशेषक्षये भवति। तत्सम्यक्त्वं सामान्येन एकं, विशेषेण मिथ्यात्वसासादनमिश्रोपशमवेदकक्षायिकभेदात् षोढा। तत्र मिथ्यादृष्टौ मिथ्यात्वं। सासादने सासादनत्वम्। मिश्रे मिश्रत्वं। असंयतादि अप्रमत्तान्तेषु उपशमवेदकक्षायिकाणि अपूर्वकरणाद्युपशान्तकषायान्तेषु उपशमश्रेण्यां औपशमिकक्षायिके क्षपकश्रेण्यामपूर्वकरणादिसिद्धपर्यन्तमेकं क्षायिकमेव।

नोइन्द्रियावरणक्षयोपशमः तज्जनितबोधनं च संज्ञा सा अस्य अस्तीति संज्ञी। इतरेन्द्रियज्ञानोऽसंज्ञी। तत्र मिथ्यादृष्ट्यादिक्षीणकषायान्तं संज्ञी। असंज्ञी मिथ्यादृष्टावेव। सयोगायोगयोर्नोइन्द्रियेन्द्रियज्ञानाभावात् संज्ञ्यसंज्ञिव्यपदेशो नास्ति।

शरीराङ्गोपाङ्गनामोदयजनितं शरीरवचनचित्तनोकर्मवर्गणाग्रहणमाहारः। विग्रहगतौ प्रतरलोकपूरण

हो जाता है। क्षायिक सम्यक्त्व तो असंयत आदि चार गुणस्थानवर्ती मनुष्योंके असंयत देशसंयत या औपचारिक महाव्रती मानुषियोंके जो कर्मभूमिके जन्मा वेदक सम्यग्दृष्टि होते हैं उनके ही केवली श्रुतकेवलीके चरणोंके समीपमें सात प्रकृतियोंका पूर्ण क्षय होनेपर होता है। वह सम्यक्त्व सामान्यसे एक है। विशेष मिथ्यात्व, सासादन, मिश्र, उपशम, वेदक और क्षायिकके भेदसे छह भेदरूप है। मिथ्यादृष्टिमें मिथ्यात्व होता है। सासादनमें सासादन और मिश्रमें मिश्र होता है। असंयतसे अप्रमत्तपर्यन्त उपशम, वेदक और क्षायिक सम्यक्त्व होते हैं। अपूर्वकरणसे उपशान्त कषाय पर्यन्त उपशमश्रेणीमें औपशमिक और क्षायिक होते हैं। क्षपकश्रेणीमें अपूर्वकरणसे लेकर तथा सिद्ध पर्यन्त क्षायिक ही होता है।

नोइन्द्रियावरणके क्षयोपशम और उससे होनेवाले ज्ञानको संज्ञा कहते हैं। वह जिसके हो वह संज्ञी है। जो मनके सिवाय अन्य इन्द्रियोंसे ही जानता है वह असंज्ञी है। मिथ्यादृष्टिसे लेकर क्षीणकषाय पर्यन्त संज्ञी होता है। असंज्ञी मिथ्यादृष्टि गुणस्थानमें ही होता है। सयोगी और अयोगी मनसे नहीं जानते इससे न वह संज्ञी कहे जाते हैं और न असंज्ञी।

१. ब °स्यकार्यं भवेत् ।

गुणस्थानदोळु मतिश्रुतावधिज्ञानंगळुं चक्षुरचक्षुरवधिदर्शनंगळुमितारुमुपयोगंगळप्पुवु। देशसंयतगुणस्थानदोळमसंयतंगे पेळ्वंतारुमुपयोगंगळप्पुवु। प्रमत्तगुणस्थानदोळु मतिश्रुतावधिमनःपर्ययज्ञानंगळुं चक्षुरचक्षुरवधिदर्शनमुमितुपयोगसप्तकमुमक्कुमंते अप्रमत्तगुणस्थानादिक्षीणकषायपर्य्यंतं प्रत्येकमुपयोगसप्तकमक्कुं। सयोगिकेवलिभट्टारकगुणस्थानदोळु मयोगिकेवलिभट्टारकगुणस्थानदोळं सिद्धपरमेष्ठिगळोळं केवलज्ञानोपयोगमुं केवलदर्शनोपयोगमुमेरडुं युगपत्संभविसुगुं :—

मि	सा	मि	अ	दे	प्र	अ	अ	अ	सू	उ	क्षी	स	अ	सि
५	५	६	६	६	७	७	७	७	७	७	७	२	२	२

इंतु भगवदर्हत्परमेस्वरचारुचरणारविंदद्वंद्ववंदनानंदितपुण्यपुंजायमानश्रीमद्रायराजगुरुमंडलाचार्य्यमहावादवादीश्वररायवादिपितामहसकलविद्वज्जनचक्रवर्त्तिश्रीमदभयसूरिसिद्धांतचक्रवर्तिश्रीपादपंकजरजोरंजितललाटपट्टं श्रीमत्केशवण्णविरचितमप्प गोम्मटसारकर्णाटकवृत्तिजीवतत्वप्रदीपिकेयोळु ओघादेशंगळोळु विंशतिप्ररूपणाधिकारं प्ररूपितमाय्तु॥

केवलदर्शनभेदाच्चतुर्धा। तत्र मिथ्यादृष्टिसासादनयोः कुमतिकुश्रुतविभंगज्ञानचक्षुरचक्षुर्दर्शनाख्याः पञ्च। मिश्रे मतिश्रुतावधिज्ञानचक्षुरचक्षुरवधिदर्शनाख्याः मिश्राः षट्। असंयतदेशसंयतयोः त एव षड्मिश्राः। प्रमत्तादिक्षीणकषायान्तेषु त एव मनःपर्ययेण सह सप्त। सयोगे अयोगे सिद्धे च केवलज्ञानदर्शनाख्यौ द्वौ॥७०५॥

इत्याचार्यश्रीनेमिचन्द्रसिद्धान्तचक्रवर्तिविरचितायां गोम्मटसारापरनामपञ्चसंग्रहवृत्तौ जीवतत्त्वप्रदीपिकाख्यायां जीवकाण्डे विंशतिप्ररूपणासु ओघादेशयोर्विंशतिप्ररूपणानिरूपणानामैकविंशोऽधिकारः॥२१॥

हैं क्योंकि वे ज्ञेय हैं जैसे अन्धकार ज्ञानका कारण नहीं है। वह उपयोग ज्ञान और दर्शनके भेदसे दो प्रकार है। उनमें ज्ञानोपयोग कुमति, कुश्रुत, विभंग, मति, श्रुत, अवधि, मनःपर्यय और केवलज्ञानके भेदसे आठ प्रकारका है। दर्शनोपयोग चक्षु, अचक्षु, अवधि और केवलदर्शनके भेदसे चार प्रकारका है। मिथ्यादृष्टि और सासादनमें कुमति, कुश्रुत, विभंगज्ञान और चक्षुदर्शन, अचक्षुदर्शन ये पाँच उपयोग होते हैं। मिश्र गुणस्थानमें, मति, श्रुत, अवधिज्ञान और चक्षु, अचक्षु अवधिदर्शन ये छह मिले हुए सम्यक्‌मिथ्यात्वरूप होते हैं। असंयत और देशसंयतमें वे ही छह उपयोग सम्यक्‌रूप होते हैं। प्रमत्तसे क्षीणकषाय पर्यन्त वे ही मनःपर्ययके साथ मिलकर सात उपयोग होते हैं। सयोगी अयोगी, और सिद्धोंमें केवलज्ञान और केवलदर्शन दो उपयोग होते हैं॥७०५॥

इस प्रकार आचार्य श्री नेमिचन्द्र विरचित गोम्मटसार अपर नाम पंचसंग्रहकी भगवान् अर्हन्त देव परमेश्वरके सुन्दर चरणकमलोंकी वन्दनासे प्राप्त पुण्यके पुंजस्वरूप राजगुरु मण्डलाचार्य महावादी श्री अभयनन्दी सिद्धान्त चक्रवर्तीके चरणकमलोंकी धूलिसे शोभित ललाटवाले श्री केशववर्णीके द्वारा रचित गोम्मटसार कर्णाटवृत्ति जीवतत्त्व प्रदीपिकाकी अनुसारिणी संस्कृतटीका तथा उसकी अनुसारिणी पं. टोडरमलरचित सम्यग्ज्ञानचन्द्रिका नामक भाषाटीकाकी अनुसारिणी हिन्दी भाषा टीकामें जीवकाण्डकी बीस प्ररूपणाओंमें-से ओघादेशमार्गणा प्ररूपणा नामक इक्कीसवाँ अधिकार सम्पूर्ण हुआ॥२१॥

ओघे चोद्दसठाणे सिद्धे वीसदिविहाणमालावा ।
वेदकसायविभिण्णे अणियट्टीपंचभागे य ॥७०७॥

ओघे चतुर्दशस्थाने सिद्धे विंशतिविधानमालापाः । वेदकषायविभिन्नेऽनिवृत्तिपंचभागेषु च ॥

गुणस्थानदोळं चतुर्दशमार्ग्गणास्थानदोळं प्रसिद्धवोळु विंशतिविधंगळप्प गुणजीवेत्यादिगळ्गे सामान्यं पर्य्याप्तमपर्य्याप्तमें ब मूरुतेरदाळापंगळप्पुवु। वेदकषायंगळिदं भेदमनुळ्ळ अनिवृत्तिकरणगुणस्थानपंचभागेगळोळं पृथगाळापंगळप्पुवेकें दोडे अनिवृत्तिकरणपंचभागेगळोळु सवेदावेदादि विशेषंगळुंटप्पुदरिदं।

अनंतरं गुणस्थानंगळोळु आळापमं पेळ्दपं :—

ओघेमिच्छदुगेवि य अयदपमत्ते सजोगठाणम्मि ।
तिण्णेव य आलावा ससेसिक्को हवे णियमा ॥७०८॥

ओघे मिथ्यादृष्टिद्विकेपि च असंयते प्रमत्ते सयोगस्थाने। त्रय एवाळापाः शेषेष्वेको भवेन्नियमात् ॥

गुणस्थानंगळोळु मिथ्यादृष्टिसासादनसम्यग्दृष्टिगुणस्थानद्वयदोळं असंयतसम्यग्दृष्टिगुणस्थानदोळं प्रमत्तसंयतगुणस्थानदोळं सयोगकेवलिभट्टारकगुणस्थानदोळं प्रत्येकं सामान्यं पर्य्याप्तं पर्य्याप्तमें ब मूरु माळापंगळप्पुवु। शेषनवगुणस्थानंगळोळु पर्य्याप्ताळापमो देयक्कुं :—

मि	सा	मि	अ	दे	प्र	अ	अ	अ	सू	उ	क्षी	स	अ
३	३	१	३	१	१	१	१	१	१	१	१	३	१

अनंतरमोयर्त्थमने विशदं माडिदपं :—

गुणस्थाने चतुर्दशमार्गणास्थाने च प्रसिद्धे विंशतिविधानां गुणजीवेत्यादीनां सामान्यपर्याप्तापर्याप्तास्त्रय आलापा भवन्ति। तथा वेदकषायविभिन्नेषु अनिवृत्तिकरणपञ्चभागेषु अपि पृथक्पृथग्भवन्ति ॥७०७॥ गुणस्थानेष्वाह—

गुणस्थानेषु मिथ्यादृष्टिसासादनयोः असंयते प्रमत्ते सयोगे च प्रत्येकं त्रयोऽपि आलापा भवन्ति। शेषनवगुणस्थानेषु एकः पर्याप्तालाप एव नियमेन ॥७०८॥ अमुमेवार्थं विशदयति—

प्रसिद्ध गुणस्थान और चौदह मार्गणास्थानमें 'गुणजीवा' इत्यादि बीस प्ररूपणाओंके सामान्य, पर्याप्त, अपर्याप्त ये तीन आलाप होते हैं। तथा वेद और कषायसे भेदरूप अनिवृत्तिकरणके पाँच भागोंमें भी आलाप पृथक्-पृथक् होते हैं ॥७०७॥

गुणस्थानोंमें आलाप कहते हैं—

गुणस्थानोंमें-से मिथ्यादृष्टि, सासादन, असंयत, प्रमत्त और सयोगीमें-से प्रत्येकमें तीनों ही आलाप होते हैं, शेष नौ गुणस्थानोंमें एक पर्याप्त आलाप ही नियमसे होता है ॥७०८॥

---

१० १. म केवेवेक्को।

सत्तण्हं पुढवीणं ओघेमिच्छे य तिण्णि आलावा ।
पढमाविरदेवि तहा सेसाणं पुण्णमालाओ ॥७१२॥

सप्तानां पृथ्वीनामोघे सामान्ये मिथ्यादृष्टौ च त्रय आलापाः । प्रथमाविरतेऽपि तथा शेषाणां पूर्णालापः ॥

सामान्यदिदं सप्तपृथ्विगळ साधारणमिथ्यादृष्टियोळु मूरुमाळापंगळप्पुवु । प्रथमपृथ्विय अविरतसम्यग्दृष्टियोळमंते मूराळापंगळप्पुवेकें दोडे प्रथमनरकमं बद्धायुष्यनप्प वेदकसम्यग्दृष्टियुं क्षायिकसम्यग्दृष्टियुं पुगुगुमप्पुदरिदं शेषंगळ प्रथमपृथ्विय सासादनमिश्रंगळं द्वितीयादि पृथ्विगळ सासादनमिश्रासंयतंगळुं पर्य्याप्ताळापमो देयक्कुं । उळिदार्र नरकंगळोळु सम्यग्दृष्टि पुगनेंदुदत्यं ।

तिरियचउक्काणोघे मिच्छदुगे अविरदे य तिण्णेव ।
णवरि य जोणिणि अयदे पुण्णो सेसेवि पुण्णो दु ॥७१३॥

तिरश्चां चतुर्णामोघे मिथ्यादृष्टिद्विके अविरते च त्रय एव । विशेषोऽस्ति योनिमत्यसंयते पूर्णः शेषेपि पूर्णस्तु ॥

तिर्य्यग्गतियोळु पंचगुणस्थानंगळोळु सामान्यतिर्य्यंचरुगळगं पंचेंद्रियतिर्य्यंचरुगळगं पर्य्याप्त-तिर्य्यंचरुगळगं योनिमतितिर्य्यंचरुगळ्गमितु नाल्कुं तेरद तिर्य्यंचरुगळगे साधारणदिदं मिथ्यादृष्टि-गुणस्थानदोळं सासादनगुणस्थानदोळमसंयतसम्यग्दृष्टिगुणस्थानदोळं प्रत्येकं मूरुमाळापंगळप्पुवल्लि विशेषमुंटदावुदें दोडे योनिमतियसंयतगुणस्थानदोळु पर्य्याप्ताळापमेयक्कुमेकें दोडे बद्धतिर्य्यगायुष्य-रप्प सम्यग्दृष्टिगळु योनिमतिगळुं षंढरुमागि पुट्टदरप्पुदरिदं शेषमिश्रदेशसंयतगुणस्थानद्वयदोळु पर्य्याप्ताळापमेयक्कुं :—

नरकगतौ सामान्येन सप्तपृथ्वीमिथ्यादृष्टौ त्रयः आलापाः स्युः । तथा प्रथमपृथ्व्यविरतेऽपि त्रय आलापाः स्युः । बद्धनरकायुर्वेदकक्षायिकसम्यग्दृष्ट्योस्तत्रोत्पत्तिसंभवात् शेषपृथ्व्यविरतानामेकः पर्याप्तालाप एव सम्यग्दृष्टेस्तत्रानुत्पत्तेः ॥७१२॥

तिर्यग्गतौ पञ्चगुणस्थानेषु सामान्यपञ्चेन्द्रियपर्याप्तयोनिमत्तिरश्चां चतुर्णां साधारणेन मिथ्यादृष्टि-सासादनासंयतेषु प्रत्येकं त्रय आलापा भवन्ति । तत्रायं विशेषः—योनिमदसंयते पर्याप्तालाप एव । बद्धायुष्यापि सम्यग्दृष्टेः स्त्रीषण्ढयोरनुत्पत्तेः । तु—पुनः शेषमिश्रदेशसंयतयोरपि पर्याप्तालाप एव ॥७१३॥

नरकगतिमें सामान्यसे सातों पृथ्वीके मिथ्यादृष्टिमें तीनों आलाप होते हैं। तथा प्रथम पृथ्वीमें अविरतमें भी तीनों आलाप होते हैं क्योंकि जिन्होंने पहले नरकायुका बन्ध किया है वे वेदक सम्यग्दृष्टि और क्षायिक सम्यग्दृष्टि प्रथम नरकमें ही उत्पन्न होते हैं। शेष पृथिवियोंमें अविरतोंके एक पर्याप्त आलाप ही होता है क्योंकि सम्यग्दृष्टि मरकर उनमें जन्म नहीं लेता ॥७१२॥

तिर्यंचगतिमें पाँच गुणस्थानोंमें सामान्यतिर्यंच, पंचेन्द्रियतिर्यंच, पर्याप्ततिर्यंच और योनिमतीतिर्यंच इन चारोंके सामान्यसे मिथ्यादृष्टि, सासादन और असंयत गुणस्थानोंमेंसे प्रत्येकमें तीन आलाप होते हैं। किन्तु इतना विशेष है कि असंयतमें योनिमतीतिर्यंचके पर्याप्त आलाप ही होता है; क्योंकि जिसने परभवकी आयुका बन्ध किया है वह सम्यग्दृष्टि

सर्व्वदेवसामान्यदोळु नाल्कुं गुणस्थानमक्कुमल्लि मिथ्यादृष्टिगुणस्थानदोळं सासादनगुणस्थानदोळं असंयतसम्यग्दृष्टिगुणस्थानदोळं सामान्यालापमुं पर्य्याप्तालापमपर्य्याप्तालापमुमेंब मूरुमालापंगळप्पुवु । अल्लि विशेषमुंटदावुदें दोडे भवनत्रयदेवक्कळं कल्पवासिस्त्रीयरुगळं असंयतगुणस्थानदोळु पर्य्याप्तालापमोंदेयक्कुमेकें दोडे तिर्य्यग्मनुष्यासंयतसम्यग्दृष्टिगळु भवनत्रयदोळं कल्पामरस्त्रीयरागि पुट्टरप्पुदरिदं ॥

मिस्से पुण्णालावो अणुदिसाणुत्तरा हु ते सम्मा ।
अविरदतिण्णालावा अणुदिसाणुत्तरे होंति ॥७१८॥

मिश्रे पूर्णालापः अनुदिशानुत्तराः खलु ते सम्यग्दृष्टयः । असंयतत्रितयालापाः अनुदिशानुत्तरे भवंति ॥

मुंपेळ्द नवग्रैवेयकावसानमाद सामान्यदेवर्कळ मिश्रगुणस्थानदोळु पर्य्याप्तालापमोंदेयक्कुं । अनुदिशानुत्तरविमानंगळहमिंदरेल्लरुं स्फुटमागयरुगळु सम्यग्दृष्टिगळेयप्पुदरिदमसंयतसम्यग्दृष्टिगुणस्थानदोळप्प सामान्यालापमुं पर्य्याप्तालापमुं निर्वृत्त्यपर्य्याप्तालापमुमेंब मूरु मालापंगळु अनुदिशानुत्तरविमानवासिगळोळप्पुवु ।

अनंतरमिंद्रियमार्ग्गणेयोळालापमं पेळ्दपं :—

बादरसुहुमेइंदियबितिचतुरिंदिय असण्णिजीवाणं ।
ओघे पुण्णे तिण्णि य अपुण्णगे पुण अपुण्णो दु ॥७१९॥

बादरसूक्ष्मैकेंद्रियद्वित्रिचतुरिंद्रियासंज्ञिजीवानामोघे पूर्णे त्रयश्चापूर्णे पुनरपूर्णस्तु ॥

बादरैकेंद्रिय सूक्ष्मैकेंद्रियद्वींद्रियत्रींद्रियचतुरिंद्रियासंज्ञिपंचेंद्रियजीवंगळ सामान्यदोळु सामान्यपर्य्याप्तापर्य्याप्तालापमें ब मूरुमालापंगळप्पुवु । पर्य्याप्तनामकर्मोदयविशिष्टजीवंगळोळमा मूरुमालापमप्पुवु । अपर्य्याप्तनामकर्म्मोदयविशिष्टजीवंगळोळु लब्ध्यपर्य्याप्तालापमोंदेयक्कुं ।

देवसामान्ये चतुर्गुणस्थानेषु मिथ्यादृष्टिसासादनयोः असंयते च त्रय आलापा भवन्ति । अयं विशेषः भवनत्रयदेवाः कल्पस्त्रीयश्च असंयते पर्याप्तालाप एव तिर्यग्मनुष्यासंयतानां तत्रोत्पत्त्यभावात् ॥७१७॥

नवग्रैवेयकावसानसामान्यदेवानां मिश्रगुणस्थाने एकः पर्याप्तालाप एव अनुदिशानुत्तरविमानाहमिन्द्राः सर्वे [illegible] सम्यग्दृष्टय एव तेन असंयते त्रय आलापा भवन्ति ॥७१८॥ अथेन्द्रियमार्गणायामाह—

[illegible] बादरसूक्ष्मैकेन्द्रियद्वित्रिचतुरिन्द्रियासंज्ञिजीवसामान्ये पर्याप्तनामोदयविशिष्टे त्रय आलापा भवन्ति । अपर्याप्तनामोदयविशिष्टे पुनः एको लब्ध्यपर्याप्तालाप एव ॥७१९॥

सब सामान्य देवोंमें चार गुणस्थानोंमें-से मिथ्यादृष्टि, सासादन और असंयतमें तीन आलाप होते हैं। इतना विशेष है कि भवनत्रिकके देवोंके और कल्पवासी देवांगनाओंके असंयतमें पर्याप्त आलाप ही होता है क्योंकि सम्यग्दृष्टि तिर्यंच और मनुष्य उनमें उत्पन्न नहीं होते ॥७१७॥

नौ ग्रैवेयक पर्यन्त सामान्य देवोंके मिश्र गुणस्थानमें एक पर्याप्त आलाप होता है। अनुदिश और अनुत्तर विमानवासी अहमिन्द्र सब सम्यग्दृष्टि ही होते हैं अतः असंयतमें तीन आलाप होते हैं ॥७१८॥

बादर एकेन्द्रिय, सूक्ष्म एकेन्द्रिय, दोइन्द्रिय, तेइन्द्रिय, चौइन्द्रिय और असंज्ञी पंचेन्द्रिय [illegible] पर्याप्त नामकर्मके उदयसे युक्त होते हैं उनके तीन आलाप होते हैं। और [illegible] अपर्याप्त नामकर्मके उदयसे युक्त हैं उनके एक लब्ध्यपर्याप्त आलाप ही होता है ॥७१९॥

पृथ्विकायिकदोळमप्कायिकदोळं तेजस्कायिकदोळं वायुकायिकदोळं नित्यनिगोदजीवंगळोळं चतुर्गतिनिगोदजीवंगळोळं इवर बादरसूक्ष्मभेदंगळोळं प्रत्येकवनस्पतियोळं तद्द्विभेदमप्प प्रतिष्ठितप्रत्येकदोळं अप्रतिष्ठितप्रत्येकदोळं ओघदोळु साधारणालापत्रयमक्कुं। त्रस जीवंगळ सामान्यदोळु गुणस्थानंगळप्पविनाल्कप्पुवल्लि मिथ्यादृष्टयादिगुणस्थानंगळोळु गुणस्थानदोळ्पेळ्दंते आलापंगळप्पुवु। विशेषमिल्ल। पृथ्विकायिकादित्रसकायिकजीवपर्य्यंतमाद लब्ध्यपर्य्याप्तरोळु लब्धिअपर्य्याप्तालापमो देयक्कुं।

अनंतरं योगमार्ग्गणेयोळु आलापमं पेळ्दपं :—

एक्कारसजोगाणं पुण्णगदाणं सपुण्ण आलाओ।
मिस्सचउक्कस्स पुणो सगएक्क अपुण्ण आलाओ ॥७२३॥

एकादशयोगानां पूर्णगतानां स्वपूर्णालापः। मिश्रचतुष्कस्य पुनः स्वकैकोऽपूर्णः आलापः॥

पर्य्याप्तिगे संद मनोवाग्योगंगळेंटुं औदारिकवैक्रियिकाहारकंगळेंब मूरुमितु पन्नोंदु योगंगळगे स्वस्वपूर्णालापमो दो देयक्कुमदें तें दोडे सत्यासत्योभयानुभयमनः पर्य्याप्तालापमुं सत्यासत्योभयानुभयभाषापर्य्याप्तालापमुं औदारिकवैक्रियिकाहारकशरीरपर्य्याप्तालापमुं तंतम्म वोंदोंदेयागि पन्नोंदुयोगंगळोळु पन्नोंदे पर्य्याप्तालापमप्पुवें दुदत्थं। मिश्रचतुष्कयोगक्के मत्ते स्वस्वापर्य्याप्तालापमोंदोंदेयक्कुमौदारिकापर्य्याप्तवैक्रियिकापर्य्याप्तआहारकापर्य्याप्त कार्म्मकायापर्य्याप्तमें बालापचतुष्टयं यथासंख्यमागोंदोंदे पेळल्पडुवुवेंबुदत्थं॥

अनंतरं वेद मार्ग्गणादियाहारमार्ग्गणापर्य्यंतमाद पत्तुं मार्ग्गणेगळोळालापक्रमं तोरिदपं॥

वेदादाहारोत्ति य सगुणट्ठाणाणमोघ आलाओ।
णवरि य संढित्थीणं णत्थि हु आहारगाण दुगं ॥७२४॥

वेदाहारपर्य्यंतं च स्वगुणस्थानानामोघ आलापः। नवमस्ति च पंढस्त्रीणां नास्त्याहारकयोर्द्विकं॥

वेदमार्ग्गणेमोदल्गोंडु आहारमार्ग्गणेपर्य्यंतमाद पत्तुं मार्ग्गणेगळोळु तंतम्ममार्ग्गणेगळु गुणस्थानंगळगे सामान्यदिदं गुणस्थानंगळोळु पेळ्दालापक्रममेयक्कुमादोडमोंदु नवीनमुंटदावुदें दोडे भावपंढरुं द्रव्यपुरुषरुं भावस्त्रीयरुं द्रव्यपुरुषरुगळप्प वेदमार्ग्गणेय सवेदानिवृत्तिकरणपर्य्यंतमाद

पर्याप्तिगतानां चतुर्मनश्चतुर्वागौदारिकवैक्रियिकाहारकैकादशयोगानां स्वस्वपूर्णालापो भवति यथा सत्यमनोयोगस्य सत्यमनःपर्याप्तालापः। मिश्रयोगचतुष्कस्य पुनः स्वस्वैकापर्याप्तालापो भवति। यथा औदारिकमिश्रस्य औदारिकापर्याप्तालापः ॥७२३॥ अथ शेषमार्गणासु आह—

वेदाद्याहारान्तदशमार्गणासु स्वस्वगुणस्थानानामालापक्रमः सामान्यगुणस्थानवद्भवति किन्तु भावषं-

पर्याप्त अवस्थामें होनेवाले चार मनोयोग, चार वचनयोग, औदारिक, वैक्रियिक, आहारक काययोग इन ग्यारह योगोंमें अपना-अपना पर्याप्त आलाप होता है। जैसे सत्यमनोयोगके सत्यमन पर्याप्त आलाप होता है। चार मिश्रयोगोंमें अपना-अपना एक अपर्याप्त आलाप होता है। जैसे औदारिकमिश्रके औदारिक अपर्याप्त आलाप होता है ॥७२३॥

शेष मार्गणाओंमें कहते हैं—

वेदसे लेकर आहारमार्गणा पर्यन्त दस मार्गणाओंमें अपने-अपने गुणस्थानोंका आलाप-क्रम सामान्य गुणस्थानकी तरह होता है। किन्तु भावसे नपुंसक द्रव्यसे पुरुष और भावसे

पन्नेरडु असंज्ञियवोंदु गुणस्थानंगळोळं आहारमार्ग्गणेयोळु आहारकर्गे पदिमूरुमनाहारर्गोदु गुणस्थानंगळोळं सामान्यदिदं गुणस्थानंगळोळु पेळ्द क्रमदिदमालापंगळं पेळ्वुदु कोळ्गे ॥

गुणजीवा पज्जत्ती पाणा सण्णा गइंदिया काया ।
जोगा वेदकसाया णाणजमा दंसणा लेस्सा ॥७२५॥
भव्वा सम्मत्ताविय सण्णी आहारगा य उवजोगा ।
जोग्गा परूविदव्वा ओघादेसेसु समुदायं ॥७२६॥

गुणजीवाः पर्य्याप्तयः प्राणाः संज्ञा गतींद्रियाणि कायाः । योगा वेदकषाया ज्ञानयमा दर्शनानि लेश्याः ॥

भव्याः सम्यक्त्वानि च संज्ञिनः आहारकाश्चोपयोगाः । योग्याः प्ररूपयितव्याः ओघादेशेषु समुदायं ॥

पदिनाल्कु गुणस्थानंगळुं मूलपर्य्याप्तजीवसमासंगळेळुं मूलापर्य्याप्तजीवसमासंगळेळुं संज्ञिपंचेंद्रियजीवसंबंधिपर्य्याप्तिगळारुमपर्य्याप्तिगळारुं । असंज्ञिजीवसंबंधिगळु विकलत्रयजीवसंबंधिगळुमप्प पर्य्याप्तिगळय्दुमपर्य्याप्तिगळय्दुं । एकेंद्रियसंबंधिपर्य्याप्तिगळु नाल्कुमपर्य्याप्तिगळु नाल्कुं संज्ञिपंचेंद्रिय पर्य्याप्तजीवसंबंधिप्राणंगळु पत्तु । तदपर्य्याप्तजीवसंबंधिप्राणंगळेळु असंज्ञिपर्य्याप्तपंचेंद्रियजीवसंबंधिप्राणंगळोंभत्तुं तदपर्य्याप्तप्राणंगळेळुं चतुरिंद्रियपर्य्याप्तजीवसंबंधिप्राणंगळेंटुं । तदपर्य्याप्तप्राणंगळारुं पर्य्याप्तत्रींद्रियजीवसंबंधिप्राणंगळेळुं । तदपर्य्याप्तप्राणंगळय्दुं पर्य्याप्तद्वींद्रियजीवसंबंधिप्राणंगळारुं । तदपर्य्याप्तप्राणंगळु नाल्कुं पर्य्याप्तैकेंद्रियजीवसंबंधिप्राणंगळु नाल्कुं । तदपर्य्याप्तजीवसंबंधिप्राणंगळु मूरुं । पर्य्याप्तसयोगकेवलिभट्टारकसंबंधिप्राणंगळु नाल्कुमवावुवेंदोडे वाक्कायायुरुच्छ्वासनिःश्वासंगळप्पुवु । पु-

द्वादशसु, असंज्ञिन एकस्मिन्, आहारकस्य त्रयोदशसु अनाहारकस्य पञ्चसु च गुणस्थानेषु सामान्यगुणस्थानोक्तक्रमेणालापाः प्रोक्ताः ॥७२४॥

गुणस्थानानि चतुर्दश, मूलजीवसमासाः पर्याप्ताः सप्त । अपर्याप्ताः सप्त । संज्ञिनः पर्याप्तयः षट् अपर्याप्तयः षट् । असंज्ञिनो विकलत्रयस्य च पर्याप्तयः पञ्च अपर्याप्तयः पञ्च । एकेन्द्रियस्य पर्याप्तयः चतस्रः अपर्याप्तयः चतस्रः । प्राणाः संज्ञिनो दश तदपर्याप्तस्य सप्त । असंज्ञिनः नव तदपर्याप्तस्य सप्त, चतुरिन्द्रियस्य अष्टौ तदपर्याप्तस्य षट्, त्रीन्द्रियस्य सप्त तदपर्याप्तस्य पञ्च, द्वीन्द्रियस्य षट् तदपर्याप्तस्य चत्वारः, एकेन्द्रियस्य चत्वारः तदपर्याप्तस्य त्रयः । सयोगकेवलिनः चत्वारः वाक्कायायुरुच्छ्वासनिश्वासाख्याः । अयो-

बारह, असंज्ञीमें एक, आहारकके तेरह और अनाहारकके पाँच गुणस्थानोंमें सामान्य गुणस्थानोंमें कहे गये क्रमके अनुसार आलाप कर लेना चाहिए ॥७२४॥

गुणस्थान चौदह, मूल जीवसमास चौदह उनमें सात पर्याप्त, सात अपर्याप्त, संज्ञी पंचेन्द्रियके छह पर्याप्तियाँ और अपर्याप्त अवस्थामें छह अपर्याप्तियाँ, इसी प्रकार असंज्ञी और विकलत्रयके पाँच पर्याप्तियाँ, पाँच अपर्याप्तियाँ। एकेन्द्रियके चार पर्याप्तियाँ, चार अपर्याप्तियाँ, प्राण संज्ञीके दस, संज्ञी अपर्याप्तकके सात, असंज्ञीके नौ, असंज्ञी अपर्याप्तकके सात, चतुरिन्द्रियके आठ, अपर्याप्तकके छह, तेइन्द्रियके सात, अपर्याप्तकके पाँच, दोइन्द्रियके छह तथा अपर्याप्तकके चार, एकेन्द्रियके चार तथा अपर्याप्तकके तीन। सयोगकेवलीके चार प्राण वचन, काय, आयु, उच्छ्वास-निश्वास, इसीके पुनः निःश्वास और आयु

ए १। वि १। ति १। च १। पं १। पु १। अ १। ते १। या १। व १। त्र १। पु १। अ १।
ते १। या १। व १। वि १। स १। पु १। अ १। ते १। या १। व १। वि १। अ १। सं १।
पु १। अ १। ते १। या १। व १। वि १। ति १। च १। प १। पु १। अ १। ते १। बा १।
व १। वि १। ति १। च १। अ १। सं १। पु २। अ २। ते २। या २। व २। त्र १। पु २।
अ २। ते २। या २। व २। वि १। स १। पु २। अ २। ते २। या २। व २। वि १। सं १।
पु २। अ २। ते २। या २। व २। वि १। ति १। च १। पं १। पु २। अ २। ते २। बा २।
घ २। वि १। ति १। च १। ति १। च १। अ १। सं १। पु २। अ २। ते २। या २। नि २।
च २। प्र १। वि १। अ १। सं १। पु २। अ २। ते २। या २। नि २। च २। प्र १। वि १।
ति १। च १। पं १। पु २। अ २। ते २। या २। नि २। च २। प्र १। वि १। ति १। च १।
अ १। सं १। पु २। अ २। ते २। वा २। नि २। च २। प्र २। वि १। ति १। च १।
अ १। सं १॥

१। २। ३। ४। ५। ६। ७। ८। ९। १०। ११। १२। १३। १४। १५। १६। १७। १८। १९॥ गुणकारसामान्यविदमों दु १। युति १९०। २। ४। ६। ८। १०। १२। १४। १६। १८। २०। २२। २४। २६। २८। ३०। ३२। ३४। ३६। ३८॥ गुणकारद्वयुति ३८०। ३।

सा १ त्र १ स्था १ ए १ वि १ सं १ ए १ वि १। अ १ सं १ ए १ वि १ ति १ च १ पं १।
अ १ ते १ वा १ व १ त्र १ पु १ अ १ ते १ वा १ व १ वि १ सं १ पु १ अ १ ते १ वा १ व १ वि १ ति
अ १ सं १ पु १ अ १ ते १ वा १ व १ वि १ ति १ च १ पं १। पु १ अ १ ते १ वा १ व १ वि १ सं १। पु २ अ २
च १ अ १ सं १ पु २ अ २ ते २ वा २ व २ त्र १ पु २ अ २ ते २ वा २ व २ वि १ सं १। पु २ अ २
ते २ वा २ व २ वि १ अ १ सं १। पु २ अ २ ते २ वा २ व २ वि १ ति १ प १ पं १। पु २ अ २
ते २ वा २ व २ वि १ ति १ च १ अ १ पं १। पु २ अ २ ते २ वा २ नि २ च २ प्र १ वि १ अ १
सं १। पु २ अ २ ते २ वा २ नि २ च २ प्र १ वि १ ति १ च १ पं १। पु २ अ २ ते २ वा २ नि २
च २ प्र १ वि १ ति १ च १ अ १ सं १। पु २ अ २ ते २ वा २ नि २ च २ प्र २ वि १ ति १ च १
अ १ सं १। १ २ ३ ४ ५ ६ ७ ८ ९ १० ११ १२ १३ १४ १५ १६ १७ १८ १९। गुणकारः सामान्य

सामान्य पर्याप्त-अपर्याप्तसे गुणा करनेपर समस्त जीवसमास स्थानके विकल्प होते हैं। एकसे लेकर उन्नीस तकके विकल्पोंको एकसे गुणा करनेपर उतने ही रहते हैं १, २, ३, ४, ५, ६, ७, ८, ९, १०, ११, १२, १३, १४, १५, १६, १७, १८, १९। इन सबका जोड़ १९०

१. इवु पर्य्याप्तंगलोंदे भेदवु। २. पर्य्याप्तापर्य्याप्तभेदर्दिद द्विगुणंगलु। ३. इवु पर्य्याप्तनिर्वृत्यपर्य्याप्त-लब्ध्यपर्य्याप्तभेदर्दिदं त्रिगुणितंगलु।

चतुःकषायिगळु मकषायरुमोळरु । अष्टज्ञानिगळु मोळरु । सप्तसंयमरुगळु मतीतसंयमरु मोळरु । चतुर्द्दर्शनिगळुमोळरु । द्रव्यभावभेदषड्लेश्यरुगळु मलेश्यरुगळुमोळरु । भव्यसिद्धरुगळु मभव्यसिद्धरुगळु मतीतभव्याभव्यसिद्धरुगळुमोळरु । षड्विधसम्यक्त्वयुक्तरुगळुमोळरु । संज्ञिगळुमसंज्ञिगळुमतिक्रांतसंज्ञ्यसंज्ञिगळु मोळरु । आहारिगळु मनाहारिगळु मोळरु । साकारोपयोगयुक्तरुमनाकारोपयोगयुक्तरुं । युगपत्साकारानाकारयोगयुक्तरुगळु मोळरु । इन्नु पर्य्याप्तिविशिष्टगुणस्थानंगळं विवक्षितमागलु पदिनाल्कुं गुणस्थानिगळुमोळरु । अतीतगुणस्थानरिल्लेकें बोडेल्लं [illegible] भवरप्पुदरिंदं । पर्य्याप्तगुणस्थानिगळ्गे । गु १४ । जी ७ । प ६ । ५ । ४ । प्रा १० । ९ । ८ । ६ । ७ । ४ । ४ । १ । सं ४ । ग ४ । इं ५ । का ६ । यो ११ । वे ३ । क ४ । ज्ञा ८ । सं ७ । द ४ । ले ६ । भ २ । स ६ । सं २ । आ २ । उ १२ । अपर्य्याप्तगुणस्थानिगळ्गे । गु ५ । मि । सा । अ । प्र । स । जी ७ । प ६ । ५ । ४ । प्रा ७ । ७ । ६ । ५ । ४ । ३ । २ । सं ४ । ग ४ । इं ५ । का ६ । यो ४ । औ मि । वै मि । आ मि । कार्म्मण । वे ३ । कषा ४ । ज्ञा ६ । कु । कु । म । श्रु । [illegible]

[illegible] पट्कायिकास्तद्रहिताश्च संति । पञ्चदशयोगाः अयोगाश्च संति । [illegible] कषायाः अकषायाश्च संति । अष्टज्ञानाः संति । सप्तसंयमास्तद्रहिताश्च संति । [illegible] द्रव्यभावषड्लेश्याः अलेश्याश्च संति । भव्यसिद्धाः अभव्यसिद्धाः अतीतसिद्धाश्च [illegible] संज्ञिनोऽसंज्ञिनोऽतीतद्वयाश्च संति । आहारिणोऽनाहारिणश्च संति । साकारोपयोगाः [illegible] युगपदुपयोगाश्च संति । अथ पर्याप्तिविशिष्टगुणस्थानानामुच्यते-तत्र चतुर्दश [illegible] तदालापाः—

पर्याप्तगुणस्थानानां गु १४ । जी ७ । प ६ ५ ४ । प्रा १० ९ ८ ७ ६ ४ ४ १ । सं ४ । ग ४ । इं ५ । का ६ । यो ११ । वे ३ । क ४ । ज्ञा ८ । सं ७ । द ४ । ले ६ । भ २ । स ६ । सं २ । आ २ । [illegible]
आ १

[illegible] अपर्याप्तगुणस्थानानां गु ५ मि सा अ प्र स । जी ७ अ । प ६ । ५ । ४ । प्रा ७ ७ ६ ५ ४ [illegible] । औमि वैमि आमि कार्म । वे ३ । क ४ । ज्ञा ६ । कु कु [illegible]

[illegible] और उनसे रहित जीव हैं। छह कायिक जीव और उनसे रहित [illegible] हैं। [illegible] और योगरहित जीव हैं। तीन वेदवाले जीव और उनसे [illegible] हैं। [illegible] जीव और कषायरहित जीव हैं। आठ ज्ञानवाले [illegible] नहीं हैं। [illegible] उनसे युक्त जीव और उनसे रहित जीव हैं। [illegible] हैं। [illegible] रहित जीव नहीं हैं। द्रव्य भाव रूप छह लेश्यावाले युक्त [illegible] हैं। [illegible] भव्यसिद्ध अभव्यसिद्ध जीव हैं और इन दोनों भावोंसे रहित [illegible] हैं। [illegible] युक्त जीव हैं। सम्यक्त्व रहित जीव नहीं हैं। संज्ञी और असंज्ञी [illegible] रहित जीव हैं। आहारक और अनाहारक जीव हैं। आकार उपयोगी, अनाकार [illegible] दोनों उपयोगवाले जीव हैं। आगे गुणस्थान और पर्याप्तियोंसे [illegible] कहते हैं—

[illegible] गुणस्थानों और पर्याप्त-अपर्याप्तोंके [illegible] कहते हैं। [illegible] नहीं हैं।

उ ५ । पर्य्याप्तकसासादनगुणस्थानवर्तिगळ्गे । गु १ । सा सा । जो १ । प । प ६ । प्रा १० । सं ४ । ग ४ । इं १ । पं । का १ । त्र । यो १० । म ४ । वा ४ । औ का १ । वै का १ । वे ३ । क ४ । ज्ञा ३ । कु । कु । वि । सं १ । अ । द २ ले ६/भा ६ । भ १ । सं १ । सा सा । सं १ । आ १ । उ ५ ॥

अपर्य्याप्तकसासादनगुणस्थानवर्त्तिगळ्गे । गु १ । अ । प । ६ । अ । प्रा ७ । अ सं ४ । ग ३ । म । दे । इं १ । पं । का १ । त्र । यो ३ । औ मि । वै मि । का । वे ३ । क ४ । ज्ञा २ । कु । कु । सं । अ द २ ले २/भा ६ । क । शु । भ १ । सं १ । या सा । सं १ । आ २ । उ ४ ॥

सम्यग्मिथ्यादृष्टिगुणस्थानवर्तिगळ्गे । गु १ । मिश्र । जी १ । प । प ६ । प्रा १० । सं ४ । ग ४ । इं १ । पं । का १ । त्र । यो १० । म ४ । वा ४ । औ का १ । वै का १ । वे ३ । क ४ । ज्ञा ३ । मि म । मि श्र । मि अ । सं १ । अ । द ३ । ले ६/२ ६ भ १ । भ ।

मिश्ररुचि । सं १ । आ १ उ ६ ॥

असंयतगुणस्थानवर्तिगळ्गे । गु १ । अ । सं । जी २ । प । अ । प ६६ । प्रा १० । ७ । सं ४ । ग ४ । इं १ । पं । का १ त्र । यो १३ । म ४ । व ४ । औ २ । वै २ । का १ । वे ३ । क ४ । ज्ञा ३ । म । श्रु । अ । सं १ । अ । द ३ । च । अ । अ ॥ ले ६/भा ६ भ १ । सं ३ । उ । वे । क्षा । सं १ । आ २ । उ ६ ॥

असंयतगुणस्थानवर्तिपर्य्याप्तासंयतसम्यग्दृष्टिगळ्गे । गु १ । असं । जी १ । प । प ६ । प्रा १० । सं ४ । ग ४ । इं १ । पं । का १ । त्र । यो १० । म ४ । व ४ । औ का १ । वै का १ । वे ३ । क ४ । ज्ञा ३ । म । श्रु । अ । सं १ । अ । द ३ । च । अ । अ । ले ६/भा ६ भ १ । सं ३ । उ । वे । क्षा । सं १ । आ १ उ ६ ॥

उ ५ । पर्याप्तसासादना—गु १ सासा । जी १ । प ६ । प्रा १० । सं ४ । ग ४ । इं १ पं । का १ त्र । यो १० । म ४ । वा ४ । औका १ । वैका १ । वे ३ । क ४ । ज्ञा ३ कु कु वि । सं १ अ । द २ । ले ६/भा ६ [illegible] १ सासा । सं १ । आ १ । उ ५ । अपर्याप्तसासादना गु १ । सासा । जी १ अ । प ६ अ । प्रा ७ अ । [illegible] १ । इं १ पं । का १ त्र । यो ३ औमि वैमि का । वे ३ । क ४ । ज्ञा २ कु कु । [illegible] २ । ले २/भा ६ क शु । भ १ । स १ सासा । सं १ । आ २ । उ ४ ॥ सम्यग्मिथ्यादृष्टीनां गु १ मिश्र । [illegible] प्रा १० । सं ४ । ग ४ । इं १ पं । का १ त्र । यो १० । म ४ वा ४ औका १ वैका १ । [illegible] । क ४ । ज्ञा ३ [illegible] अ । द ३ । ले ६/भा ६ । भ १ । स १ मिश्ररुचि । सं १ । आ १ । [illegible]

[illegible] । प्रा १० ७ । सं ४ । ग ४ । इं १ पं । का १ त्र । [illegible] । ज्ञा ३ म श्रु अ । सं १ अ । द ३ [illegible]

[illegible] । आ २ । उ ६ । [illegible] गु १ अ । जी १ प । प ६ । प्रा १० । [illegible] १ त्र । यो १० म ४ वा ४ औका १ । वैका १ । वे ३ । क ४ । ज्ञा ३ [illegible]

म। इं १। पं। का १। त्र। यो ९। वे ३। क ४। ज्ञा ४। सं २। सा। छे। द ३। द्र।
अ। ले ६ भ १। सं २। उ। क्षा। सं १। आ १। उ ७॥
भा १

अनिवृत्तिकरणगुणस्थानवर्त्तिप्रथमभागानिवृत्तिकरणंगे। गु १। अनि। जो १। प६।
प्रा १०। सं २। मै। ग १। म। इं १। का १। यो ९। वे ३। क ४। ज्ञा ४। सं २। सा छे।
द ३। ले ६ भ १। सं २। उ। क्षा। सं १। आ १। उ ७॥
भा १

अनिवृत्तिकरणगुणस्थानवर्त्तिद्वितीयभागानिवृत्तिकरणंगे। गु १। अनि। जि १। प६।
प्रा १०। सं १। प। ग १। म। इं १। का १। यो ९। वे ०। क ४। ज्ञा ४। म। श्रु। द्र।
सं २। सा। छे। द ३। ले ६ भ १। सं २। उ। क्षा। सं १। आ १। उ ७॥
भा १

तृतीयभागानिवृत्तिकरणंगे। गु १। जो १। प ६। प्रा १०। सं १। प। ग १। म। इं।
का १। यो ९। वे ०। क ३। ज्ञा ४। सं २। सा। छे। द ३। ले ६ भ १। सं २। उ।
भा १
क्षा। सं १। आ १। उ ७॥

चतुर्थभागानिवृत्तिकरणंगे। गु १। अनि। जो १। प ६। प्रा १०। सं १। प। ग।
म। इं १। का १। यो ९। वे ०। क २। ज्ञान ४। सं २। सा। छे। द ३। ले ६ भ।
भा १
सं २। उ। क्षा। सं १। आ १। उ ७॥

पंचमभागानिवृत्तिकरणंगे। गु १। अनि। जी १। प ६। प्रा १०। सं १। प। ग १। म।
इं १। प ०। का १। त्र। यो ९। वे ०। क १। लो। ज्ञा ४। सं २। सा। छे। द ३। ले ६
भा १
भ १। सं २। उ। क्षा। सं १। आ १। उ ७॥

सं १। ग १ म। इं १ पं। का १ त्र। यो ९। वे ३। क ४। ज्ञा ४। सं २। सा छे। द ३ द्र अ।
ले ६। भ १। स २। उ क्षा। सं १। आ १। उ ७। अनिवृत्तिकरणप्रथमभागवर्तिना—गु १ अनिवृत्ति।
भा १
जी १। प ६। प्रा १०। सं २ मै प। ग १ म। इं १। का १। यो ९। वे ३। क ४। ज्ञा ४। सं २
सा छे। द ३। ले ६। भ १। स २ उ क्षा। सं १। आ १। उ ७। तद्द्वितीयभागवर्तिनां—गु १ अनि।
भा १
जी १। प ६। प्रा १०। सं १ प। ग १। इं १। का १। यो ९। वे ०। क ४। ज्ञा ४ म श्रु अ।
सं २ सा छे। द ३। ले ६। भ १। स २ उ क्षा। सं १। आ १। उ ७। तृतीयभागवर्तिनां—गु १
भा १
अनि। जी १। प ६। प्रा १०। सं १ प। ग १ म। इं १। का १। यो ९। वे ०। क ३। ज्ञा ४।
सं २ सा छे। द ३। ले ६। भ १। स २ उ क्षा। सं १। आ १। उ ७। चतुर्थभागवर्तिनां—गु १ अनि।
भा १
जी १। प ६। प्रा १०। सं १ प। ग १ म। इं १। का १। यो ९। वे ०। क २। ज्ञा ४। सं २ सा
छे। द ३। ले ६। भ १। स २ उ क्षा। सं १। आ १। उ ७। पंचमभागवर्तिनां—गु १ अनि। जी १।
भा १
प ६। प्रा १०। सं १ प। ग १ म। इं १ पं। का १ त्र। यो ९। वे ०। क १ लो। ज्ञा ४। सं २ सा

इं। ०। का ०। यो ०। वे। ०। क ०। ज्ञा १। के। सं। ०। द १। के। ले ०। भ। ०।
क्षा। सं। ०। आ १। अनाहार। उ २॥

आदेशदोळु गत्यनुवाददोळु नारकरुगळ्गे सामान्यालापं पेळल्पडुवल्लि। गु ४।
प। अ। प ६। ६। प्रा १०। ७। सं ४। ग १। नरकगति। इं १। का १। यो ११।
या ४। वै २। का १। वे १। पं। क ४। ज्ञा ६। कु। कु। वि। म। श्रु। अ। सं।
द ३। च। अ। अ। ले ३
भा ३
भ २। सं ६। मि। सा। मि। उ। वे। क्षा।
आ २। उ ९॥

सामान्यपर्य्याप्तनारकर्गे गु ४। जी १। प ६। प्रा १०। सं ४। ग १। न।
का १। यो ९। वे १। पं ०। क ४। ज्ञा ६। कु। कु। वि। म। श्रु। अ। सं १। अ।
च। अ। अ। ले १ कृ
भा ३
। भ २। सं ६। मि। सा। मि। उ। वे। क्षा। सं २। उ ९॥

सामान्यनारकापर्याप्तकंगे गु २ मि। अ। जो २। प ६। प्रा ७। सं ४। ग।
इं १। का १। यो २। वै। मि। का॥ वे १। प ०। क ४। ज्ञा ५। कु। कु। म।
सं १। अ। द ३। ले २ क। शु
भा ३
। भ २। सं ३। मि। वे। क्षा। सं १। आ २। उ ८

सामान्यनारकमिथ्यादृष्टिगळ्गे गु १। मि। जी २। प। अ। प ६। ६। प्रा।
सं ४। ग १। न। इं १। का १। यो ११। वे १। प ०। क ४। ज्ञा ३। कु। कु। वि।
अ। द २। ले ३
भा ३
भ २। सं १। मि। सं १ आ २। उ ५॥

प ०। प्रा ०। सं ०। ग ०। इं ०। का ०। यो ०। वे ०। क ०। ज्ञा १ के। स ०। द १ के
भ ०। स १ क्षा। सं ०। आ १ अनाहार। उ २।

आदेशे गत्यनुवादे नारकाणां—गु ४। जी २ प अ। प ६। ६ प्रा १० ७। सं ४। ग
इं १। का १। यो ११। म ४ वा ४ वै २ का १। वे १ पं। क ४। ज्ञा ६ कु, कु, वि म श्रु अ
अ। द ३ च अ अ। ले ३
भा ३
। पर्याप्तेष्वपरि कृष्णलेश्या एकैव अपर्याप्तकाले कपोतलेश्या विग्रहगतौ शु
इति द्रव्यलेश्यात्रय। भ २। स ६ मि सा मि उ वे क्षा। सं १। आ २। उ ९। तत्पर्याप्ताना-
जी १। प ६। प्रा १०। सं ४। ग १ न। इं १। का १। यो ९। वे १ पं। क ४। ज्ञा ६ कु
श्रु अ। सं १ अ। द ३ च अ अ। ले १ कृ
भा ३
। भ २। स ६ मि सा मि उ वे क्षा। सं १। आ १
तदपर्याप्ताना—गु २। मि अ। जी १। प ६ अ। प्रा ७ अ। सं ४। ग १ न। इं १। का १
वैमि क। वे १ पं। क ४। ज्ञा ५ कु कु म श्रु अ। सं १ अ। द ३। ले २ क शु
भा ३
। भ २। स ३ मि
सं १। आ २। उ ८। तन्मिथ्यादृष्टीना—गु १ मि। जी २ प अ। प ६ ६। प्रा १० ७। सं ४।
इं १। का १। योग ११। वे १ पं। क ४। ज्ञा ३ कु कु वि। सं १ अ। द २। ले ३
भा ३
। भ

1. द्रव्य कपोत शुक्ल।

सामान्यनारकपर्य्याप्तासंयतंगे । गु १ । जी १ । प ६ । प्रा १० । सं ४ । ग १ न । इं १ । का १ । यो ९ । वे १ पं । क ४ । ज्ञा ३ म । श्रु । अ । सं १ अ । द ३ । ले १ भ १ । सम्य ३,
भा ३
उ । वे । क्षा । स १ । आ १ । उ प ६ ॥

सामान्यनारकाऽपर्य्याप्तासंयतंगे । गुण १ । जी १ । अ । प ६ । अ । प्रा ७ । अ । सं ४ । ग १ । न । इं १ । का १ । यो २ । वै मि । का । वे १ । पं ० । क ४ । ज्ञा ३ । म । श्रु । अ । सं १ । अ । द ३ ले २ क शु । भ १ । सं २ । वे क्षा ॥ सं १ । आ २ । उ ६ ॥
भा १ कपो

घर्म्मेय सामान्यनारकर्ग्गे ।। गु ४ । जी २ । प । अ । प । ६ । ६ । प्रा १० । ७ । सं ४ । ग १ न । इं १ । का १ । यो ११ । म ४ । वा ४ । वै २ । का १ । वे १ । पं । क ४ । ज्ञा ६ । कु । कु । वि । म । श्रु । अ । सं १ । अ । द ३ ले ३ कृ । क । शु । भ २ । सं ६ । सं १ । आ २ । उ ९ ॥
भा १

घर्म्मेय सामान्यनारकपर्य्याप्तकर्ग्गे । गु ४ । जी १ । प ६ । प्रा १० । सं ४ । ग १ । न । इं १ । का १ । यो ९ । म ४ । वा ४ । वै का १ । वे १ । प ० । क ४ । ज्ञा ६ । सं १ । अ । द ३ । ले १ कृ भ २ । सं ६ । सं १ । आ १ । उ ९ ॥
भा १ कृ

घर्म्मेय सामान्यनारकापर्य्याप्तर्ग्गे । गु २ । मि । अ । जी १ । अ । प ६ । अ । प्रा ७ । अ । सं ४ । ग १ न । इं १ । का १ । यो २ । वै मि । का । वे १ । प ० । क ४ । ज्ञा ५ । कु । कु । म । श्रु । अ । सं १ । अ । द ३ । ले २ क शु । भ २ । स ३ । मि । वे । क्षा । सं १ । आ २ । उ ८ ॥
भा १ क

आ २ । उ ६ । तत्पर्याप्तानां—गु १ । जी १ । प ६ । प्रा १० । सं ४ । ग १ न । इं १ । का १ । यो ९ । वे १ पं । क ४ । ज्ञा ३ म श्रु अ । सं १ अ । द ३ । ले १ कृ । भ १ । स ३ । उ वे क्षा । सं १ ।
भा ३ अ
आ १ । उ ६ । तदपर्याप्तानां—गु १ । जी १ अ । प ६ अ । प्रा ७ अ । सं ४ । ग १ न । इं १ । का १ । यो २ । वैमि का । वे १ पं । क ४ । ज्ञा ३ म, श्रु, अ । सं १ अ । द ३ । ले २ क शु । भ १ स २ वे ।
भा ३ अशुभ
क्षा । सं १ । आ २ । उ ६ । घर्मानारकाणां—गु ४ । जी २ प अ । प ६ ६ । प्रा १० ७ । सं ४ । ग १ न । इं १ । का १ । यो ११ । म ४ वा ४ वै २ का १ । वे १ पं । क ४ । ज्ञा ६ कु कु वि म श्रु अ । सं १ अ । द ३ । ले ३ क क शु । भ २ स ६ । सं १ आ २ । उ ९ । तत्पर्याप्तानां—गु ४ । जी १ प । प ६ ।
भा १ क
प्रा १० । सं ४ । ग १ न । इं १ । का १ । यो ९ । म ४ वा ४ वै का १ । वे १ पं । क ४ । ज्ञा ६ । सं १ अ । द ३ । ले १ क । भ २ । स ६ । सं १ । आ १ । उ ९ । तदपर्याप्तानां—गु २ मि अ । जी १ अ । प ६ अ । प्रा ७ अ । सं ४ । ग १ न । इं १ । का १ । यो २ वैमि । का । वे १ पं । क ४ । ज्ञा ५ कु कु म श्रु अ । सं १ अ । द ३ । ले २ क शु । भ २ । स ३ मि वे क्षा । सं १ । आ २ । उ ८ ।
भा १ क

द्वितीयापृथ्वीनारकसम्यग्मिथ्यादृष्टिगळ्गे। गु १। जो १। प ६। प्रा १०। सं ४। गति १। इं १। का १। यो ९। वे १। क ४। ज्ञा ३॥ सं १। द २। ले १ भ १। सं १। मिथ।
१
सं १। आ १। उ ५॥

द्वितीयादिपृथ्वीनारकाऽसंयतसम्यग्दृष्टिगळ्गे। गु १। जो १। प ६। प्रा १०। सं ४। ग १। इं १। का १। यो ९। ये १। क ४। ज्ञा ३। म। श्रु। अ। सं १। अ। द ३। च। अ। अ। १ भ १। सं २। उ। वे। सं १ आ। १। उ ६। म। श्रु। अ। च। अ। अ॥
१

तिर्य्यंचरु पंचप्रकारमप्परवरोळु सामान्यतिर्य्यंचरुगळ्गे। गु ५। जो १४। प ६। ६। ५। ५। ४। ४। प्रा १०। ७। ९। ७। ६। ५। ८। ६। ७। ५। ६। ४। ४। ३। सं ४। ग १। ति १। इं ५। का ६। यो ११। म ४। व ४। औ २। का १। ये ३। क ४। ज्ञा ६। म। श्रु। अ। कु। कु। वि। सं २। अ। दे। द ३। च। अ। अ। ले ६ द्रव्यदोळु भावदोळं भ २। सं ६।
भा ६
उ। वे। क्षा। मि। सा। मि। सं २। आ २। उ ९। म। श्रु। अ। कु। कु। वि। च। अ। अ॥

तिर्य्यंच सामान्यपर्य्याप्तकर्गे। गु ५। जो ७। प ६। ५। ४। प्रा १०। ९। ८। ७। ६। ५। ४। सं ४। ग १। ति। इं ५। का ६। यो ९। ये ३। क ४। ज्ञा ६। सं २। द ३। ले ६ भ २। स ६। सं २। आ १। उ ९॥
६

तिर्य्यंचसामान्यापर्य्याप्तकर्गे। गु ३। मि। सा। अ। जो ७। प ६। ५। ४। प्रा ७। ७। ६। ५। ४। ३। सं ४। ग १। ति। इं ५। का ६। यो २। मिश्रका। वे ३। क ४। ज्ञा ५। म। श्रु। अ। कु। कु। सं १ अ। द ३। च। अ। अ लेशक शु भ २। सं ४। मि। सा।
भा ३ अशु

तत्सम्यग्मिथ्यादृशां—गु १, जो १, प ६, प्रा १०, सं ४, ग १, इं १, का १, यो ९, वे १, क ४, ज्ञा ३, सं १, द २, ले १, भ १, स १, मिश्रं, सं १, आ १, उ ५, तदसंयतानां गु १, जो १, प ६, प्रा १०,
भा १
सं ४, ग १, इं १, का १, यो ९, वे १, क ४, ज्ञा ३ म श्रु अ, सं १, अ, द ३, च अ अ। ले १ स
भा १
स २ उ वे, सं १ आ १ उ ६ म श्रु अ च अ अ।

पञ्चविधतिर्यक्षु सामान्यानां—गु ५। जी १४। प ६ ६ ५ ५ ४ ४। प्रा १० ७ ९ ७ ८ ६ ७ ५ ६ ४ ४ ३। सं ४। ग १ ति। इं ५। का ६। यो ११ म ४ व ४ औ २ का १। वे ३। का ४। ज्ञा ६ कु कु वि म श्रु अ। सं २ अ दे। द ३ च अ अ। ले ६। भ २। स ६ उ वे क्षा मि सा मि। सं २।
भा ६
आ २। उ ९ म श्रु अ कु कु वि च अ अ। तत्पर्याप्तानां—गु ५। जी ७। प ६ ५ ४। प्रा १० ९ ८ ७ ६ ५ ४। सं ४। ग १ ति। इं ५। का ६। यो ९। वे ३। क ४। ज्ञा ६। सं २। द ३। [illegible] ६। भ २।
भा ६
स ६। सं २। आ १। उ ९। तदपर्याप्तानां—गु ३ मि सा अ। जो ७। प ६ ५ ४। प्रा ७ ७ ६ ५ ४ ३। सं ४। ग १ ति। इं ५। का ६। यो २ मिश्र का। वे ३। क ४। ज्ञा ५ कु कु म श्रु अ। सं १। अ।

BHĀRATĪYA JÑĀNAPĪTHA

MŪRTIDEVĪ JAIN GRANTHAMĀLĀ

FOUNDED BY

LATE SAHU SHANTI PRASAD JAIN

IN MEMORY OF HIS LATE MOTHER SHRIMATI MURTIDEVI

AND

PROMOTED BY HIS BENEVOLENT WIFE

LATE SHRIMATI RAMA JAIN

IN THIS GRANTHAMALĀ CRITICALLY EDITED JAINA AGAMIC, PHILOSOPHICAL, PURĀṆIC, LITERARY, HISTORICAL AND OTHER ORIGINAL TEXTS AVAILABLE IN PRAKRIT, SANSKRIT, APABHRAṀŚA, HINDI, KANNAḌA, TAMIL, ETC., ARE BEING PUBLISHED IN THEIR RESPECTIVE LANGUAGES WITH THEIR TRANSLATIONS IN MODERN LANGUAGES.

ALSO

BEING PUBLISHED ARE

CATALOGUES OF JAINA-BHAṆḌĀRAS, INSCRIPTIONS, ART AND ARCHITECTURE ...

कुमति कुश्रुतज्ञानि मिथ्यादृष्टि पर्याप्तक	बीस प्ररूपणा	१०२९
" " " अपर्याप्तक	"	१०३०
" " सासादन	"	"
" " " पर्याप्तक	"	"
" " " अपर्याप्तक	"	१०३१
विभंगज्ञानि	"	"
" मिथ्यादृष्टि	"	"
" सासादन	"	"
मतिश्रुतज्ञानि	"	"
" पर्याप्तक	"	१०३२
" अपर्याप्तक	"	"
" असंयत	"	"
मतिश्रुतज्ञानि असंयत अपर्याप्तक	"	१०३२
" " पर्याप्तक	"	"
मनःपर्ययज्ञानि	"	१०३३
केवलज्ञानि	"	"
संयमानुवाद	"	"
" प्रमत्त संयत	"	"
" अप्रमत्त सं.	"	१०३४
सामायिक संयम	"	"
परिहारविशुद्धि	"	"
यथाख्यात संयम	"	"
असंयम	"	१०३५
" पर्याप्तक	"	"
" अपर्याप्तक	"	"
चक्षुदर्शनी	"	१०३६
" पर्याप्तक	"	"
" अपर्याप्तक	"	"
" मिथ्यादृष्टि	"	"
" " पर्याप्तक	"	१०३७
" " अपर्याप्तक	"	"
अचक्षुदर्शनी	"	"
" पर्याप्तक	"	"
" अपर्याप्तक	"	१०३८
" मिथ्यादृष्टि	"	"
" " पर्याप्तक	"	"
" " अपर्याप्तक	"	"
अवधिदर्शनी	बीस प्ररूपणा	१०३९
" पर्याप्तक	"	"
" अपर्याप्तक	"	"
कृष्णलेश्या	"	"
" पर्याप्तक	"	"
" अपर्याप्तक	"	१०४०
" मिथ्यादृष्टि	"	"
" " पर्याप्तक	"	"
" " अपर्याप्तक	"	"
" सासादन	"	१०४१
" " पर्याप्तक	"	"
" " अपर्याप्तक	"	"
" मिश्र	"	"
" असंयत सम्यग्दृष्टि	"	"
" " पर्याप्तक	"	१०४२
" " अपर्याप्तक	"	"
कपोतलेश्या	"	"
" पर्याप्तक	"	१०४३
" अपर्याप्तक	"	"
" मिथ्यादृष्टि	"	"
" " पर्याप्तक	"	"
" " अपर्याप्तक	"	१०४४
" सासादन	"	"
" " पर्याप्तक	"	"
" " अपर्याप्तक	"	"
" सम्यग्मिथ्यादृष्टि	"	"
" असंयत सम्यग्दृष्टि	"	१०४५
" " पर्याप्तक	"	"
" " अपर्याप्तक	"	"
तेजोलेश्या	"	"
" पर्याप्तक	"	"
" अपर्याप्तक	"	१०४६
" मिथ्यादृष्टि	"	"
" " पर्याप्तक	"	"
" " अपर्याप्तक	"	"
" सासादन	"	"
" " पर्याप्तक	"	१०४७
" सासादन अपर्याप्त	"	"

प्रत्यक्षं परोक्षमुमेंदितु द्विप्रकारमप्प प्रमाणमक्कुं। [illegible] पत्तिनिराकरणमिमं स्याद्वादमतप्रमाणस्थापनमुमं [illegible] नोडिकोळल्पडुवुदेके बोडिहेतुवादरूपमप्पागमदोळ् हेतुवादक्कनधिकारमप्पुदरिंदं।

अनंतरं ज्ञानभेदमं पेळ्दपं।

पंचेव होंति णाणा मदिसुदओहीमणं च केवलयं।
खयउवसमिया चउरो केवलणाणं हवे खइयं ॥३००॥

पंचैव भवंति ज्ञानानि मतिः श्रुतावधिमनःपर्य्ययकेवलानि। [illegible] केवलज्ञानं भवेत्क्षायिकं ॥

मतिश्रुतावधिमनःपर्य्ययकेवलमें[illegible] सम्यग्ज्ञानंगळ्[illegible] सामान्यापेक्षेयिदं संग्रहरूपद्रव्यार्थिकनयमनाश्रयिसि ज्ञानमों[illegible] [illegible] पेक्षेयिदं पर्य्यायार्थिकनयमनाश्रयिसि ज्ञानंगळय्दें[illegible] [illegible] वधिमनःपर्य्ययमेंब नाल्कुं ज्ञानंगळुं क्षायोपशमिकंगळप्पुवु। [illegible] द्रव्यगळनुभागदरोळ् सर्व्वघातिस्पर्द्धकंगळुदयाभावलक्षणमप्प क्षयमुं [illegible] शममें बुदु। क्षयश्चासावुपशमश्च क्षयोपशमः। क्षयोपशमे भवानि क्षायोपशमिकानि। अथवा क्षयोपशमः प्रयोजनमेषां क्षायोपशमिकानि। [illegible]

ब्रुवन्ति—कथयन्ति अर्हदादयः। एतज्ज्ञानं प्रत्यक्षं परोक्षं चेति द्विविधं प्रमाणं भवति। [illegible] फललक्षणानि तद्विप्रतिपत्तिनिराकरणं स्याद्वादमतप्रमाणस्थापनं च [illegible] अत्राहेतुवादरूपे आगमे हेतुवादस्यानधिकारात् ॥२९९॥ अथ ज्ञानभेदानाह—

मतिश्रुतावधिमनःपर्ययकेवलनामानि सम्यग्ज्ञानानि पञ्चैव [illegible]। यद्यपि [illegible] संग्रहरूपद्रव्यार्थिकनयमाश्रित्य ज्ञानमेकमेव कथितं, तथापि विशेषापेक्षया पर्यायार्थिकनयमाश्रित्य ज्ञानानि पञ्चैवेत्युक्तानि इत्यर्थः। तेषु मतिश्रुतावधिमनःपर्ययरूपाणि चत्वारि ज्ञानानि क्षायोपशमिकानि। भवन्ति मतिज्ञानाद्यावरणवीर्यान्तरायकर्मद्रव्याणां अनुभागस्य सर्वघातिस्पर्धकानामुदयाभावलक्षणः क्षयः, [illegible] प्राप्तानां सदवस्थारूप उपशमः। क्षयश्चासावुपशमश्च क्षयोपशमः क्षयोपशमे भवानि क्षायोपशमिकानि। अथवा क्षयोपशमः प्रयोजनमेषामिति क्षायोपशमिकानि। [illegible]

प्रकारका प्रमाण होता है। प्रमाणका स्वरूप, संख्या, विषय, फल तथा [illegible] विवादों-का निराकरण करके स्याद्वादसम्मत प्रमाणका स्थापन विस्तारपूर्वक प्रमेयकमलमार्तण्ड आदि तर्कशास्त्रके ग्रन्थोंमें देखना चाहिए। इस अहेतुवाद रूप आगम ग्रन्थमें हेतुवादका अधिकार नहीं है ॥२९९॥

आगे ज्ञानके भेद कहते हैं—

मति, श्रुत, अवधि, मनःपर्यय और केवल नामक सम्यग्ज्ञान पाँच ही हैं, न कम हैं, न अधिक हैं। यद्यपि सामान्यकी अपेक्षा संग्रह रूप द्रव्यार्थिक नयके आश्रयसे ज्ञान एक ही कहा है, तथापि विशेषकी अपेक्षा पर्यायार्थिक नयके आश्रयसे ज्ञान पाँच ही कहे हैं यह उक्त कथनका अभिप्राय है। उनमें-से मति, श्रुत, अवधि, मनःपर्यय नामक चार ज्ञान क्षायो-पशमिक होते हैं। मतिज्ञान आदि आवरण और वीर्यान्तराय कर्म द्रव्यके अनुभागके सर्वघाती स्पर्धकोंके उदयका अभाव रूप क्षय और जो उदय अवस्थाको प्राप्त न होकर सत्ता-में स्थित हैं उनका वही हुआ सदवस्थारूप उपशम। क्षय और उपशमको क्षायोपशम कहते

तत्संज्ञिपंचेंद्रियपर्य्याप्तनोळेयक्कुमन्यनोळागदें बुदरिदं इतरमत्यज्ञानमुं श्रुताज्ञानमुमें बीयज्ञानद्वयमेकेंद्रियादिगळोळु पर्य्याप्तापर्य्याप्तकरोळेल्लरोळु मिथ्यादृष्टिसासादनरोळु संभविसुगुमें दु पेळल्पट्टुदाप्तु । खलु स्फुटमागि ।

अनंतरं सम्यग्मिथ्यादृष्टिगुणस्थानदोळु ज्ञानस्वरूपमं पेळ्दपं ।

मिस्सुदए संमिस्सं अण्णाणतिएण णाणतियमेव ।
संजमविसेससहिए मणपज्जवणाणमुद्दिट्ठं ॥३०२॥

मिश्रोदये संमिश्रमज्ञानत्रयेण ज्ञानत्रयमेव । संयमविशेषसहिते मनःपर्य्ययज्ञानमुद्दिष्टं ॥

मिश्रोदये सम्यग्मिथ्यात्वकर्म्मोदयमागुत्तिरलु अज्ञानत्रयदोडने सम्यग्ज्ञानत्रयमे संमिश्रं संमिश्रमक्कुमन्तर्यविवेचनत्वदिदं । सम्यग्मिथ्यामतिज्ञानमुं सम्यग्मिथ्याश्रुतज्ञानमुं सम्यग्मिथ्यावधिज्ञानमुमें ब व्यपदेशमक्कुं । सम्यग्मिथ्यादृष्टियोळु वर्त्तमानज्ञानत्रयं केवलं सम्यग्ज्ञानमुमल्तु । केवलं मिथ्याज्ञानमुमल्तु । मत्तें तप्पुदेंदोडुभयात्मकश्रद्धानमात्मनोळें तंते युभयात्मकत्वदिदं ज्ञानमुं संमिश्रमें दितु पूज्यपादाचार्य्यर्गाळिदं पेळल्पट्टुदु । मनःपर्य्ययज्ञानं मत्ते संयमविशेषसहितनोळु प्रमत्तसंयतादिक्षीणकषायपर्य्यंतमप्प गुणस्थानसप्तकदोळु तपोविशेषोपबृंहितविशुद्धिपरिणामविशिष्टनोळु संभविसुगुमितरदेशसंयतादियोळु संभविसदेकेंदोडे देशसंयतादियोळु तद्विधतपोविशेषाभावमप्पुदरिदं ।

मिथ्याज्ञानं तत् संज्ञिपंचेंद्रियपर्याप्त एव भवति, नान्यस्मिन् जीवे इति अनेन इतरत् मत्यज्ञानं श्रुताज्ञानमिति द्वय एकेंद्रियादिषु पर्याप्तापर्याप्तेषु सर्वेषु मिथ्यादृष्टिसासादनेषु संभवति इति कथितं भवति । द्वितीयः खलुशब्दः स्फुटार्थं स्फुटं ॥३०१॥ अथ सम्यग्मिथ्यादृष्टिगुणस्थाने ज्ञानस्वरूपं निरूपयति—

मिश्रोदये—सम्यग्मिथ्यात्वकर्मोदये सति अज्ञानत्रयेण सह सम्यग्ज्ञानत्रयमेव संमिश्रं भवति अशक्यविवेचनत्वेन सम्यग्मिथ्यामतिज्ञानं सम्यग्मिथ्याश्रुतज्ञानं सम्यग्मिथ्यावधिज्ञानमिति व्यपदेशभाग्भवति । सम्यग्मिथ्यादृष्टौ वर्तमानं ज्ञानत्रयं न केवलं सम्यग्ज्ञानं, न केवलं मिथ्याज्ञानं किन्तु उभयात्मकश्रद्धानवत् उभयात्मकत्वेन मिथ्याज्ञानसंमिश्रं सम्यग्ज्ञानं भवति इत्याचार्यैः कथितं ज्ञातव्यम् । मनःपर्ययज्ञानं तु संयमविशेषसहितेषु प्रमत्तसंयतादिक्षीणकषायपर्यन्तेषु सप्तगुणस्थानेषु तपोविशेषोपबृंहितविशुद्धिपरिणामविशिष्टेषु

कि जो अवधिज्ञानका विपरीत रूप विभंग नामक मिथ्याज्ञान है वह संज्ञी पंचेन्द्रिय पर्याप्तके ही होता है, अन्य जीवके नहीं होता। इससे यह व्यक्त होता है कि अन्य मतिअज्ञान और श्रुतअज्ञान ये दोनों एकेन्द्रिय आदि पर्याप्त और अपर्याप्त सब मिथ्यादृष्टि और सासादन गुणस्थानवर्ती जीवोंके होते हैं ॥३०१॥

अब सम्यग्मिथ्यादृष्टि गुणस्थानमें ज्ञानका स्वरूप कहते हैं—

मिश्र अर्थात् सम्यक्मिथ्यात्व कर्मका उदय होनेपर तीन अज्ञानोंके साथ तीनों सम्यग्ज्ञान मिले हुए होते हैं। अलग-अलग करना शक्य न होनेसे उन्हें सम्यग्मिथ्या मतिज्ञान, सम्यग्मिथ्या श्रुतज्ञान और सम्यग्मिथ्या अवधिज्ञान नामसे कहते हैं। सम्यग्मिथ्यादृष्टिमें वर्तमान तीनों ज्ञान न केवल सम्यग्ज्ञान होते हैं और न केवल मिथ्याज्ञान होते हैं किन्तु जैसे उनके सम्यक्रूप और मिथ्यारूप मिला हुआ श्रद्धान होता है वैसे ही मिथ्याज्ञान और सम्यग्ज्ञान मिला हुआ होता है यह आचार्यका कथन जानना। किन्तु मनःपर्ययज्ञान विशेष संयमसे सहित प्रमत्तसंयत नामक छठे गुणस्थानसे लेकर क्षीणकषाय नामक बारहवें गुणस्थानपर्यन्त सात गुणस्थानोंमें तपविशेषसे वृद्धिको प्राप्त विशुद्धिरूप परिणामोंसे विशिष्ट

श्रुताज्ञानत्व प्रसंगमक्कुमदरिदमुपदेशक्रियेयिल्लदे येत्तलानुमितप्पूहापोहविकल्पात्मकमप्प हिंसानृत-स्तेयाब्रह्मपरिग्रहकारणमप्पार्त्तरौद्रध्यानकारणमप्प शल्यदंडगारवसंज्ञाद्यप्रशस्तपरिणामकारणमप्प इंद्रियमनोजनितविशेषग्रहणरूपमप्प मिथ्याज्ञानमदु मत्यज्ञानमें दितु निश्चयिसल्पडुवुदु ।

आभीयमासुरक्खं भारहरामायणादि उवएसा ।
तुच्छा असाहणीया सुयअण्णाणेत्ति णं वेंति ॥३०४॥

आभीतमासुरक्षं भारतरामायणाद्युपदेशाः । तुच्छा असाधनीयाः श्रुताज्ञानमितीदं ब्रुवंति ॥

तुच्छाः परमार्त्थशून्यंगळु असाधनीयाः सत्पुरुषवर्ग्गानादरणीयंगळुमेकेंदोडे परमार्त्थशून्यत्व-दिंदं आभीतासुरक्षभारतरामायणाद्युपदेशंगळं तत्प्रबंधंगळुमवर श्रवणदिदं पुट्टिदुदावुदोंदु ज्ञानमदिदु श्रुताज्ञानमें दिताचार्य्यंरुगळु पेळ्वरु । आसमंतात् भीताः आभीताः चोरास्तच्छास्त्र-मप्याभीतं । असवः प्राणास्तेषां रक्षा येभ्यस्तेऽसुरक्षास्तलवरास्तेषां शास्त्रमासुरक्षं । कौरवपांडवीय-पंचभर्तृकैकभार्य्यावृत्तांतयुद्धव्यतिकरादिचर्च्याव्याकुलमं भारतमें बुदु । सीताहरणरामरावणीय-जातिवानरराक्षसयुद्धव्यतिकरादिस्वेच्छाकल्पनारचितमं रामायणमें बुदु । आदिशब्ददिदमावुवावुदु मिथ्यादर्शनदूषितमर्थैकांतवादिस्वेच्छाकल्पितकथाप्रबंधभुवनकोशहिंसायागादिगृहस्थकर्म्मंमुं मि-

---

बन्धनाद्युपहारादिग्रहणकारणगूढार्थविशेषादिरूप गृह्यते । उपदेशपूर्वकत्वे श्रुताज्ञानत्वप्रसंगात् । उपदेशक्रियां विना यदीदृगूहापोहविकल्पात्मकं हिंसानृतस्तेयाब्रह्मपरिग्रहकारणं आर्त्तरौद्रध्यानकारणं शल्यदण्डगारवसंज्ञाद्यप्रशस्तपरिणामकारणं च इन्द्रियमनोजनितविशेषग्रहणरूपं मिथ्याज्ञानं तन्मत्यज्ञानमिति निश्चेतव्यं ॥३०३॥

तुच्छाः परमार्थशून्याः, असाधनीया अत एव सत्पुरुषाणामनादरणीयाः परमार्थशून्यत्वात् आभीता-सुरक्षभारतरामायणाद्युपदेशाः तत्प्रबन्धाः तेषां श्रवणादुत्पन्नं यज्ज्ञानं तदिदं श्रुताज्ञानमिति ब्रुवन्त्याचार्याः । आ समन्तात् भीताः आभीताः चोराः तच्छास्त्रमप्याभीतं । असवः प्राणाः तेषां रक्षा येभ्यः ते असुरक्षाः तलवराः तेषां शास्त्रमासुरक्षं । कौरवपाण्डवीयपञ्चभर्तृकैकभार्यावृत्तान्तयुद्धव्यतिकरादिचर्चाव्याकुलं भारतं, सीताहरण-रामरावणीयजातिवानरराक्षसयुद्धव्यतिकरादिस्वेच्छाकल्पनारचितं रामायणं । आदिशब्दादन्यन्मिथ्यादर्शनदूषित-

---

हो बुद्धि होती है वह कुमति ज्ञान है। उपदेशपूर्वक होनेपर उसे कुश्रुत ज्ञानका प्रसंग आता है। अतः उपदेशके बिना जो इस प्रकारका ऊहापोह विकल्परूप हिंसा, असत्य, चोरी, विषयसेवन और परिग्रहका कारण, आर्त तथा रौद्रध्यानका कारण, शल्य, दण्ड, गारव, संज्ञा आदि अप्रशस्त परिणामोंका कारण, जो इन्द्रिय और मनसे उत्पन्न हुआ विशेष ग्रहणरूप मिथ्या-ज्ञान है वह कुमतिज्ञान है यह निश्चय करना चाहिए ॥३०३॥

तुच्छ अर्थात् परमार्थसे शून्य और इसी कारणसे सज्जनोंके द्वारा अनादरणीय आभीत, आसुरक्ष, भारत रामायण आदिके उपदेश, उनकी रचनाएँ, उनका सुनना तथा उनके सुननेसे उत्पन्न हुआ ज्ञान उसे आचार्य श्रुतअज्ञान कहते हैं। आभीत चोरको कहते हैं क्योंकि उससे सब ओरसे भय सताता है। उनके शास्त्रको भी आभीत शास्त्र कहते हैं। असु अर्थात् प्राणोंकी रक्षा जिनसे होती है वे असुरक्ष अर्थात् कोतवाल आदि उनके शास्त्रको आसुरक्ष कहते हैं। कौरव पाण्डवोंके युद्ध, पंचभर्ता द्रौपदीका वृत्तान्त, युद्धकी कथा आदिकी चर्चासे भरा महाभारत ग्रन्थ है, सीताहरण, रामकी उत्पत्ति, रावणकी जाति, वानरों और राक्षसोंके युद्धकी यथेच्छ कल्पनासे लेकर रची गयी रामायण है। आदि शब्दसे जो-जो मिथ्यादर्शनसे दूषित एकान्तवादी यथेच्छ कथाप्रबन्ध, भुवनकोश हिंसामय यज्ञादि

प्रत्ययबलात् सम्यग्दर्शनोत्पत्तिप्रतीतेर्व्विशिष्टस्यावधिज्ञानस्य भंगो विपर्य्ययो विभंगमें दितु निरुक्तिसिद्धार्त्थंविकदरिंदमे प्ररूपितत्वदिदं।

अनंतरं गाथानवकदिदं स्वरूपोत्पत्तिकारणभेदविषयंगळनाश्रयिसि मतिज्ञानमं पेळ्दपं :—

अहिमुहणियमियबोहणमाभिणिबोहियमणिंदिइंदियजं।
अवगहईहावाया धारणगा होंति पत्तेयं ॥३०६॥

अभिमुखनियमितबोधनमाभिनिबोधिकमनिंद्रियेंद्रियजं। अवग्रहेहावायधारणकाः भवंति प्रत्येकं ॥

स्थूलवर्त्तमानयोग्यदेशावस्थितोऽर्थोऽभिमुखः। अस्येंद्रियस्यायमेवार्थः इत्यवधारितो नियमितोऽभिमुखश्चासौ नियमितश्च अभिमुखनियमितस्तस्यार्त्थस्य बोधनं ज्ञानमाभिनिबोधिकमें दितु मतिज्ञानमेंबुदत्थं। अभिनिबोध एवाभिनिबोधिकमेंदितु स्वार्त्थिकठण् प्रत्ययदिदं सिद्धमक्कुं। स्पर्शनादींद्रियंगळगे स्थूलादिगळप्प स्पर्शादिस्वार्त्थंगळोळु ज्ञानजननशक्तिसंभवमप्पुदरिंदं सूक्ष्मांतरितदूरार्थंगळप्प परमाणुशंखचक्रवर्त्तिनरकस्वर्गपटलमेर्व्वादिगळोळमा इंद्रियंगळगे ज्ञानजननशक्ति संभविसदेंबुदत्थं।

इवरिदं मतिज्ञानक्के स्वरूपमं पेळल्पट्टुदु, एंतप्पुदा मतिज्ञानमें दोडे अनिंद्रियेंद्रियजं मनमुं

भवतरकारणदर्शनस्मरणानुसंधानप्रत्ययबलात् सम्यग्दर्शनोत्पत्तिप्रतीतेः। विशिष्टस्य अवधिज्ञानस्य भङ्गः—विपर्ययः विभङ्ग इति निरुक्तिसिद्धार्थस्यैव अनेन प्ररूपितत्वात् ॥३०५॥ अथ नवभिर्गाथाभिः स्वरूपोत्पत्तिकारणभेदविषयान् आश्रित्य मतिज्ञानं प्ररूपयति—

स्थूलवर्तमानयोग्यदेशावस्थितोऽर्थः अभिमुखः, अस्येन्द्रियस्य अयमेवार्थः इत्यवधारितो नियमितः। अभिमुखश्चासौ नियमितश्च अभिमुखनियमितः। तस्यार्थस्य बोधनं ज्ञानं आभिनिबोधिकं मतिज्ञानमित्यर्थः। अभिनिबोध एव आभिनिबोधकमिति स्वार्थिकेन ठण्प्रत्ययेन सिद्धं भवति। स्पर्शनादीन्द्रियाणां स्थूलादिष्वेव स्पर्शादिषु स्वार्थेषु ज्ञानजननशक्तिसंभवात्। सूक्ष्मान्तरितदूरार्थेषु परमाणुशङ्खचक्रवर्तिमेर्वादिषु तेषां ज्ञानजननशक्तिर्न संभवतीत्यर्थः। अनेन मतिज्ञानस्य स्वरूपमुक्तं। कथंभूतं तत्? अनिन्द्रियेन्द्रियजं—अनिन्द्रियं मनः,

---

क्योंकि नारकियोंके विभंग ज्ञानके द्वारा वेदनाभिभव और उसके कारणोंके दर्शन स्मरण आदि रूप ज्ञानके बलसे सम्यग्दर्शनकी उत्पत्ति होती है। 'वि' अर्थात् विशिष्ट अवधिज्ञानका भंग अर्थात् विपर्यय विभंग होता है इस निरुक्ति सिद्ध अर्थको ही यहाँ कहा है ॥३०५॥

अब नौ गाथाओंसे स्वरूप, उत्पत्ति, कारण, भेद और विषयको लेकर मतिज्ञानका कथन करते हैं—

स्थूल, वर्तमान और योग्यदेशमें स्थित अर्थको अभिमुख कहते हैं। इस इन्द्रियका यही विषय है इस अवधारणाको नियमित कहते हैं। अभिमुख और नियमितको अभिमुखनियमित कहते हैं। उस अर्थके बोधन अर्थात् ज्ञानको मतिज्ञान कहते हैं। अभिनिबोध ही आभिनिबोधिक है इस प्रकार स्वार्थमें ठण् प्रत्यय करनेसे इसकी सिद्धि होती है। स्पर्शन आदि इन्द्रियोंकी अपने स्थूल आदि स्पर्श आदि विषयोंमें ही ज्ञानको उत्पन्न करनेकी शक्ति

---

१. म स्थूलार्थं°। २. म यंतप्प। ३. ब अथ स्वरूपोत्पत्तिकारणभेदविषयान् आश्रित्य गाथानवकेन मतिज्ञानमाह। ४. ब स्थूलार्थरूपस्पर्शादि स्वार्थेषु। ५. ब णुनरकस्वर्गपटलमे°। ६. ब °पं. प्ररूपितम्।

मतिज्ञानविषयं व्यंजनमें दुमर्त्थमें दु द्विविधमक्कुं २। अल्लि इंद्रियंगळिवं प्राप्तमप्प विषयं व्यंजनमें बुदक्कुं । इंद्रियंगळिदमप्राप्तमप्प विषयमर्त्थमें बुदक्कुमा प्राप्ताप्राप्तार्थंगळोळु क्रमदिदं यथासंख्यं । आ व्यंजनार्त्थावग्रहभेदंगळेरडुं २ व्यापृतौ प्रवृत्तौ भवतः प्रवृत्तंगळप्पुवु । इंद्रियंगळिदं प्राप्तार्त्थविशेषग्रहणं व्यंजनावग्रहमक्कु--। मिंद्रियंगळिदमप्राप्तार्त्थविशेषग्रहणमर्त्थावग्रहमक्कुमें दु-पेळ्दतेरं। व्यंजनव्यक्तं शब्दादिजातमें दितु तत्त्वार्त्थविवरणंगळोळु पेळल्पट्टुदितु पेळल्पट्टोडितो व्याख्यानदोडने तु संगतमक्कुमें दोडे पेळल्पडुगुं ।

विगतमंजनमभिव्यक्तिर्य्यस्य तद्व्यंजनं। व्यज्यते मृक्ष्यते प्राप्यत इति व्यंजनमें वितंऽजगति व्यक्ति मृक्षणेषु एंदितु व्यक्तिमृक्षणार्त्थंगळ्गे ग्रहणमप्पुदरिदं। शब्दाद्यर्त्थं श्रोत्रादींद्रियदिदं प्राप्तंगुमा-वोडमेन्नेवरमभिव्यक्तमल्लन्नेवरमे व्यंजनमें दु पेळल्पट्टुदेकवारजलकणसिक्तनूतनशरावदंते मत्तम-भिव्यक्तियागुत्तिरलदे अर्त्थमक्कुमें तोगळु पुनः पुनर्ज्जलकणसिच्यमाननूतनशरावमभिव्यक्तसेक-मक्कुमवुकारणादिदं चक्षुर्म्मनस्सुगळऽप्राप्तमप्प विषयदोळु प्रथमोद्दिष्टव्यंजनावग्रहमिल्ल। चक्षु-र्म्मनस्सुगळु स्वविषयमप्पार्त्थमं प्राप्य पोद्दिये अल्लिज्ञानमं पुट्टिसुगुमें ब नैय्यायिकादिमतं स्याद्वाद-

मतिज्ञानविषयो व्यञ्जनं अर्थश्चेति द्विविधः। तत्र इन्द्रियैः प्राप्तो विषयो व्यञ्जनं[2] तैरप्राप्तः अर्थः। तयोः प्राप्ताप्राप्त[3]योरर्थयोः क्रमशः यथासंख्यं तौ व्यञ्जनार्थावग्रहभेदौ व्यापृतौ प्रवृत्तौ भवतः। इन्द्रियैः प्राप्तार्थविशेषग्रहणं व्यञ्जनावग्रहः। तैरप्राप्तार्थविशेषग्रहणं अर्थावग्रह इत्यर्थः। व्यञ्जनं–अव्यक्तं शब्दादिजातं इति तत्त्वार्थविवरणेषु[4] प्रोक्तं कथमनेन व्याख्यानेन सह संगतमिति चेदुच्यते। विगतं–अञ्जनं–अभिव्यक्तिर्यस्य तद्व्यञ्जनम्। व्यज्यते म्रक्ष्यते प्राप्यते इति व्यञ्जनं अञ्जु गतिव्यक्तिम्रक्षणेष्विति व्यक्तिम्रक्षणार्थयोर्ग्रहणात्। शब्दाद्यर्थः श्रोत्रादीन्द्रियेण प्राप्तोऽपि यावन्नाभिव्यक्तस्तावद् व्यञ्जनमित्युच्यते एकवारजलकणसिक्तनूतन-शराववत्। पुनरभिव्यक्तौ सत्यां स एवार्थो भवति। यथा पुनः पुनर्जलकणसिच्यमाननूतनशरावः अभिव्यक्तसेको भवति। अतः कारणात् चक्षुर्मनसोऽप्राप्ते विषये प्रथमो व्यञ्जनावग्रहो नास्ति। चक्षुर्मनसी स्वविषयमर्थं प्राप्यैव तत्र ज्ञानं जनयतः, इति नैयायिकादीनां मतं स्याद्वादतर्कग्रन्थेषु बहुधा निराकृतमित्यत्राहेतुवादे आगमाश्रि

मतिज्ञानका विषय दो प्रकारका है—व्यंजन और अर्थ। उनमें-से इन्द्रियोंके द्वारा प्राप्त विषयको व्यंजन और अप्राप्तको अर्थ कहते हैं। उन प्राप्त और अप्राप्त अर्थोंमें क्रमसे व्यंजनावग्रह और अर्थावग्रह प्रवृत्त होते हैं। इन्द्रियोंसे प्राप्त अर्थके विशेष ग्रहणको व्यंजनावग्रह कहते हैं, और अप्राप्त अर्थके विशेष ग्रहणको अर्थावग्रह कहते हैं।

शंका—तत्त्वार्थसूत्रकी टीकामें कहा है, शब्दादिसे होनेवाले अव्यक्त ग्रहणको व्यंजन कहते हैं। उसकी संगति इस व्याख्याके साथ कैसे सम्भव है ?

समाधान—'अंजु' धातुके तीन अर्थ हैं—गति, व्यक्ति और म्रक्षण। यहाँ उनमें-से व्यक्ति और म्रक्षण अर्थ लेकर व्यंजन शब्द बना है। 'विगतं-अंजनं-अभिव्यक्तिर्यस्य' जिसका अंजन अर्थात् अभिव्यक्ति दूर हो गया है वह व्यंजन है। यह अर्थ तत्त्वार्थकी टीकामें लिया है। 'व्यज्यते म्रक्ष्यते प्राप्यते इति व्यंजनम्' जो प्राप्त हो वह व्यंजन है यह यहाँ ग्रहण किया है। शब्द आदि रूप अर्थ श्रोत्र आदि इन्द्रियके द्वारा प्राप्त होनेपर भी जबतक व्यक्त नहीं होता तबतक उसे व्यंजन कहते हैं। जैसे एक वार जलबिन्दुसे सिक्त नया सकोरा। पुनः व्यक्त होनेपर उसे ही अर्थ कहते हैं। जैसे बार-बार जलबिन्दुओंसे सींचे जानेपर नया

१. म प्राप्तमुमेंबुदर्त्थंमं। २. ब °नमिन्द्रियैरप्राप्तो विषयोऽर्थः। ३. ब °सार्थयोः। ४. ब °णे प्रोक्तमनेन सहेदं व्याख्यानं कथं संग°।

पेळल्पट्टुदरिंदमिंद्रियार्त्थसंबंधानंतरं दर्शनं पुट्टुगुमें दु पेळ्दी गाथासूत्रदोळनुक्तमुं पूर्व्वाचार्य्यवचनानुसारदिदं व्याख्यानिसल्पट्टुदु ग्राह्यमक्कुं मेंकोळल्पडुवुदें बुदत्थं। गृहीते अवग्रहदिंदमिदु श्वेतमें दितु ज्ञातात्थंदोळु विशेषमप्प बलाकारूपक्कागलु पताकारूपक्कागलु यथावस्थितवस्तुविनाऽकांक्षे बलाकया भवितव्यमें दितु भवितव्यताप्रत्ययरूपमप्प बलाकेयोळे संजायमानमीहें यें ब द्वितीयज्ञानमक्कुमथवा पताकारूपमप्प विषयमनवलंबिसि उत्पद्यमानमनया पताकया भवितव्यमें दितु भवितव्यताप्रत्ययरूपं पताकेयोळे संजायमानाकांक्षे ईहेयें ब द्वितीयज्ञानमक्कुमिंतींद्रियांतरविषयंगळोळं मनोविषयदोळमवग्रहगृहीतदोळु यथावस्थितमप्प विशेषदाकांक्षारूपमीहें यें दितु निश्चितव्यमक्कुमेकें दोडे मतिज्ञानावरणक्षयोपशमतारतम्यभेददिदमवग्रहेहाज्ञानंगळ्गे भेदसंभवमुळ्ळुदरिंदमी सम्यग्ज्ञानप्रकरणदोळु बलाका वा पताका वा यें दितु संशयमक्कु बलाकेयोळु पताकया भवितव्यमें दितु विपर्य्ययमक्कुमी मिथ्याज्ञानंगळ्गनवतारमें दरियल्पडुगुं।

ज्ञानं छद्मस्थानां' इति श्रीनेमिचन्द्रसैद्धान्तचक्रवर्तिभिरपि प्रोक्तत्वात्, इन्द्रियार्थसंबन्धानन्तरं दर्शनमुत्पद्यते इत्येतस्मिन् गाथासूत्रे अनुक्तमपि पूर्वाचार्यवचनानुसारेण व्याख्यानं ग्राह्यमित्यर्थः। गृहीते–अवग्रहेण इदं श्वेतमिति ज्ञाते अर्थविशेषस्य बलाकारूपस्य पताकारूपस्य वा यथावस्थितवस्तुन आकाङ्क्षा बलाकया भवितव्यमिति भवितव्यताप्रत्ययरूपं बलाकायामेव संजायमानं ईहाख्यं द्वितीयं ज्ञानं भवेत्। अथवा पताकारूपं विषयमालम्ब्य उत्पद्यमाना अनया पताकया भवितव्यमिति भवितव्यताप्रत्ययरूपा पताकायामेव संजायमाना आकाङ्क्षा ईहेति द्वितीयं ज्ञानं भवेत्। एवं इन्द्रियान्तरविषयेषु मनोविषये च अवग्रहगृहीते यथावस्थितरूपविशेषस्य आकाङ्क्षारूपा ईहेति निश्चेतव्यम्। मतिज्ञानावरणक्षयोपशमस्य तारतम्यभेदेन अवग्रहेहाज्ञानयोर्भेदसंभवात्। अस्मिन् सम्यग्ज्ञानप्रकरणे बलाका वा पताका इति संशयस्य, बलाकाया पताकया भवितव्यमिति विपर्ययस्य च मिथ्याज्ञानस्यानवतारात् ॥३०८॥

अनन्तर अर्थके आकारादिको लिये हुए जो सविकल्प ज्ञान होता है वह अवग्रह है। श्री नेमिचन्द्र सिद्धान्त चक्रवर्तीने भी कहा है कि छद्मस्थोंके दर्शनपूर्वक ज्ञान होता है। यद्यपि इस गाथासूत्रमें यह नहीं कहा है कि इन्द्रिय और अर्थका सम्बन्ध होनेके अनन्तर दर्शन उत्पन्न होता है। फिर भी पूर्वाचार्योंके वचनके अनुसार व्याख्यान करना चाहिए। 'गृहीते' अर्थात् अवग्रहके द्वारा 'यह श्वेत है' ऐसा जाननेपर बलाकारूप या पताकारूप यथावस्थित अर्थको जाननेकी आकांक्षा यह बलाका—बगुलोंकी पंक्ति होना चाहिए इस प्रकार बगुलोंकी पंक्तिमें ही जो भवितव्यतारूप ज्ञान होता है वह ईहा है। अथवा पताकारूप विषयका आलम्बन लेकर अर्थात् यदि अवग्रहसे जानी हुई श्वेत वस्तु पताका प्रतीत हो तो यह पताका होनी चाहिए, इस प्रकार जो पताकामें ही भवितव्यता प्रत्ययरूप आकांक्षा होती है वह दूसरा ईहा ज्ञान है। इस प्रकार अन्य इन्द्रियोंके विषयमें और मनके विषयमें अवग्रहसे गृहीत वस्तुमें यथावस्थित विशेषकी आकांक्षारूप ज्ञान ईहा है यह निश्चय करना चाहिए। मतिज्ञानावरणके क्षयोपशमकी हीनाधिकताके भेदसे अवग्रह और ईहा ज्ञानमें भेद होता है। इस सम्यग्ज्ञानके प्रकरणमें 'यह बलाका है या पताका' इस संशयको तथा बलाकामें यह पताका होनी चाहिए, इस विपरीत मिथ्याज्ञानको स्थान नहीं है ॥३०८॥

१. ब °तार इति शाठ्यम्।

ओंदानुमोंदु वस्तुविन प्रदेशात् एकदेशदोडनविनाभावियप्पव्यक्तमप्प वस्तुविन ग्रहणमनिसृतज्ञानमेंबुदयवा ओंदु वस्तुविन एकदेशमं मेणु सकलं वस्तुवं मेगाळंबिसिकोंडु मत्तमन्यवस्तुविन गतिः ज्ञानमावुदो वदुवुमनिःसृतज्ञानमक्कुमदक्कुदाहरणमं तोरिदपं ।

पुक्खरगहणे काले हत्थिस्स य वदणगवयगहणे वा ।
वत्थंतरचंदस्स य घेणुस्स य बोहणं च हवे ॥३१३॥

पुष्करग्रहणे काले हस्तिनश्च वदनगवयग्रहणे वा । वस्त्वंतरचंद्रस्य च धेनोश्च बोधनं च भवेत् ॥

जलदिंदं पोरगे दृश्यमानमप्प पुष्करद जलमग्नहस्तिकराग्र ग्रहणकालदोळु, दर्शनकालदोळु तदविनाभावि जलमग्नहस्तिग्रहणं जलदोळु हस्तिमग्ननिर्द्दपुदेंदितु प्रतीति वा इव एंतेंते इदरिंदमी साध्याविनाभावनियमनिश्चयमनुळ्ळ साधनदत्तणि "साधनात्साध्यविज्ञानमनुमानमें"दितु अनुमानप्रमाणं संगृहीतमक्कुं । अथवा ओंदानुमोव्वं युवतिय वदनग्रहणकाले वदनदर्शनकालदोळे वस्त्वंतरचंद्रग्रहणं मुखसादृश्यदिदं चंद्रस्मरणं चंद्रसदृशं मुखमें दितु प्रत्यभिज्ञानं मेणरण्यदोळु गवयग्रहणकाले गवयदर्शनकालदोळे धेनुविन बोधनं धेनुविन स्मरणं गोसदृशं गवयमें दितु प्रत्यभिज्ञानं मेणु भवेत् अक्कुं । अनंतरगाथोक्तमप्पनिःसृतज्ञानविकल्पनितुमुदाहरणंगळु । वा शब्दं पक्षांतरसूचकं मेणु एंतीगळु

कस्यचिद्वस्तुनः, प्रदेशाद्-एकदेशाद् व्यक्तात् तदविनाभाविनोऽव्यक्तस्य वस्तुनो ग्रहणं अनिसृतज्ञानम् । अथवा एकस्य वस्तुनः एकदेशं वा सकलं वस्तु वा अवलम्ब्य गृहीत्वा पुनरन्यस्य वस्तुनो गतिः—ज्ञानं यत्, तदप्यनिसृतज्ञानं भवति ॥३१२॥ तदुदाहरति—

पुष्करस्य जलाद्बहिर्दृश्यमानस्य जलमग्नहस्तिकराग्रस्य ग्रहणकाले दर्शनकाले एव तदविनाभाविजलमग्नहस्तिग्रहणं जले हस्ती मग्नोऽस्तीति प्रतीतिः । वा इव यथा अनेन अस्मात् साध्याविनाभावनियमनिश्चयात् साधनात् साध्यस्य ज्ञानमनुमानमिति अनुमानप्रमाणं संगृहीतं भवति । अथवा कस्याश्चित् युवतेर्वदनग्रहणकाले वस्त्वन्तरस्य चन्द्रस्य ग्रहणम् । मुखसादृश्याच्चन्द्रस्य स्मरणं चन्द्रसदृशं मुखमिति प्रत्यभिज्ञानं वा । अरण्ये गवयग्रहणकाले गवयदर्शनकाल एव धेनोर्बोधनं स्मरणं गोसदृशो गवय इति प्रत्यभिज्ञानं वा भवेत् । वा इव

किसी वस्तुके प्रकट हुए एकदेशको देखकर उसके अविनाभावी अप्रकट अंशको ग्रहण करना अनिसृत ज्ञान है। अथवा एक वस्तुके एकदेश या समस्त वस्तुको ग्रहण करके अन्य वस्तुको जानना भी अनिसृत ज्ञान है ॥३१२॥

उसका उदाहरण देते हैं—

जलमें डूबे हुए हाथीकी जलसे बाहर दिखाई देनेवाली सूँड़को देखते ही उसके अविनाभावी जलमग्न हस्तिका ग्रहण अनिसृत ज्ञान है। इससे, जिसका साध्यके साथ अविनाभाव नियम निश्चित है ऐसे साधनसे साध्यके ज्ञानको अनुमान कहते हैं इस अनुमान प्रमाणका संग्रह होता है। अथवा किसी युवतीके मुखको ग्रहण करते समय अन्य वस्तु चन्द्रमाका ग्रहण अथवा मुखकी समानतासे चन्द्रमाका स्मरण कि चन्द्रके समान मुख है अथवा गवयको देखते ही गायका स्मरण या गौके समान गवय है यह प्रत्यभिज्ञान इससे गृहीत होता है। 'वा' शब्द उदाहरणके प्रदर्शनमें प्रयुक्त हुआ है। जो बतलाता है कि अनन्तर

१. म °भावियप्प प्रतीत्यनिश्चयदत्तणिंद साधना° ।

मतिज्ञानं सामान्यापेक्षेयिदमोंदु १। अवग्रहेहावायधारणापेक्षेयिदं नाल्कु ४। इंद्रियानिंद्रियजनितार्थावग्रहेहावायधारणापेक्षेयिदं चतुर्विंशति २४। अर्थव्यंजनोभयावग्रहापेक्षेयिदं अष्टाविंशतिगळुमप्पु २८। विंतु नाल्कुं स्थानंगळं त्रिःप्रतिकंगळं माडि यथाक्रमं प्रथमस्थानचतुष्टयमं विषयसामान्यदिदेमोंदरिदं गुणिसुवुदु। द्वितीयस्थानचतुष्टयमं बह्वादिविषयगळाररिदं गुणिसिदुदु। तृतीयस्थानचतुष्टयमं बह्वादिद्वादशविषयंगळिदं गुणिसुवुदितु गुणिसुत्तमिरलु मतिज्ञानदोळु विषयसामान्यार्धविषयसर्वविषयापेक्षंगळप्प स्थानंगळप्पुवु

२८। १	२८। ६	२८। १२
२४। १	२४। ६	२४। १२
४। १	४। ६	४। १२
१। १	१। ६	१। १२

अनंतरं श्रुतज्ञानप्ररूपणेयं प्रारंभिसुवातं मोदलोळन्नेवरं तत्सामान्यलक्षणमं पेळ्दपं :—

अत्थादो अत्यंतरमुवलंभं तं भणंति सुदणाणं।
आभिणिबोहियपुव्वं णियमेणिह सद्दजं पमुहं ॥३१५॥

अर्थादर्थांतरमुपलभमानं तद्भणंति श्रुतज्ञानमाभिनिबोधिकपूर्वं नियमेनेह शब्दजं प्रमुखं ॥

मतिज्ञानं सामान्येन एकं १। अवग्रहेहावायधारणापेक्षया चत्वारि ४। इन्द्रियानिन्द्रियजनितार्थावग्रहेहावायधारणापेक्षया चतुर्विंशतिः २४। अर्थव्यञ्जनोभयावग्रहापेक्षया अष्टाविंशतिः २८। एतानि चत्वारि स्थानानि त्रिःप्रतिकानि—

२८। १	२८। ६	२८। १२
२४। १	२४। ६	२४। १२
४। १	४। ६	४। १२
१। १	१। ६	१। १२

कृत्वा यथाक्रमं प्रथमं स्थानचतुष्टयं विषयसामान्येनैकेन गुणयेत्। द्वितीयं स्थानचतुष्टयं बह्वादिविषयषट्केन गुणयेत्। तृतीयं स्थानचतुष्टयं बह्वादिभिर्द्वादशविषयैर्गुणयेत्। एवं गुणिते सति मतिज्ञाने सामान्यविषयार्धविषयसर्वविषयापेक्षया स्थानानि भवन्ति ॥३१४॥ अथ श्रुतज्ञानप्ररूपणा प्रारभमाणः[1] प्रथमस्तावत्तत्सामान्यलक्षणमाह—

मतिज्ञान सामान्यसे एक है। अवग्रह, ईहा, अवाय और धारणाकी अपेक्षा चार हैं। इन्द्रिय और मनसे उत्पन्न अवग्रह, ईहा, अवाय और धारणाकी अपेक्षा चौबीस हैं। अर्थावग्रह और व्यंजनावग्रहकी अपेक्षा अठाईस हैं। इन चारों स्थानोंको तीन जगह स्थापित करके यथाक्रम प्रथम चार स्थानोंको सामान्य विषय एकसे गुणा करना चाहिए। दूसरे चार स्थानोंको बहु आदि छह विषयोंसे गुणा करना चाहिए। तीसरे चार स्थानोंको बहु आदि बारह विषयोंसे गुणा करना चाहिए। इस तरह गुणा करनेपर मतिज्ञानके सामान्य विषय, बहु आदि छह अर्धविषय और सर्व विषयकी अपेक्षा स्थान होते हैं। यथा—॥३१४॥

२८×१	२८×६	२८×१२
२४×१	२४×६	२४×१२
४×१	४×६	४×१२
१×१	१×६	१×१२

अथ श्रुतज्ञान प्ररूपणाको प्रारम्भ करते हुए पहले श्रुतज्ञानका सामान्य लक्षण कहते हैं—

१. म॰ दिर गुं। २. ब॰ णं प्ररूपयति।

अर्थांतरज्ञानद प्रतिपादकमप्पुदु परमागमदोळु रूढमक्कुमोंदानुमोंदु प्रकारदिंदं कथंचित् निरुक्ति-संभविप रूढिशब्ददोळजहत्स्वार्थवृत्तिकदोळु कुशं लातीति कुशलः एंदितु कुशलादिशब्दंगळोळु निपुणाद्यर्थंगळु रूढंगळा रूढार्थंगळोळु तत्कुशलशब्दनिरुक्ति येंतंते अरियल्पडुगुमल्लि जीवोऽस्ति येंदितु नुडियल्पडुत्तिरलु जीवोऽस्ति येंदितो शब्दज्ञानं श्रोत्रेंद्रियप्रभवमतिज्ञानमक्कुमा ज्ञानदिंदं जीवोऽस्तिशब्दवाच्यरूपात्मास्तित्वदोळु वाच्यवाचकसंबंधसंकेतसंकलनमा पूर्व्वकमागि आवुदोंदु ज्ञानं पुट्टुगुमदक्षरात्मकश्रुतज्ञानमक्कुमेकेंदोडक्षरात्मकशब्दसमुत्पन्नत्वदिंदं कार्य्यदोळु कारणोपचारमुंटप्पुदरिदं । वातशीतस्पर्शज्ञानदिंदं वातप्रकृतिगे तत्स्पर्शनदोळमनोज्ञज्ञानमनक्षरात्मकलिंगजमप्प श्रुतज्ञानमेंबुदक्कुमेकेंदोडे शब्दपूर्व्वकत्वाभावमप्पुदरिदं ।

लोगाणमसंखमिदा अणक्खरप्पे हवंति छट्ठाणा ।
वेरूवछट्ठवग्गपमाणं रूऊणमक्खरगं ॥३१६॥

लोकानामसंख्यमितान्यनक्षरात्मके भवंति षट्स्थानानि। द्विरूपषष्ठवर्गप्रमाणं रूपोनमक्षरगं॥

प्रधानं भवति । श्रूयते—श्रोत्रेन्द्रियेण गृह्यते इति श्रुतः शब्दः, तस्मादुत्पन्नमर्थज्ञानं श्रुतज्ञानमिति व्युत्पत्तेरपि अक्षरात्मकप्राधान्याश्रयणात् । अथवा श्रुतमिति रूढिशब्दोऽयं मतिज्ञानपूर्वकस्य अर्थान्तरज्ञानस्य प्रतिपादकः परमागमे रूढः । यथाकथंचिन्निरुक्तिसंभवः रूढिशब्दे अजहत्स्वार्थवृत्तिः कुशं लातीति कुशल इति कुशलादिशब्देषु निपुणाद्यर्थेषु रूढेषु तन्निरुक्तिवत् । तत्र जीवोऽस्तीत्युक्ते जीवोऽस्तीति[3] शब्दज्ञानं श्रोत्रेन्द्रियप्रभवं मतिज्ञानं भवति । तेन ज्ञानेन जीवोऽस्तीति शब्दवाच्यरूपे आत्मास्तित्वे वाच्यवाचकसंबन्धसंकेतसंकलनपूर्वकं यत् ज्ञानमुत्पद्यते तदक्षरात्मकं श्रुतज्ञानं भवति, अक्षरात्मकशब्दसमुत्पन्नत्वेन कार्ये कारणोपचारात् । वातशीतस्पर्शज्ञानेन वातप्रकृतिकस्य तत्स्पर्शे अमनोज्ञज्ञानमनक्षरात्मकं लिङ्गजं श्रुतज्ञानं भवति, शब्दपूर्वकत्वाभावात् ॥३१५॥ अथ श्रुतज्ञानस्य अक्षरानक्षरात्मकभेदौ प्ररूपयति—

श्रुत अर्थात् शब्द है। उससे उत्पन्न अर्थज्ञान श्रुतज्ञान है। इस व्युत्पत्तिसे भी अक्षरात्मक श्रुतज्ञानकी प्रधानता लक्षित होती है। अथवा 'श्रुत' यह रूढ़ि शब्द है। परमागममें मतिज्ञानपूर्वक होनेवाले अन्य अर्थके ज्ञानको कहनेमें रूढ़ है। फिर भी यथायोग्य निरुक्ति होती है। रूढ़ि शब्द अपने अर्थको नहीं छोड़ते। जैसे कुशको जो लाता है वह कुशल है इस प्रकार कुशल आदि शब्द चतुर आदि अर्थोंमें रूढ़ हैं फिर भी उनकी व्युत्पत्ति उसी प्रकार की जाती है। इसी प्रकार श्रुतके सम्बन्धमें जानना। 'जीव है' ऐसा कहनेपर यह जो शब्दका ज्ञान होता है कि 'जीव है,' यह श्रोत्रेन्द्रियसे उत्पन्न हुआ मतिज्ञान है। और ज्ञानके द्वारा 'जीव है' इस शब्दके वाच्यरूप आत्माके अस्तित्वमें वाच्यवाचक सम्बन्धके संकेत ग्रहणपूर्वक जो ज्ञान उत्पन्न होता है वह अक्षरात्मक श्रुतज्ञान है। क्योंकि अक्षरात्मक शब्दसे उत्पन्न हुआ है इस प्रकार कार्यमें कारणका उपचार किया है। तथा वायुके शीत स्पर्शके ज्ञानसे वात प्रकृतिवाले मनुष्यको जो उसके स्पर्शमें 'यह मेरे लिए अनुकूल नहीं है' ऐसा जो ज्ञान होता है वह अनक्षरात्मक लिंगजन्य श्रुतज्ञान है क्योंकि वह शब्दपूर्वक नहीं हुआ है ॥३१५॥

अब श्रुतज्ञानके अक्षरात्मक और अनक्षरात्मक भेदोंको कहते हैं—

१. म °लनपूर्वं संकलनमागि । २. म कार्यंकारणो । ३. ब °स्त्येवद्ज्ञानं ।

[illegible] पर्य्यायमुं अक्षरं च अक्षरमुं पदं च पदमुं संघातश्चेति संघातमुमें दितु द्वंद्वैकत्वं प्रतिपत्तिक[illegible]नुयोगश्च प्रतिपत्तिकमुमनुयोगमुमें दित्लियुमंते द्वंद्वैकत्वमक्कुं। द्विकवार-[illegible] च प्राभृतकप्राभृतकमुं प्राभृतकमें वुं वस्तु वस्तुवें वुं पूर्व्वं च पूर्व्वमुमेंदितु दशभेदंगळप्पुवु। [illegible] पर्य्याय[illegible] पत्तुं समासंगळिदं कूडि श्रुतज्ञानं विंशतिविधमुमक्कुमल्लि अक्षरादि [illegible] विंशतिविधत्वनियमदोळु हेतुवं पेळ्दपं।

[illegible] भवंति अप्युर्वेदितु इतिशब्दक्के हेत्वर्थंवृत्ति सिद्ध[illegible]। [illegible] अक्षरमक्षरसमासश्च पदं पदसमासश्च संघातः संघातसमासश्च [illegible] अनुयोगोऽनुयोगसमासश्च प्राभृतकप्राभृतकं प्राभृतकप्राभृतक-[illegible] वस्तु वस्तुसमासश्च पूर्वं पूर्व्वसमासश्चेति एंदितु तवा-[illegible]।

[illegible] गाथाचतुष्टयमं पेळ्दपं।

[illegible] गुरुमजस्स दु पज्जयं णाणं।
[illegible] पुण तदणंतरणाणभेदम्मि ॥३१९॥

[illegible] पर्य्यायं ज्ञानं। पर्य्यायावरणं पुनस्तदनंतरज्ञानभेदे॥

[illegible] अक्षरं च पदं च संघातश्चेति द्वन्द्वैकत्वम्। प्रतिपत्ति-[illegible]। द्विकवारप्राभृतकं च प्राभृतकप्राभृतकमित्यर्थः। प्राभृतकं [illegible] पूर्वोक्ताः पर्यायादीना दशभिः समासैः मिलित्वा श्रुतज्ञानं [illegible] विंशतिविधत्वनियमे हेतुमाह— [illegible] भवन्ति इति इतिशब्दस्य हेत्वर्थवृत्तिसिद्धेः। [illegible] पदं, पदसमासश्च, संघातः, संघातसमासश्च, [illegible] प्राभृतकप्राभृतकं, प्राभृतकप्राभृतकसमासश्च, [illegible] पूर्वसमासश्चेति [illegible] भवति ॥३१७–३१८॥ [illegible]—

[illegible] प्रतिपत्तिक, अनुयोग, प्राभृत प्राभृतक, प्राभृतक, वस्तु, पूर्व [illegible] श्रुतज्ञानके बीस भेद होते हैं—अर्थात् [illegible] अक्षर, अक्षरसमास, पद, पदसमास, प्रतिपत्तिक, प्रतिपत्तिकसमास, [illegible] प्राभृतक प्राभृतक, प्राभृतक प्राभृतकसमास, वस्तु, वस्तुसमास, [illegible]। यहाँ अक्षरादिके द्वारा कहे जानेवाले अर्थका [illegible] बीस ही होनेमें हेतु कहते हैं कि श्रुत-[illegible]। यहाँ 'इति' शब्द हेतुके अर्थमें है। इसलिए श्रुतज्ञानके [illegible] भेद हैं [illegible]

[illegible] गाथाओंसे कहते हैं—

सुहुमणिगोद अपज्जत्तयस्स जादस्स पढमसमयम्हि ।
हवदि हु सव्वजहण्णं णिच्चुग्घाडं णिरावरणं ॥३२०॥

सूक्ष्मनिगोदापर्य्याप्तकस्य जातस्य प्रथमसमये भवति खलु सर्व्वजघन्यं नित्योद्घाटं निरावरणं ॥

सूक्ष्मनिगोदलब्ध्यपर्य्याप्तक जननद प्रथमसमयदोळु निरावरणं प्रच्छादनरहितमप्प नित्योद्घाटं सर्व्वदा प्रकाशमानमप्प सर्व्वजघन्यं सर्व्वनिकृष्टशक्तिकमप्प पर्य्यायमें व श्रुतज्ञानमक्कुं। खलु । ई गाथासूत्रं पूर्व्वाचार्य्यप्रसिद्धं स्वोक्तार्थसंप्रतिपत्तिप्रदर्शनार्थमागि उदाहरणत्वदिं बरेयल्पट्टुदु ।

सुहुमणिगोद अपज्जत्तगेसु सगसंभवेसु भमिऊण ।
चरिमापुण्णतिवक्काणादिमवक्कट्ठियेव हवे ॥३२१॥

सूक्ष्मनिगोदलब्ध्यपर्य्याप्तगतेषु स्वसंभवेषु भ्रमित्वा । चरमापूर्णत्रिवक्राणामाद्यवक्रस्थित एव भवेत् ॥

सूक्ष्मनिगोदलब्ध्यपर्याप्तनोळु संद स्वसंभवेषु द्वादशोत्तरषट्सहस्रप्रमितंगळप्प भवेषु भवंगळोळु भ्रमित्वा भ्रमिसि चरमापूर्णभवद त्रिवक्रविग्रहगतियिंदमुत्पन्नजीवन प्रथमवक्रद प्रथमसमयदोळिर्द्दंगेये मुंपेळ्द सर्व्वजघन्यपर्य्यायमें ब श्रुतज्ञानमक्कुं । मत्तल्लिये तज्जीवक्के स्पर्शनेंद्रियप्रभवसर्व्वजघन्यमतिज्ञानमचक्षुर्द्दर्शनावरणक्षयोपशमसमुद्भूताचक्षुर्द्दर्शनमुमक्कुमेकें दोडे·

सूक्ष्मनिगोदलब्ध्यपर्याप्तकस्य जातं–जननं तस्य प्रथमसमये निरावरणं–प्रच्छादनरहितं नित्योद्घाटं अतएव सर्वदा प्रकाशमानं सर्वजघन्यं–सर्वनिकृष्टशक्तिकं पर्यायाख्यं श्रुतज्ञानं भवति । खलु एतद्गाथासूत्रं पूर्वाचार्यप्रसिद्धं–स्वोक्तार्थसंप्रतिपत्तिप्रदर्शनार्थं उदाहरणत्वेन लिखितम् ॥३२०॥

सूक्ष्मनिगोदलब्ध्यपर्याप्तकेषु स्वसंभवेषु द्वादशोत्तरषट्सहस्रप्रमितेषु भवेषु भ्रमित्वा चरमापूर्णभवस्य त्रिवक्रविग्रहगत्या उत्पन्नस्य जीवस्य प्रथमवक्रसमये स्थितस्यैव पूर्वोक्तं सर्वजघन्यं पर्यायाख्यं श्रुतज्ञानं भवति तत्रैव तस्य जीवस्य स्पर्शनेन्द्रियप्रभवं सर्वजघन्यं मतिज्ञानं, अचक्षुर्दर्शनावरणक्षयोपशमसंभूतं अचक्षुर्दर्शनमपि

सूक्ष्मनिगोदिया लब्ध्यपर्याप्तकके जन्मके प्रथम समय पर्यायनामक श्रुतज्ञान होता है। यह निरावरण है इसीसे सर्वदा प्रकाशमान रहता है, सबसे जघन्य अर्थात् निकृष्ट शक्तिवाला होता है। यह गाथा सूत्र प्राचीन है यहाँ ग्रन्थकारने अपने कथनकी यथार्थता दिखलानेके लिए उदाहरणके रूपमें लिखा है ॥३२०॥

सूक्ष्म निगोद लब्ध्यपर्याप्तक जीव अपने सूक्ष्म निगोद लब्ध्यपर्याप्तक सम्बन्धी छह हजार बारह भवोंमें भ्रमण करके अन्तिम लब्ध्यपर्याप्तक भवमें तीन मोड़ेवाली विग्रहगतिसे उत्पन्न होकर प्रथम मोड़के समयमें स्थित होता है उसके ही सबसे जघन्य पर्याय श्रुतज्ञान होता है। उसी समय उसके स्पर्शन इन्द्रियजन्य सबसे जघन्य मतिज्ञान होता है और अचक्षुदर्शनावरणके क्षयोपशमसे उत्पन्न अचक्षुदर्शन भी होता है। यहाँ ही सबसे जघन्य पर्याय श्रुतज्ञान होनेका कारण यह है कि बहुत क्षुद्रभवोंमें भ्रमण करनेसे उत्पन्न हुए बहुत

१. ब स्पर्शनाय ।

उउ४	उउ४	उउ५	उउ४	उउ४	उउ५	उउ४	उउ४	उउ६
उउ४	उउ४	उउ५	उउ४	उउ४	उउ५	उउ४	उउ४	उउ६
उउ४	उउ४	उउ५	उउ४	उउ४	उउ५	उउ४	उउ४	उउ७
उउ४	उउ४	उउ५	उउ४	उउ४	उउ५	उउ४	उउ४	उउ६
उउ४	उउ४	उउ५	उउ४	उउ४	उउ५	उउ४	उउ४	उउ६
उउ४	उउ४	उउ५	उउ४	उउ४	उउ५	उउ४	उउ४	उउ७
उउ४	उउ४	उउ५	उउ४	उउ४	उउ५	उउ४	उउ४	उउ६
उउ४	उउ४	उउ५	उउ४	उउ४	उउ५	उउ४	उउ४	उउ६
उउ४	उउ४	उउ५	उउ४	उउ४	उउ५	उउ४	उउ४	उउ८

इस प्रकार षट्स्थान वृद्धियोंका क्रम दिखलाया। यन्त्रमें दर्शित रचनाके अनुसार श्रोताजनोंको बिना व्यामोहके जानना चाहिए। इस यन्त्रका स्पष्टीकरण इस प्रकार है—

पर्याय नामक श्रुतज्ञानके भेदसे अनन्तभागवृद्धि युक्त पर्याय समास नामक श्रुतज्ञानका प्रथम भेद होता है। इस प्रथम भेदसे अनन्तभागवृद्धि युक्त पर्याय समासका दूसरा भेद होता है। इस प्रकार सूच्यंगुलके असंख्यातवें भाग प्रमाण अनन्त भाग वृद्धि होनेपर एक बार असंख्यात भागवृद्धि होती है। ऊपर यन्त्रमें प्रथम पंक्तिके प्रथम कोठेमें दो बार उकार लिखा है वह सूच्यंगुलके असंख्यातवें भाग प्रमाण अनन्त भाग वृद्धिकी पहचान जानना। उसके आगे चारका अंक लिखा वह एक बार असंख्यात भाग वृद्धिकी पहचान जानना। इसके ऊपर सूच्यंगुलके असंख्यातवें भाग प्रमाण अनन्त भागवृद्धि होनेपर दूसरी बार असंख्यात भाग वृद्धि होती है। इसी क्रमसे सूच्यंगुलके असंख्यातवें भाग प्रमाण असंख्यात भाग वृद्धि होती है। इसीसे यंत्रमें प्रथम पंक्तिके दूसरे कोठेमें प्रथम कोठाकी तरह दो उकार और एक चारका अंक लिखा है जो दो बार सूच्यंगुलके असंख्यातवें भाग बारका सूचक है। अतः दूसरी बार लिखनेसे सूच्यंगुलके असंख्यातवें भाग बार जानना। उससे आगे सूच्यंगुलके असंख्यातवें भाग प्रमाण अनन्त भाग वृद्धि होनेपर एक बार असंख्यात भाग वृद्धि होती है। अतः प्रथम पंक्तिके तीसरे कोठेमें दो उकार और एक पाँचका अंक लिखा है। आगे जैसे पहले अनन्त भाग वृद्धिको लिये सूच्यंगुलके असंख्यातवें भाग प्रमाण असंख्यात भाग वृद्धिके होनेपर पीछे सूच्यंगुलके असंख्यातवें भाग प्रमाण अनन्त भाग वृद्धिके होनेपर एक बार संख्यात भाग वृद्धि हुई वैसे ही उसी क्रमसे दूसरी संख्यात भाग वृद्धि हुई। इसी क्रमसे तीसरी हुई। इस प्रकार संख्यात भाग वृद्धि भी सूच्यंगुलके असंख्यातवें भाग प्रमाण बार होती है। इससे ऊपर यन्त्रमें प्रथम पंक्तिमें जैसे तीन कोठे किये थे वैसे ही सूच्यंगुलके असंख्यातवें भागकी पहचानके लिए दूसरे तीन कोठे उसी प्रथम पंक्तिमें किये। यहाँसे आगे सूच्यंगुलके असंख्यातवें भाग प्रमाण अनन्त भाग वृद्धिके होनेपर एक बार असंख्यात भाग वृद्धि होती है। इस प्रकार सूच्यंगुलके असंख्यातवें भाग प्रमाण असंख्यात भाग वृद्धि होती है। उसकी पहचानके लिए यन्त्रमें दो उकार और चारका अंक लिये दो कोठे किये। इससे आगे सूच्यंगुलके असंख्यातवें भाग प्रमाण अनन्त भाग वृद्धि होनेपर एक बार संख्यात गुण वृद्धि होती है। सो उसकी पहचानके लिए प्रथम पंक्तिके नौवें कोठेमें दो उकार और छहका अंक लिखा। जैसे प्रथम पंक्तिका क्रम रहा उसी प्रकार आदिसे लेकर सब क्रम दूसरी बार होनेपर एक बार दूसरी संख्यातगुणवृद्धि होती है। इसी क्रमसे सूच्यंगुलके असंख्यातवें भाग प्रमाण संख्यातगुणवृद्धि

पर्य्यायसमासश्रुतज्ञानविकल्पंगळोळु सर्व्वजघन्यप्रथमविकल्पमक्कु ज $\frac{\overline{१६}}{१६}$ मिदरनंतैकभागमनल्लिये समच्छेदं माडि कूडुत्तिरलुमक्कु पर्य्यायसमासद्वितीयज्ञानविकल्पमक्कु ज $\frac{\overline{१६}}{१६}$ $\frac{\overline{१६}}{१६}$ मदरनंतैकभागमनल्लिये समच्छेदं माडि कूडुत्तं विरलु पर्य्यायसमासतृतीयज्ञानविकल्पमक्कु ज $\frac{\overline{१६}}{१६}$ $\frac{\overline{१६}}{१६}$ $\frac{\overline{१६}}{१६}$ मदरनंतैकभागमनल्लिये समच्छेदं माडि कूडिदोडे पर्य्यायसमासचतुर्त्थज्ञानविकल्पमक्कु ज $\frac{\overline{१६}}{१६}$ $\frac{\overline{१६}}{१६}$ $\frac{\overline{१६}}{१६}$ $\frac{\overline{१६}}{१६}$ मदरनंतैकभागमनल्लिवे समच्छेदं माडि कूडिदोडे पर्य्यायसमासपंचमश्रुतज्ञानविकल्पमक्कु ज $\frac{\overline{१६}}{१६}$ $\frac{\overline{१६}}{१६}$ $\frac{\overline{१६}}{१६}$ $\frac{\overline{१६}}{१६}$ $\frac{\overline{१६}}{१६}$ मदरनंतैकभागमनल्लिये समच्छेदं माडि कूडु-

---

ज्ञानविकल्पेषु सर्वजघन्यप्रथमविकल्पः स्यात् ज $\frac{\overline{१६}}{१६}$ अस्यानन्तैकभागे ज $\frac{\overline{१६}}{१६ । १६}$ अस्मिन्नेव समच्छेदेन युते स पर्यायसमासद्वितीयज्ञानविकल्पः ज $\frac{\overline{१६}}{१६}$ । $\frac{\overline{१६}}{१६}$ । अस्यानन्तैकभागे अस्मिन्नेव समच्छेदेन युते पर्यायसमासतृतीयज्ञानविकल्पः ज $\frac{\overline{१६}}{१६}$ । $\frac{\overline{१६}}{१६}$ । $\frac{\overline{१६}}{१६}$ । अस्यानन्तैकभागे अस्मिन्नेव समच्छेदेन युते पर्यायसमासचतुर्थज्ञानविकल्पः ज $\frac{\overline{१६}}{१६}$ । $\frac{\overline{१६}}{१६}$ । $\frac{\overline{१६}}{१६}$ । $\frac{\overline{१६}}{१६}$ । अस्यानन्तैकभागे अस्मिन्नेव समच्छेदेन युते पर्यायसमासपञ्चमश्रुतज्ञानविकल्पः । ज $\frac{\overline{१६}}{१६}$ । $\frac{\overline{१६}}{१६}$ । $\frac{\overline{१६}}{१६}$ । $\frac{\overline{१६}}{१६}$ । $\frac{\overline{१६}}{१६}$ । अस्यानन्तैकभागे अस्मिन्नेव समच्छेदेन

आवे उसे उस तीसरे भेदमें मिलानेपर पर्याय समास ज्ञानका चतुर्थ विकल्प आता है। यह चतुर्थ अनन्त भाग वृद्धि हुई। फिर इस चतुर्थ भेदमें अनन्तसे भाग देकर जो एक भाग आवे उसे उस चतुर्थ विकल्पमें मिलानेपर पर्याय समासका पंचम विकल्प आता है। यह पाँचवीं अनन्तभाग वृद्धि हुई। फिर उस पाँचवें भेदमें अनन्तसे भाग देनेपर जो भाग आता है उसे पाँचवें भेदमें मिलानेपर पर्याय समासका छठा विकल्प आता है। यह छठी अनन्त भाग वृद्धि हुई। इसी प्रकार सूच्यंगुलके असंख्यातवें भाग प्रमाण अनन्त भाग वृद्धि होनेपर जो पर्याय समास ज्ञानका भेद हुआ उसको एक बार असंख्यात लोक प्रमाण संख्यातसे भाग देनेपर जो परिमाण आवे उसे उसी भेदमें मिलानेपर एक बार असंख्यात भाग वृद्धिको लिये हुए पर्याय समास ज्ञानका भेद होता है। उसमें अनन्तसे भाग देनेपर जो परिमाण आवे उसे

पर्य्यायसमासज्ञानविकल्पंगळोळु सर्व्वजघन्यप्रथमविकल्पमक्कु ज $\frac{१६}{१६}$ मिदरनंतैकभागमन-न्तिये समच्छेदं माडि कूडुत्तिरलु पर्य्यायसमासद्वितीयज्ञानविकल्पमक्कु ज $\frac{१६}{१६}$ $\frac{१६}{१६}$ मिदरनंतैक-भागमनन्तिये समच्छेदं माडि कूडुत्तं विरलु पर्य्यायसमासतृतीयज्ञानविकल्पमक्कु ज $\frac{१६}{१६}$ $\frac{१६}{१६}$ $\frac{१६}{१६}$ मिदरनंतैकभागमनन्तिये समच्छेदं माडि कूडिदोडे पर्य्यायसमासचतुर्थज्ञानविकल्पमक्कु ज $\frac{१६}{१६}$ $\frac{१६}{१६}$ $\frac{१६}{१६}$ $\frac{१६}{१६}$ मिदरनंतैकभागमनन्तिये समच्छेदं माडि कूडिदोडे पर्य्यायसमासपंचम-ज्ञानविकल्पमक्कु ज $\frac{१६}{१६}$ $\frac{१६}{१६}$ $\frac{१६}{१६}$ $\frac{१६}{१६}$ $\frac{१६}{१६}$ मिदरनंतैकभागमनन्तिये समच्छेदं माडि कूडु-

---

ज्ञानविकल्पेषु सर्वजघन्यप्रथमविकल्पः स्यात् ज $\frac{१६}{१६}$ अस्यानन्तैकभागे ज $\frac{१६}{१६ । १६}$ अस्मिन्नेव समच्छेदेन युते पर्यायसमासद्वितीयज्ञानविकल्पः ज $\frac{१६}{१६}$ । $\frac{१६}{१६}$ । अस्यानन्तैकभागे अस्मिन्नेव समच्छेदेन युते पर्यायसमासतृतीयज्ञानविकल्पः ज $\frac{१६}{१६}$ । $\frac{१६}{१६}$ । $\frac{१६}{१६}$ । अस्यानन्तैकभागे अस्मिन्नेव समच्छेदेन युते पर्यायसमासचतुर्थज्ञानविकल्पः ज $\frac{१६}{१६}$ । $\frac{१६}{१६}$ । $\frac{१६}{१६}$ । $\frac{१६}{१६}$ । अस्यानन्तैकभागे अस्मिन्नेव समच्छेदेन युते पर्यायसमासपंचमज्ञानविकल्पः । ज $\frac{१६}{१६}$ । $\frac{१६}{१६}$ । $\frac{१६}{१६}$ । $\frac{१६}{१६}$ । $\frac{१६}{१६}$ । अस्यानन्तैकभागे अस्मिन्नेव समच्छेदेन

आवे उसे उस तीसरे भेदमें मिलानेपर पर्याय समास ज्ञानका चतुर्थ विकल्प आता है। यह चतुर्थ अनन्त भाग वृद्धि हुई। फिर इस चतुर्थ भेदमें अनन्तसे भाग देकर जो एक भाग आवे उसे उस चतुर्थ विकल्पमें मिलानेपर पर्याय समासका पंचम विकल्प आता है। यह पाँचवीं अनन्तभाग वृद्धि हुई। फिर उस पाँचवें भेदमें अनन्तसे भाग देनेपर जो भाग आता है उसे पाँचवें भेदमें मिलानेपर पर्याय समासका छठा विकल्प आता है। यह छठी अनन्त भाग वृद्धि हुई। इसी प्रकार सूच्यंगुलके असंख्यातवें भाग प्रमाण अनन्त भाग वृद्धि होनेपर
जो पर्याय [illegible] ज्ञानका भेद हुआ उसको एक बार असंख्यात लोक प्रमाण संख्यातसे भाग
देनेपर [illegible] उसी भेदमें मिलानेपर एक बार असंख्यात भाग वृद्धिको लिये
[illegible] है। उसमें अनन्तसे भाग देनेपर जो परिमाण आवे उसे

पर्य्यायसमासश्रुतज्ञानविकल्पंगळोळु सर्व्वजघन्यप्रथमविकल्पमक्कु ज $\frac{\overline{१६}}{१६}$ मिदरनंतैकभागमनल्लिये समच्छेदं माडि कूडुत्तिरलुमदु पर्य्यायसमासद्वितीयज्ञानविकल्पमक्कु ज $\frac{\overline{१६}}{१६}$ $\frac{\overline{१६}}{१६}$ मदरनंतैकभागमनल्लिये समच्छेदं माडि कूडुत्तं विरलु पर्य्यायसमासतृतीयज्ञानविकल्पमक्कु ज $\frac{\overline{१६}}{१६}$ $\frac{\overline{१६}}{१६}$ $\frac{\overline{१६}}{१६}$ मदरनंतैकभागमनल्लिये समच्छेदं माडि कूडिदोडे पर्य्यायसमासचतुर्त्थज्ञानविकल्पमक्कु ज $\frac{\overline{१६}}{१६}$ $\frac{\overline{१६}}{१६}$ $\frac{\overline{१६}}{१६}$ $\frac{\overline{१६}}{१६}$ मदरनंतैकभागमनल्लिये समच्छेदं माडि कूडिदोडे पर्य्यायसमासपंचमश्रुतज्ञानविकल्पमक्कु ज $\frac{\overline{१६}}{१६}$ $\frac{\overline{१६}}{१६}$ $\frac{\overline{१६}}{१६}$ $\frac{\overline{१६}}{१६}$ $\frac{\overline{१६}}{१६}$ मदरनंतैकभागमनल्लिये समच्छेदं माडि कूडु-

---

ज्ञानविकल्पेषु सर्वजघन्यप्रथमविकल्पः स्यात् ज $\frac{\overline{१६}}{१६}$ अस्यानन्तैकभागे ज $\frac{\overline{१६}}{१६ । १६}$ अस्मिन्नेव समच्छेदेन युते पर्यायसमासद्वितीयज्ञानविकल्पः ज $\frac{\overline{१६}}{१६}$ । $\frac{\overline{१६}}{१६}$ । अस्यानन्तैकभागे अस्मिन्नेव समच्छेदेन युते पर्यायसमासतृतीयज्ञानविकल्पः ज $\frac{\overline{१६}}{१६}$ । $\frac{\overline{१६}}{१६}$ । $\frac{\overline{१६}}{१६}$ । अस्यानन्तैकभागे अस्मिन्नेव समच्छेदेन युते पर्यायसमासचतुर्थज्ञानविकल्पः ज $\frac{\overline{१६}}{१६}$ । $\frac{\overline{१६}}{१६}$ । $\frac{\overline{१६}}{१६}$ । $\frac{\overline{१६}}{१६}$ । अस्यानन्तैकभागे अस्मिन्नेव समच्छेदेन युते पर्यायसमासपञ्चमश्रुतज्ञानविकल्पः । ज $\frac{\overline{१६}}{१६}$ । $\frac{\overline{१६}}{१६}$ । $\frac{\overline{१६}}{१६}$ । $\frac{\overline{१६}}{१६}$ । $\frac{\overline{१६}}{१६}$ । अस्यानन्तैकभागे अस्मिन्नेव समच्छेदेन

आवे उसे उस तीसरे भेदमें मिलानेपर पर्याय समास ज्ञानका चतुर्थ विकल्प आता है। यह चतुर्थ अनन्त भाग वृद्धि हुई। फिर इस चतुर्थ भेदमें अनन्तसे भाग देकर जो एक भाग आवे उसे उस चतुर्थ विकल्पमें मिलानेपर पर्याय समासका पंचम विकल्प आता है। यह पाँचवीं अनन्तभाग वृद्धि हुई। फिर इस पाँचवें भेदमें अनन्तसे भाग देनेपर जो भाग आता है उसे पाँचवें भेदमें मिलानेपर पर्याय समासका छठा विकल्प आता है। यह छठी अनन्त भाग वृद्धि हुई। इसी प्रकार सूच्यंगुलके असंख्यातवें भाग प्रमाण अनन्त भाग वृद्धि होनेपर जो पर्याय समास ज्ञानका भेद हुआ उसको एक बार असंख्यात लोक प्रमाण संख्यातसे भाग देनेपर जो परिमाण आवे उसे उसी भेदमें मिलानेपर एक बार असंख्यात भाग वृद्धिको लिये हुए पर्याय समास ज्ञानका भेद होता है। उसमें अनन्तसे भाग देनेपर जो परिमाण आवे उसे

मोदल्गोंडु तदुत्कृष्टवृद्धिपर्य्यंतं भेदमुंटप्पुदरिंदमवर विन्यासं तोरल्पडुगुमदें तेंदोडे पर्य्यायसमासज्ञानप्रथमविकल्पदोळिद्दं वृद्धियं तेगदु जघन्यद मेगे स्थापिसि अवर केळगे एकवारानंतैकभागवृद्धियं स्थापिसुवुदंतु स्थापिसुत्तिरलु तद्वृद्धिगे प्रक्षेपकमेंब पेसरक्कु। मंते द्वितीयविकल्पदोळिद्दं जघन्यमं मेगे स्थापिसि तदधस्तनभागदोळु तद्वृद्धिप्रक्षेपकंगळेरडुमोंदु प्रक्षेपकप्रक्षेपकमुमप्पुवयं क्रमदिदं केळगे केळगिरिसुवुदु। तृतीयविकल्पदोळं जघन्यमं मेगे स्थापिसि तद्वृद्धिगळप्प मूरुं प्रक्षेपकंगळं मूरुं प्रक्षेपकप्रक्षेपंगळमोंदु पिशुलियुमं यथाक्रमदिदं तज्जघन्यद केळगे केळगे स्थापिसुवुदु। चतुर्थविकल्पदोळुमंते जघन्यमं मेगे स्थापिसि तदधस्तनभागदोळु तद्वृद्धिगळप्प नाल्कुं प्रक्षेपकंगळं षट्प्रक्षेपकप्रक्षेपकंगळं चतुःपिशुलिगळुमनोंदु पिशुलिपिशुलियुमं यथाक्रमदिंद केळगे केळगे स्थापिसुवुदु।

पंचमविकल्पदोळमंते जघन्यमं मेग स्थापिसि तदधस्तनभागदोळु तद्वृद्धिगळप्प प्रक्षेपकंगळय्दुमं प्रक्षेपकप्रक्षेपकंगळ पत्तुं। पिशुलिगळु पत्तुमं पिशुलिपिशुलिगळय्दुमनोंदु चूर्णियुमं यथाक्रमदिंद केळगे केळगे स्थापिसुवुदु। षष्ठविकल्पदोळुमंते जघन्यमं मेगे स्थापिसि तदधस्तनभागदोळु

अथ तद्वृद्धीनां तज्जघन्यमादिं कृत्वा तदुत्कृष्टवृद्धिपर्यन्तं भेदे सति तद्विन्यासो दर्श्यते। तद्यथा—पर्यायसमासप्रथमविकल्पे स्थितवृद्धिं पृथक्कृत्य जघन्यमुपरि संस्थाप्य तस्याधः एकवारानन्तैकभागवृद्धिं स्थापयेत्, तद्वृद्धेः प्रक्षेपक इति नाम। तथा द्वितीयविकल्पे जघन्यमुपरि संस्थाप्य तदधस्तनभागे तद्वृद्धेर्द्वौ प्रक्षेपकौ एकं प्रक्षेपकप्रक्षेपकं च अधोऽधो न्यस्येत्। तृतीयविकल्पे जघन्यमुपरि संस्थाप्य तद्वृद्धेस्त्रीन् प्रक्षेपकान् त्रीन् प्रक्षेपकप्रक्षेपकान् एकं पिशुलिं च अधोऽधो न्यस्येत्। चतुर्थविकल्पे तज्जघन्यमुपरि न्यस्य तदधस्तनभागे तद्वृद्धेश्चतुरः प्रक्षेपकान् षट् प्रक्षेपकप्रक्षेपकान् चतुरः पिशुलीन् एकं पिशुलिपिशुलिं च अधोऽधो न्यस्येत्। पञ्चमविकल्पे

आगे यहाँ अनन्त भाग वृद्धि रूप सूच्यंगुलके असंख्यातवें भाग प्रमाण स्थान कहे हैं उनका जघन्य स्थानसे लेकर उत्कृष्ट स्थान पर्यन्त स्थापनका विधान कहते हैं। सो प्रथम ही संज्ञाओंको कहते हैं—

विवक्षित मूल स्थानको विवक्षित भागहारका भाग देनेपर जो प्रमाण आवे उसे प्रक्षेपक कहते हैं। उसी प्रमाणको उसी भागहारसे भाग देनेपर जो प्रमाण आवे उसे प्रक्षेपक-प्रक्षेपक कहते हैं। उसमें भी विवक्षित भागहारसे भाग देनेपर जो प्रमाण आवे उसे पिशुलि कहते हैं। उसमें भी विवक्षित भागहारसे भाग देनेपर जो प्रमाण आवे उसे पिशुलि-पिशुलि कहते हैं। उसमें भी विवक्षित भागहारसे भाग देनेपर जो प्रमाण आवे उसे चूर्णि कहते हैं। उसमें भी विवक्षित भागहारका भाग देनेपर जो प्रमाण आवे उसे चूर्णि-चूर्णि कहते हैं। इसी प्रकार पूर्व प्रमाणको विवक्षित भागहारका भाग देनेपर द्वितीय आदि चूर्णि-चूर्णि कही जाती है। अस्तु—

सो पर्याय समास ज्ञानके प्रथम भेदमें ऊपर जघन्यको स्थापित करके उसके नीचे एक बार अनन्त भाग वृद्धिकी स्थापना करना चाहिए। उस वृद्धिका नाम प्रक्षेपक है। तथा दूसरे विकल्पमें जघन्यको ऊपर स्थापित करके उसके नीचे-नीचे उसकी वृद्धिके दो प्रक्षेपक और एक प्रक्षेपक-प्रक्षेपक स्थापित करें। तीसरे विकल्पमें जघन्यको ऊपर स्थापित करके उसकी वृद्धिके तीन प्रक्षेपक, तीन प्रक्षेपक-प्रक्षेपक और एक पिशुली नीचे-नीचे स्थापित करें। चतुर्थ विकल्पमें जघन्यको ऊपर स्थापित करके उसके नीचे-नीचे उसकी वृद्धिके चार प्रक्षेपक,

वेक्कं दु तज्जघन्यमं मेले स्थापिसि तदधस्तनभागदोळु यथाक्रमदिदं प्रक्षेपकंगळु गच्छमात्रंगळप्पुवेंदु सूच्यंगुलासंख्यातभागमात्रंगळं स्थापिसिदवर केळगे प्रक्षेपकप्रक्षेपकंगळु रूपोनगच्छेय एकवारसंकलनधनमात्रंगळप्पुवेंदु रूपोनसूच्यंगुलासंख्यातभागगच्छेय एकवारसंकलनधनप्रमितंगळं स्थापिसुवुदवर केळगे पिशुलिगळु द्विरूपोनगच्छेय द्विकवारसंकलनधनमात्रंगळप्पुवेंदु द्विरूपोनसूच्यंगुलासंख्यातभागगच्छेय द्विकवारसंकलनधनमात्रंगळं स्थापिसुवुदवर केळगे पिशुलि पिशुलिगळु त्रिरूपोनगच्छेय त्रिवारसंकलनधनप्रमितंगळप्पुवेंदु त्रिरूपोनसूच्यंगुलासंख्यात भागगच्छेय त्रिवार-

चरमानन्तभागवृद्धियुक्तस्थानविकल्पे पृथक्कृततज्जघन्यमुपरि न्यस्येत्। तदधस्तनभागे यथाक्रमं प्रक्षेपकान् सूच्यङ्गुलासंख्येयभागमात्रान् न्यस्येत्। तदधः प्रक्षेपकप्रक्षेपकाः रूपोनगच्छस्य एकवारसंकलनधनमात्राः सन्तीति रूपोनसूच्यङ्गुलासंख्येयभागगच्छस्य एकवारसंकलनधनमात्रान् न्यस्येत्। तदधः पिशुलयः द्विरूपोनगच्छस्य द्विकवारसंकलनधनमात्राः सन्तीति द्विरूपोनसूच्यङ्गुलासंख्येयभागगच्छस्य द्विकवारसंकलनधनमात्रान् न्यस्येत्।

स्थापित करना, उसके नीचे प्रक्षेपक-प्रक्षेपकोंको, यतः वे एक कम गच्छके एक बार संकलन धन मात्र होते हैं अतः एक कम सूच्यंगुलके असंख्यात भाग गच्छके एक बार संकलन धन मात्र स्थापित करना। उनके नीचे पिशुली, जो दो हीन गच्छके दो बार संकलन धन मात्र होती हैं, इसलिए दो हीन सूच्यंगुलके असंख्यातवें भाग गच्छके दो बार संकलन धन मात्र स्थापित करना। उनके नीचे पिशुली-पिशुली तीन हीन गच्छके तीन बार संकलन धन मात्र होती हैं इसलिए तीन हीन सूच्यंगुलके असंख्यातवें भाग गच्छके तीन बार संकलन धन मात्र स्थापित करना। उनके नीचे चूर्णि चार हीन गच्छके चार बार संकलन धन मात्र होती हैं इसलिए चार हीन सूच्यंगुलके असंख्यातवें भाग गच्छके चार बार संकलन धन मात्र स्थापित करना। उनके नीचे चूर्णि-चूर्णि पाँच हीन गच्छके पाँच बार संकलन धन मात्र होती है इसलिए पाँच हीन सूच्यंगुलके असंख्यातवें भाग गच्छके पाँच बार संकलन धन मात्र स्थापित करना। इसी प्रकार उसके नीचे-नीचे चूर्णि-चूर्णि छह हीन आदि गच्छके छह बार आदि संकलन धन मात्र होती हैं इसलिए छह हीन सूच्यंगुलके असंख्यातवें भाग आदि गच्छोंके छह हीन सूच्यंगुलके असंख्यात भागादि बार संकलन धन मात्र नीचे-नीचे स्थापित करना। ऐसा करते-करते सबसे नीचेकी द्विचरम चूर्णि-चूर्णि दो हीन गच्छसे हीन गच्छकी दो हीन गच्छबार संकलित धन प्रमाण होती हैं इसलिए दो हीन सूच्यंगुलके असंख्यातवें भागसे हीन सूच्यंगुलके असंख्यातवें भाग गच्छके दो हीन सूच्यंगुलके असंख्यात भाग बार संकलन धन मात्र स्थापित करना। उनके नीचे एक हीन गच्छसे हीन गच्छके एक हीन गच्छ मात्र बार संकलन धन मात्र उसकी अन्तिम चूर्णि-चूर्णि हैं इसलिए एक हीन सूच्यंगुलके असंख्यातवें भागसे हीन सूच्यंगुलके असंख्यातवें भाग गच्छके एक हीन सूच्यंगुलके असंख्यात भाग मात्र बार संकलित धन प्रमाण स्थापित करना। परमार्थसे अन्तिम चूर्णि-चूर्णिका संकलित धन ही घटित नहीं होता क्योंकि द्वितीय आदि स्थानका अभाव है।

विशेषार्थ—अंक संदृष्टिसे उक्त कथन इस प्रकार जानना। जघन्य पर्याय ज्ञानका प्रमाण ६५५३६। विवक्षित भागहार अनन्तका प्रमाण चार। पूर्वोक्त क्रमसे चारका भाग देनेपर प्रक्षेपकका प्रमाण १६३८४। प्रक्षेपक-प्रक्षेपकका प्रमाण ४०९६। पिशुलीका प्रमाण १०२४। पिशुली-पिशुलीका प्रमाण २५६। चूर्णि प्रमाण ६४। चूर्णि-चूर्णि प्रमाण १६। इसी

षड्रूपोनादिगच्छेय षड्वारसंकलनादिधनप्रमितंगळप्पुवेंदु षड्रूपोनसूच्यंगुलासंख्यातभागादिवारसंकलनधनमात्रंगळं केळगेकेळगे स्थापिसुत्तं पोगि सर्व्वाधस्तनद्विचरम चूर्णिचूर्णिगळु द्विरूपोनगच्छोनगच्छद्विरूपोनगच्छोनगच्छवारसंकलनदधन प्रमितंगळप्पुवेंदु द्विरूपोनसूच्यंगुलासंख्यातभागोनसूच्यंगुलासंख्यातभागगच्छेय द्विरूपोनसूच्यंगुलाऽसंख्यातभागवारसंकलनधनमात्रंगळं

स्थापिसुवु ज २ । ३ । ४ । ००० । २–३ । २–२ । २ २ दुवनपर्वात्तसि ज २ २ यवर केळगे

१६ । २ २ । २ २ । २३ । ००० । ० ४ । ० ३ । ० २ । ० १   १६ ० ०

रूपोनगच्छोनगच्छरूपोनगच्छमात्रवार संकलनधनमात्र तच्चरमचूर्णिचूर्णियप्पुदरिंदं रूपोनसूच्यंगुलासंख्यातभागोनसूच्यंगुलासंख्यातभागगच्छेय रूपोनसूच्यंगुलासंख्यातभागमात्रवारसंकलनधनप्रमितमं ज । १ । २ । ३ ० ० ० २ २ २–१ २ अपर्वात्ततमनिदं ज । १ स्थापिसुवुदु

१६ २ । २ । २-१ । २–२ । ००० ० ३–० २ । ० १   १६ । २

० ० ० ०   ०

परमार्थरूपदिदं चरमचूर्णिचूर्णिगे संकलितमे घटिसदेकेंदोडे द्वितीयादिस्थानाभावमप्पुदरिंदं। इल्लि षट्स्थानप्रकरणदोळनंतभागवृद्धियुक्तपर्य्यायसमासजघन्यादिज्ञानविकल्पंगळोळु सर्व्वत्र स्थापिसिद प्रक्षेपकंगळु गच्छमात्रंगळप्पुवदु कारणदिदं सुगमंगळु। प्रक्षेपकप्रक्षेपकादिगळ प्रमाणमरियल्लिगे करणसूत्रमिदु।

धनमात्रान् स्थापयेत्। एवं तदधस्तनाधस्तनचूर्णिचूर्णयः षड्रूपोनादिगच्छस्य षड्वारादिसंकलनधनप्रमिताः सन्तीति षड्रूपोनसूच्यङ्गुलासंख्येयभागादिगच्छानां षड्रूपोनसूच्यङ्गुलासंख्यातभागादिवारसंकलनधनमात्रान् अधोऽधो विन्यस्य गत्वा सर्वाधस्तनद्विचरमचूर्णिचूर्णयः द्विरूपोनगच्छोनगच्छस्य द्विरूपोनगच्छवारसंकलनधनप्रमिताः सन्तीति द्विरूपोनसूच्यङ्गुलासंख्येयभागोनसूच्यङ्गुलासंख्यातभागगच्छस्य द्विरूपोनसूच्यङ्गुलासंख्यातभागवारसंकलनधनमात्रान् स्थापयेत्—

ज   २   ३   ४ । ००० । २–३   २–२   २–१   २

१६ २–१   २–१   २–२   २–३ । ००० । ० । ४   ० । ३   ० । २   २ । १

०   ०   ०   ०

ज   २

अपवर्तिते एवं—१६ २–१   ० तदधो रूपोनगच्छोनगच्छस्य रूपोनगच्छमात्रवारसंकलनधनमात्राः तच्चरमचूर्णिचूर्णयः सन्तीति रूपोनसूच्यङ्गुलासंख्यातभागोनसूच्यङ्गुलासंख्यातभागगच्छस्य रूपोनसूच्यङ्गुलासंख्यातभागमात्रवारसंकलनधनमिदं—

०   (१६ २–१ के नीचे)

ज   १   २   ३   ४   ०००   २ । ३ । २–२ । २–१ । २

१६ २   २   २–१   २–२   २–३ । ०००   ० ४ । ० ३ । ० २ । ० १

०   ०   ०   ०   ०

ज   १

अपवर्तितमिदं— १६ २ स्थापयेत्। परमार्थतः चरमचूर्णिचूर्णेः संकलितमेव न घटेत द्वितीयादिस्थानाभावात्। अत्र षट्स्थानप्रकरणे अनन्तभागवृद्धियुक्तविकल्पेषु सर्वत्र प्रक्षेपकाः गच्छमात्राः सन्तीति सुगमाः।

०   (१६ २ के नीचे)

इस षट्स्थान प्रकरणमें अनन्त भागवृद्धि युक्त विकल्पोंमें सर्वत्र प्रक्षेपक गच्छ प्रमाण होते हैं इसलिए वे सुगम हैं। प्रक्षेपक-प्रक्षेपक आदिका प्रमाण लानेके लिए करणसूत्र इस

ज	ज	ज	ज	ज	ज	ज	ज
प्र	ज १ १६	ज २ १६	ज ३ १६	ज ४ १६	ज ५ १६	ज ६।0000000000 १६	ज२ । १६ a
	प्र प्र	ज १ १६।१६	ज ३ १६।१६	ज ६ १६।१६	ज १० १६।१६	ज १५00000000 १६।१६	ज २ २ १६।१६ aaa १
		पि	ज १ १६।१६।१६	ज ४ १६।१६।१६	ज १० १६।१६।१६	ज २0।0000000 १६।१६।१६	ज २ २ २ २ १६।१६।१६ aa ३ a २१
			पि पि	ज १ १६।१६।१६।१६	ज ५ १६।१६।१६।१६	ज ५।0000000	ज २३ २२ २१ २ ३ २४ aaa । १ ३२
				घू	ज १ १६।१६।१६।१६।१६	ज ६।00000000000 १६।१६।१६।१६।१६	ज २ २ 0 १६ a a 0
					घू घू	ज १।000000000 १६।१६।१६।१६।१६।१६	ज १ १६ २ a

संकलनवारंगळ प्रमाणमक्कुमल्लि कोष्ठधनस्यानयने विवक्षित ४ चतुर्व्वारसंकलनधनमंतप्पल्लि। प्रभवः आदि येंतुंटक्कुमेंदोडे इष्टोनितोर्ध्वंपदसंख्या स्यात्। तन्न विवक्षितसंकलनवारप्रमाणमं नाल्कं कळेदुळिदूर्ध्वंपदप्रमाणमें तुंटंतुदु प्रभवमक्कुमेंदिल्लि ऊर्ध्वंगच्छमु मूरप्पुवयरोळु नाल्कं कळेदुळिद द्विरूपुगळु प्रभवमें बुदर्थं।

ततो रूपाधिक क्रमेण तदादिभूतप्रभवभूत द्विरूपं मोदलगोंडु मुंदे रूपाधिकक्रमदिवं गुणकारा भवंत्यूर्ध्वंगच्छपर्य्यंतं अनुलोमक्रमदिं गुणकारंगळप्पु ऊर्ध्वंगच्छप्रमाणांकदक्कें नेयरमुत्पत्तिपर्यंतमन्नेवरं ज २।३।४।५।६ ई गुणकारंगळ्गे केळगे एकरूपादि रूपोत्तरहाराः भवन्ति एक-
१६।५

रूपादिरूपोत्तरमप्प भागहारंगळु विलोमक्रमदिदमप्पुवु। प्रभवपर्य्यंतं मेलण गुणकारभूतप्रभवांक-माद्यंकमवसानमन्नेवरमन्नेयरं ज ३।४।५।६ केळगे अपवर्तितलब्धं चतुर्व्वारसंकलन-
१६।५।४।३।२।१

धनमक्कु ज ६ इंतनंतभागवृद्धियुक्तचरमस्तानविकल्पद तिर्य्यंपदे
१६ १६ १६ १६ १६

तिर्य्यंगच्छदोळु सूच्यंगुलासंख्यातभागमात्रगच्छदोळु २ रूपोने २ एकरूपोनमादोडे तव
० ०

भवन्ति उद्ध्वगच्छोति ऊर्ध्वगच्छाङ्कोत्पत्तिपर्यन्तं—ज २ ३ ४ ५ ६ तेषां गुणकाराणां अधः हारा भागहाराः
१६ ५

इगिरूवमादि एकरूपादयः रुउत्तरा-रूपोत्तरा होंति भवन्ति विलोमक्रमेण रूपाधिकेष्टवारस्थानेषु पभवोत्ति प्रभवाङ्कपर्यन्तं ज २ ३ ४ ५ ६ अपवर्तिते लब्धं चतुर्वारसंकलनधनं भवति—
१६ १६ १६ १६ १६ ५ ४ ३ २ १

ज ६ एवमनन्तभागवृद्धियुक्तचरमविकल्पे तिर्यक्पदं सूच्यङ्गुलासंख्यातभागमात्रे २
१६ १६ १६ १६ १६ ०

इस संकलित धनको अपने अभिप्रायके अनुसार लानेके लिए केशववर्णीने दो गाथाएँ कही हैं। उनका अर्थ उदाहरण पूर्वक कहते हैं—अनन्त भाग वृद्धि युक्त स्थानोंमें जो विवक्षित स्थान है वह तिर्यक् पद है। जैसे छठा स्थान तिर्यक्पद है। उसमें एक घटानेपर उसके नीचे पाँच संकलन वार होते हैं। प्रक्षेपकके नीचे कोठोंमें-से प्रत्येकमें क्रमसे एक बार, दो बार आदि सम्भव संकलनोंकी संख्या होती है। यहाँ इष्ट चार बार संकलन धन गत कोठेके धनको लानेके लिए इष्ट संकलन वारके प्रमाण ४ को ऊर्ध्वपद ६ में कम करनेपर ६ – ४ = २ आदि होता है। इस आदि दोसे लगाकर एक-एक अधिकके क्रमसे ऊर्ध्व गच्छ छह पर्यन्त गुणकार होते हैं यथा २, ३, ४, ५, ६। इन गुणकारोंके नीचे भागहार एक रूप आदि एक अधिक बढ़ते हुए उल्टे क्रमसे होते हैं। सो यहाँ चार बार संकलनके कोठेमें चूर्णि है। जघन्यमें पाँच बार अनन्तका भाग देनेसे जो प्रमाण आता है उतना चूर्णिका प्रमाण है। इस प्रमाणके गुणकार क्रमसे दो, तीन, चार, पाँच, छह हैं और पाँच, चार, तीन, दो एक भागहार हैं। गुणकारसे चूर्णिके प्रमाणको गुणा करके भागहारोंका भाग देनेपर यथायोग्य अपवर्तन करनेपर छह गुणित चूर्णि मात्र प्रमाण आता है। इसका आशय यह है जो १६, १६, १६, १६, १६ पर चूर्णिका प्रमाण है। 'ज' अर्थात् जघन्य पर्याय ज्ञानमें १६ अर्थात् अनन्तका पाँच बार

---

१. म°नारमेन्नेवरं।

[illegible] मतोत्तरमात्र [illegible] विशेषकर्मदि भवंति प्रभजगमंतं आदिभूत- [illegible] गुणकारं गत्वेत्युणयणु :—

[illegible] २–४। २–३ । २–२ २ । २ [illegible] इति त्रिसमयप्रतनमणुरविमन्तर्गतितमिति
[illegible]
[illegible] तस्याप्तिरिक्तमणुर्राषं ।

[illegible] एकार्धिते त्रिशितिद्विलमनुर्गिचूर्ग द्विरूपोनगुणगुणा- [illegible] गुणतेतोवे तिर्यंतरे हपोने सति हपहोनमावोगिनु

[illegible] कोलनस्या-

[illegible] प्रमाणमेतुर्वेवोवे इयोगितोवेगसंख्या [illegible] २—२ [illegible] प्रमाणं प्रभगमजुमें दूर्णपरं

[illegible] द्विरूपमासितपगुमें गुरार्थं ।

[illegible] गुणकारा भवंतु- [illegible] गुणकारेण [illegible] प्रमाणा [illegible]

[illegible] २ [illegible] अत्र त्रिसमयारनमनी-
[illegible]

[illegible] त्रिशितिद्विलमनुगिपुर्ण-

[illegible] २ [illegible]

[illegible] २–२ [illegible] २

[illegible]

[illegible] है। [illegible] होती है वह [illegible] [illegible] [illegible] भजका प्रमाण लाते हैं जो इस [illegible] जाता जाता है। इसमें [illegible] [illegible] भजका [illegible] जाता है। [illegible] [illegible] जाता है। [illegible] [illegible] इससे लेकर आगे [illegible] [illegible] लेकर आगे [illegible] बढ़ते हुए [illegible] है। यहाँ [illegible] [illegible] है। अतः

भागमात्रंगळु संदु द्वितीयषट्स्थानक्कादिभूतमप्पअष्टांकमोंदु पुट्टुगुमेन्नेवरं मन्नेवरेगमो क्रमदिं पल्पडुगुं।

आदिमछट्ठाणम्मि य पंच य वड्ढी हवंति सेसेसु ।
छव्वड्ढीओ होंति हु सरिसा सव्वत्थ पदसंखा ॥३२७॥

आदिमषट्स्थाने च पंच वृद्धयो भवंति शेषेषु। षड्वृद्धयो भवंति खलु सदृशी सर्वत्र पदसंख्या ॥

इल्लि संभविसुवंतप्पअसंख्यातलोकमात्रषट्स्थानंगळोळु आदिमषट्स्थाने आदौ भवमादिमं षण्णां स्थानानां समाहारः षट्स्थानं आदिम षट्स्थानमादिमषट्स्थानं तस्मिन् मोदल षट्स्थानदोळु पंच वृद्धयो भवंति पंचवृद्धिगळेयप्पुवेकेंदोडे चरमाष्टांकसंज्ञेयनुळ्ळनंतगुणवृद्धियुक्तस्थानक्के द्वितीय षट्स्थानक्कादित्व प्रतिपादनदिदं शेषेषु शेषद्वितीयादिचरमावसानमाद षट्स्थानंगळोळेल्लमष्टांकादियाद षड्वृद्धिगळप्पुवुमंतागुत्तिरलु सदृशी सर्व्वत्र पदसंख्या ई षट्स्थानंगळोळु संभविसुव स्थानविकल्पंगळ संख्यासादृश्यनियमक्के निमित्तमप्प सूच्यंगुलासंख्यातभागक्कवस्थितस्वरूपमुळ्ळदरिदं। समस्तषट्स्थानंगळ स्थानविकल्पंगळ संख्येसमानमेयक्कुमंतादोडे मोदल षट्स्थानदोळु पंचवृद्धियुक्तस्थानंगळप्पुदरिनष्टांकमेंतु घटियिसुगुमेंदोडुत्तरसूत्रंदोळु पेळ्दपं :—

संख्यातभागवृद्धियुक्तस्थानान्यपि प्रत्येकं काण्डककाण्डकप्रमितानि नीत्वा पुनरनन्तभागासंख्यातभागवृद्धियुक्तस्थानानि प्रत्येकं काण्डकप्रमितानि नीत्वा पुनरनन्तभागवृद्धियुक्तस्थानान्येव सूच्यङ्गुलासंख्यातभागमात्राणि नीत्वा द्वितीयषट्स्थानस्य आदिभूतमष्टाङ्कसंज्ञं भवति इत्येवं सर्वत्र षट्स्थानपतितवृद्धिक्रमो ज्ञातव्यः ॥३२६॥

अत्र संभवत्सु असंख्यातलोकमात्रेषु षट्स्थानेषु मध्ये आदिमे प्रथमे षट्स्थाने पञ्चैव वृद्धयो भवन्ति, चरमस्य अष्टाङ्कसंज्ञस्य अनन्तगुणवृद्धियुक्तस्य द्वितीयषट्स्थानस्यादित्वप्रतिपादनात्। शेषेषु द्वितीयादिचरमावसानेषु षट्स्थानेषु सर्वा अष्टाङ्कादयः षड्वृद्धयो भवन्ति। तथापि सदृशी सर्वत्र पदसंख्या एतेषु षट्स्थानेषु संभवति-स्थानविकल्पसंख्या सदृशा समानैव सादृश्यनियमनिमित्तस्य सूच्यङ्गुलासंख्यातभागस्य अवस्थितस्वरूपत्वात्। तथा सति प्रथमषट्स्थाने पञ्चवृद्धियुक्तस्थानानि संभवन्ति ॥३२७॥ अष्टाङ्कः कथं न घटते इति चेदेतुमाह—

होनेपर पुनः अनन्त भाग वृद्धि युक्त स्थान सूच्यंगुलके असंख्यातवें भाग मात्र होनेपर द्वितीय षट्स्थानका आदिभूत अष्टांक होता है। इस प्रकार सर्वत्र षट्स्थानपतित वृद्धि क्रम जानना ॥३२६॥

जघन्य पर्याय ज्ञानके ऊपर असंख्यात लोक मात्र षट्स्थान होते हैं जो पर्याय समास श्रुतज्ञानके विकल्प हैं। उनमें-से प्रथम षट्स्थानमें पाँच ही वृद्धियाँ होती हैं क्योंकि अनन्त गुण वृद्धिसे युक्त जो अष्टांक संज्ञावाला अन्तिम स्थान है उसे दूसरे षट्स्थानका आदि स्थान कहा है। शेष दूसरेसे लेकर अन्तिम पर्यन्त सब षट्स्थानोंमें अष्टांक आदि छहों वृद्धियाँ होती हैं। ऐसा होनेसे इन षट्स्थानोंमें स्थानके विकल्पोंकी संख्या समान ही है क्योंकि सर्वत्र सूच्यंगुलका असंख्यातवाँ भाग तदवस्थ है उसमें हीनाधिकता नहीं है। इस तरह प्रथम षट्स्थानमें पाँच वृद्धि युक्त स्थान ही होते हैं ॥३२७॥

---

१. म °सूचंगल।

ओंदु षट्स्थानदोळु ओंदेयष्टांकमक्कुमेकेंदोडदरकावृत्यभावमप्पुदरिदं। 'अंगुल असंख-भागं पुव्वगवड्ढी गदे दु परवड्ढी एक्कं वारं होदित्ति' एंदितु पूर्व्वपूर्व्ववृद्धिगळु सूच्यंगुलासंख्यात-भागमात्रवारंगळु सलुत्तिरलुत्तरोत्तरवृद्धिगळोंदोंदप्पुवें व क्रममुळ्ळुदरिंद मनंतगुणवृद्धिगावृत्य-भावमेकेंदोडे ईयनंतगुणवृद्धिस्थानक्के पूर्व्ववृद्धिगळावृत्यसिद्धियप्पुदरिदं। समांकः कांडकं असंख्यातगुणवृद्धियुक्तस्थानंगळु सूच्यंगुलासंख्यातभागमात्रंगळेयक्कुमदरिदं मेळगण षडंकपंचांक-चतुरंकोर्व्वंकगळु रूपाधिकसूच्यंगुलासंख्यातभागगुणितक्रमंगळप्पुवु। यावदुर्व्वंकमें दिदभिविधि-यप्पुदरिदमुर्व्वंकक्के सीमात्वमं सूचिसुत्तमदनु व्यापिसुगुमवर न्यासमिदु :—

एकस्मिन् षट्स्थाने एक एवाष्टाङ्को भवति कुतः ? 'अंगुलअसंखभागं पुव्वगवड्ढीगदे दु परवड्ढी एक्कं वारं होदीति' वचन पूर्वस्यागंभवेनावृत्तेरभावात्। समाङ्कः असंख्यातगुणवृद्धियुक्तस्थानानि काण्डकं सूच्यङ्गुलासंख्यातभागमात्राण्येव भवन्ति। तदनन्तराः षडङ्कपञ्चाङ्कचतुरङ्कोर्वङ्कास्तु रूपाधिकसूच्यङ्गुलासंख्यातभागगुणितक्रमा भवन्ति यावदुर्वङ्कं इत्यभिविधिः उर्वङ्कस्य सीमत्वं सूचयन् तमेव व्याप्नोति तन्न्यासोऽयम्—

एक षट्स्थानमें एक ही अष्टांक होता है क्योंकि पहले कहा है कि सूच्यंगुलके असंख्यातवें भाग पूर्वकी वृद्धि होनेपर आगेकी वृद्धि एक बार होती है। सो अष्टांक पूर्वमें है नहीं, इसलिए इसकी आवृत्ति बार-बार घटना सम्भव नहीं है। समांक अर्थात् असंख्यात

मुन्नुदरिदं तत्त्रिचतुर्थं मुंपेळ्द संख्यातभागवृद्धियुतोत्कृष्टसंख्यातमात्रस्थानंगळ त्रिचतुर्थभाग-स्थानंगळु सलुत्तं विरलल्लिय प्रक्षेपकमुं प्रक्षेपकप्रक्षेपकमेंबेरडु वृद्धिगळं जघन्यदोळिक्कल्पडुत्तिरलु लब्ध्यक्षरं द्विगुणमक्कुमदेंतें दोडे प्रक्षेपकप्रक्षेपकद रूपोनगच्छदेकवारसंकलनधनप्रमितद $ज \frac{१५ । ३ । १५ । ३}{१५ । १५ । ४ । २ । ४ । १}$ ऋणमं बेरिरिसि $ज \frac{१ । ३}{१५ \; ३२}$ अपवर्त्तितधनमिदु $ज \frac{९}{३२}$ इदरोळोंदु रूपं-तेगेदु धनमं बेरिरिसिदुदु $ज \frac{१}{३२}$ शेषापवर्त्तितधनं $ज \frac{१}{४}$ इदं प्रक्षेपकवृद्धियोळु $ज \frac{३}{४}$ कूडिदोडे

संख्यातमात्रस्थानानां त्रिचतुर्थभागस्थानानि नीत्वा तत्र प्रक्षेपकः प्रक्षेपकप्रक्षेपकश्चेति वृद्धिद्वये जघन्यस्योपरि युते लब्ध्यक्षरं द्विगुणं भवति । तद्यथा—

प्रक्षेपकप्रक्षेपकस्य रूपोनगच्छस्य एकवारसंकलनधनप्रमितस्य $ज \frac{१५ \; ३ । १५ \; ३}{१५ \; १५ \; ४ \; २ \; ४ \; १}$ ऋणं पृथक्कृत्य $ज \frac{१}{१५} \frac{३}{३२}$ शेषमपवर्त्य $ज \frac{९}{३२}$ एकरूपं पृथग् न्यस्य $ज \frac{१}{३२}$ शेषे $ज \frac{८}{३२}$ अपवर्त्य $ज \frac{१}{४}$ प्रक्षेपकवृद्धौ $ज \frac{३}{४}$

संख्यात मात्र स्थानोंको चारसे भाग देकर उनमें-से तीन भाग प्रमाण स्थानोंके होनेपर प्रक्षेपक और प्रक्षेपक-प्रक्षेपक इन दोनों वृद्धियोंको साधिक जघन्य ज्ञानमें जोड़नेपर लब्ध्यक्षर ज्ञान साधिक दूना होता है। कैसे, सो कहते हैं—पूर्व वृद्धि होनेपर जो साधिक जघन्य ज्ञान हुआ उसमें दो बार उत्कृष्ट संख्यातसे भाग देनेपर प्रक्षेपक-प्रक्षेपक होता है। सो एक हीन गच्छका संकलन धन मात्र प्रक्षेपक-प्रक्षेपककी वृद्धि यहाँ करनी है। पूर्वोक्त करण सूत्रके अनुसार उस प्रक्षेपक-प्रक्षेपकको एक हीन उत्कृष्ट संख्यातके तीन चौथाई भागसे और उत्कृष्ट संख्यातके तीन चौथाई भागसे गुणा करना और दो और एकसे भाग देना। ऐसा करनेपर साधिक जघन्यका एक हीन तीन गुणा उत्कृष्ट संख्यात और तीन गुणा उत्कृष्ट संख्यात तो गुणकार हुआ तथा दो बार उत्कृष्ट संख्यात और चार दो, चार एक भागहार हुआ। एक हीन सम्बन्धी ऋणराशि साधिक जघन्यको तीनका गुणकार और उत्कृष्ट संख्यात तथा बत्तीसको भागहार करनेपर होती है। उसको अलग रखकर शेषका अपवर्तन करनेपर साधिक जघन्यको नौसे गुणा और बत्तीससे भाग प्रमाण हुआ। साधिक जघन्यका चिह्न जं ऐसा है सो जं $\frac{९}{३२}$ हुआ।

विशेषार्थ—यहाँ दो बार उत्कृष्ट संख्यातका गुणकार और भागहारका अपवर्तन किया। गुणकार तीन-तीनको परस्परमें गुणा करनेसे नौका गुणकार हुआ और चार, दो, चार एक भागहारको परस्परमें गुणा करनेसे बत्तीस भागहार हुआ। ऐसे ही अन्यत्र भी जानना। अस्तु।

इस जं $\frac{९}{३२}$ में एक गुणकार साधिक जघन्यका बत्तीसवाँ भाग है जं $\frac{१}{३२}$। इसको अलग रखकर शेष साधिक जघन्यको आठका गुणकार और बत्तीसका भागहार रहा। इसका अपवर्तन करनेपर साधिक जघन्यका चौथा भाग रहा जं $\frac{१}{४}$। प्रक्षेपक गच्छ प्रमाण है सो साधिक जघन्यको एक बार उत्कृष्ट संख्यातका भाग देनेपर प्रक्षेपक होता है उसको उत्कृष्ट

ज १।४१ अपर्याप्तनप्रक्षेपकप्रक्षेपक ज १६८१ इल्लि एकरूपं धनमं बेरिरिसुत्तं
१५।११२।५६ ११२।५६

ज १ शेषमं ज १६।८० अपर्याप्तसलं ज १५ इवं प्रक्षेपकदोळु ज ४१ कूडिदोडे
११२।५६ ११२।५६ ५६ ५६

ज ५६ अपर्याप्तजघन्यमक्कुमदनुपरितनजघन्यदोळ्कूडिदडे लब्धमदं द्विगुणमक्कु ज २।
५६

मुन्निरिसिद धनदोळ् ज १ इदं नोडलु संख्यातगुणहीनमप्प ऋणमं ज १।४१
११२।५६ १५।११२।५६

१ [illegible] शेषमं ज १ — द्विगुणजघन्यदोळु कूडिदोडे साधिकमक्कुम ज २ सततसमं
११२।५६

[illegible] ज १ ८१। शेषं [illegible] ज १६ ८१। एकरूपं धनं पृथक्कृत्य
१५ ११२ ५६ ११२ ५६

ज १ शेषं ज १६ ८० [illegible] ज १५ प्रक्षेपके निक्षिप्य ज ५६ आवलिते जघन्यं भवति।
११२ ५६ ११२ ५६ ५६ ५६

ज। [illegible] द्विगुणं भवति। ज २। इसमेव पृथक्स्थापितधनेन
ज १ [illegible] ज १ ८१ [illegible] ज १— साधिकं कुर्यात् ज २।
११२ ५६ १५ ११२ ५६ ११२ ५६

१० [illegible] संख्यातका गुणकार तथा [illegible], दो, [illegible] भागहार होता है। यहाँ [illegible] साधिक जघन्यको इक्यासीका गुणकार और उत्कृष्ट संख्यात, [illegible] और [illegible] भागहार मात्र है यथा ज १×४१। सो इसको अलग रखकर
१५।११२।५६
[illegible] संख्यातका अपवर्तन करनेपर साधिक जघन्यको सोलह सौ इक्यासी- [illegible] और [illegible] भागहार होता है यथा ज १६८१। यहाँ
११२×५६

१५ [illegible] गुणा करनेपर सोलह सौ इक्यासी हुए और [illegible] गुणा करनेपर एकसौ बारह हुए तथा दूसरे [illegible] एकसे गुणा [illegible]। [illegible] अलग रखा इसका धन साधिक जघन्यको एकसौ बारह [illegible] मात्र होता है। शेष रहे साधिक जघन्यको सोलहसौ [illegible] और [illegible] भागहार। यथा एक भागका धन
२० ज १ शेष। ज १६८० । इसमें एकसौ [illegible] अपवर्तन करनेपर साधिक जघन्यको
११२ × ५६ ११२ × ५६

[illegible] गुणकार और [illegible] भागहार यथा ज १५। इसमें प्रक्षेपका प्रमाण जघन्यको

ज १।४९ / १५।६००० वेरिरिसि अपवर्त्तिसिदोडिनितक्कुं ज ३४३ / ६००० इदरोळु पविमूरु रूपगळं तेगेदिरि- सुवुदु ज १३ / ६००० शेषमिदु ज ३३० / ६००० अपवर्त्तितमिदु ज ११ / २०।१० इल्लि धन ज १३ / ६००० मिदरोळु प्रथमद्वितीयऋणंगळु संख्यातगुणहीनंगळेंदु किंचिदूनं माडि ज १३ = / ६००० मत्तं प्रक्षेपकप्रक्षेपक ज १५।७।७ / १५।२।१०।१० ऋणमिनितक्कु ज १।७ / १५।२०० मिदं वेरिरिसि ज १५।७।७ / १५।२०० अपवर्त्तितमिदु ज ४९ / २०।१० इदरोळु मुन्निन पिशुलियनमनेकादशरूपं कूडुत्तिरलुभयधनमिदु ज ६० / २०० अपवर्त्तितमिदु

शेषधनमपवर्त्य ज १५ ७ । ४९ / १५ १० ६०० अत्रस्थमृणं ज १ ४९ / १५ ६००० पृथक्संस्थाप्य शेषमपवर्त्य ज ३४३ । / ६००० इदमपनीतप्रक्षेपकादनेन पृथक्संस्थाप्य ज १३ । / ६००० शेषं ज ३३० । / ६००० अपवर्त्य ज ११ / २० १० एकत्र संस्थाप्य अत्र भाग् पृथक्स्थापने ज १३ / ६००० प्रथमद्वितीयऋणं संख्यातगुणहीनमिति किंचिदूनं कृत्वा ज १३–१ / ६००० एकत्र संस्थाप्य पुनः प्रक्षेपकप्रक्षेपके ज १५ ७ । ७ / १५ २ १० । १० । ऋणं ज १ ७ / १५ २०० । पृथक् संस्थाप्य शेषं ज १५ ७ ७ । / १५ २००

एक हीन गच्छका एक बार संकलन धन मात्र है सो साधिक जघन्यको दो बार उत्कृष्ट संख्यातसे भाग देनेपर प्रक्षेपक-प्रक्षेपक होता है। उसका पूर्व सूत्रानुसार एक हीन सात गुणा उत्कृष्ट संख्यातका तथा सात गुणा उत्कृष्ट संख्यातका गुणकार और दस, दो तथा दस एक भागहार हुआ। पिशुलि दो हीन गच्छका दो बार संकलित धन मात्र होती है। सो साधिक जघन्यको तीन बार उत्कृष्ट संख्यातका भाग देनेसे पिशुली होती है। उसको पूर्व सूत्रानुसार दो हीन और सातसे गुणित उत्कृष्ट संख्यात और एक हीन तथा सातसे गुणित उत्कृष्ट संख्यात व सात गुणित उत्कृष्ट संख्यात गुणकार तथा दस, तीन, दस दो, दस एक भागहार होते हैं। इनमें पिशुलीके गुणकारमें दो कम किये थे उस सम्बन्धी प्रथम ऋणका प्रमाण साधिक जघन्यको दोका और एक हीन तथा सातसे गुणित उत्कृष्ट संख्यातका तथा सात गुणा उत्कृष्ट संख्यातका गुणकार तथा दो बार उत्कृष्ट संख्यातका और छहका और तीन बार दसका भागहार करनेपर होता है। उसको अलग स्थापित करके शेषका अपवर्तन करनेपर साधिक जघन्यको एक हीन सात गुणा उत्कृष्ट संख्यातका तथा उनचासका तो गुणकार हुआ और उत्कृष्ट संख्यात छह हजारका भागहार होता है यहाँ गुणकारमें एक हीन है।

पुट्टिपुतस्थानंगळ्पुट्टुत्तिर्पुवल्लदे केवलं पर्य्यायजघन्यज्ञानमने भागिसियुं गुणिसियुं पुट्टिदुवल्लें-पुदक्कुं दु निश्चयिसुवुदु मोघल्यांक्षरज्ञानम के । उ नपवर्त्तितुतिरलु श्रुतकेवलज्ञानसंख्यातभाग-
१८=उ
मात्रार्त्थाक्षरज्ञानप्रमाणमक्कुं के अक्षराज्जातं ज्ञानमक्षरज्ञानमर्त्थविषयमर्त्थग्राहकमर्त्थाक्षर-
१८=
ज्ञानं। अथवा अर्य्यते गम्यते ज्ञायतेयित्यर्त्थः। न क्षरतीत्यक्षरं द्रव्यरूपतया विनाशाभावात् । अर्त्थश्चासावक्षरं च तदर्त्थाक्षरं। अथवा अर्य्यते गम्यते श्रुतकेवलस्य संख्येयभागत्वेन निश्चीयत इत्यर्त्थः। अर्त्थश्चासावक्षरं च तदर्त्थाक्षरं तस्माज्जातं ज्ञानमर्त्थाक्षर ज्ञानं ।

अथवा त्रिविधमक्षरं लब्ध्यक्षरं निर्वृत्यक्षरं स्थापनाक्षरं चेति। तत्र पर्य्यायज्ञानावरण-प्रभृतिश्रुतकेवलज्ञानावरणपर्य्यंतक्षयोपशमोद्भूतात्मनोर्त्थग्रहणशक्तिर्लब्धिर्भावेंद्रियं । तद्रूपमक्षरं लब्ध्यक्षरं अक्षरज्ञानोत्पत्तिहेतुत्वात् । कंठोष्टताल्वादिस्थानस्पृष्टतादिकरणप्रयत्ननिर्व्वर्त्यमानस्वरूप-मकारादिककारादिस्वरव्यंजनरूपमूलवर्णतत्संयोगादिसंस्थानं निर्वृत्यक्षरं । पुस्तकेषु तत्तद्देशानु-

---

यथाक्रमं चतुरङ्कपञ्चाङ्कषडङ्कसप्ताङ्काष्टाङ्कवृद्धियुतस्थानानि उत्पद्यन्ते, न च केवलं पर्यायजघन्यज्ञानमेव भक्त्वा गुणयित्वा उत्पद्यते इति निश्चेतव्यं, इदमर्थाक्षरज्ञानं के उ अपवर्तितं सन् श्रुतकेवलज्ञान-
१८=उ
संख्यातभागमात्रं अर्थाक्षरज्ञानप्रमाणं भवति के अक्षराज्जातं ज्ञानं अक्षरज्ञानं अर्थविषयमर्थग्राहकं
१८=
अर्थाक्षरज्ञानं अथवा अर्यते गम्यते ज्ञायते इत्यर्थः, न क्षरति इत्यक्षरं द्रव्यरूपतया विनाशाभावात् । अर्थश्चासावक्षरं च तदर्थाक्षरम् । अथवा अर्यते गम्यते श्रुतकेवलस्य संख्येयभागत्वेन निश्चीयते इत्यर्थः, अर्थश्चासावक्षरं च तदर्थाक्षरं तस्माज्जातं ज्ञानमर्थाक्षरज्ञानम् । अथवा त्रिविधमक्षरं लब्ध्यक्षरं निर्वृत्यक्षरं स्थापनाक्षरं चेति । तत्र पर्यायज्ञानावरणप्रभृतिश्रुतकेवलज्ञानावरणपर्यन्तक्षयोपशमादुद्भूतात्मनोऽर्थग्रहणशक्तिर्लब्धिः भावेन्द्रियं, तद्रूपमक्षरं लब्ध्यक्षरं, अक्षरज्ञानोत्पत्तिहेतुत्वात् कण्ठोष्ठताल्वादिस्थानस्पृष्टतादिकरणप्रयत्ननिर्वर्त्यमानस्वरूपं अकारादिककारादिस्वरव्यञ्जनरूपं मूलवर्णतत्संयोगादिसंस्थानं निर्वृत्यक्षरम् । पुस्तकेषु तत्तद्देशानुरूपतया

के समान है इसलिए चतुरंकसे लेकर अष्टांक पर्यन्त षट्स्थानोंके भागवृद्धि और गुण वृद्धिसे युक्त सब स्थान अपने-अपने अनन्तर पूर्व अष्टांक वृद्धि युक्त स्थानसे भाग देनेपर जितना प्रमाण आवे उससे पुनः उस पूर्व स्थानको गुणा करनेपर यथाक्रमसे चतुरंक, पंचांक, षष्ठांक, सप्तांक और अष्टांक वृद्धि युक्त स्थान उत्पन्न होते हैं। केवल जघन्य पर्याय ज्ञानमें भाग देकर और फिर उसीसे गुणा करनेपर ये स्थान उत्पन्न नहीं होते। यह निश्चित जानना। इस प्रकार श्रुत केवल ज्ञानका संख्यातवाँ भाग मात्र अर्थाक्षर श्रुत ज्ञानका प्रमाण होता है।

अक्षरसे उत्पन्न हुआ ज्ञान अक्षर ज्ञान है। जो अर्थको विषय करता है या अर्थका ग्राहक है वह अर्थाक्षर ज्ञान है। अथवा जो अर्यते अर्थात् जाननेमें आता है वह अर्थ है और द्रव्य रूपसे विनाश न होनेसे अक्षर है अर्थ और अक्षरको अर्थाक्षर कहते हैं। अथवा 'अर्यते' अर्थात् श्रुत केवलके संख्यातवें भाग रूपसे जिसका निश्चय किया जाता है वह अर्थ है। अर्थ और अक्षर अर्थाक्षर है। उससे उत्पन्न ज्ञान अर्थाक्षर ज्ञान है। अथवा अक्षर तीन प्रकारका है—लब्ध्यक्षर, निर्वृत्यक्षर, और स्थापनाक्षर। उनमें-से पर्याय ज्ञानावरणसे लेकर श्रुतकेवलज्ञानावरण पर्यन्तके क्षयोपशमसे उत्पन्न आत्माकी अर्थको ग्रहण करनेकी शक्ति लब्धि-

अनंतरं गाथाद्वयदिदं शास्त्रकारनक्षरसमासमं पेळ्दपं :—

एयक्खरादु उवरिं एगेगेणक्खरेण वड्ढंतो ।

संखेज्जे खलु उड्ढे पदणामं होदि सुदणाणं ॥३३५॥

एकाक्षरादुपरि चैकैकेनाक्षरेण वर्द्धमानाः । संख्येये खलु वृद्धे पदनाम भवति श्रुतज्ञानं ॥

एकाक्षरजनितार्त्थज्ञानदमेले तु मत्ते पूर्वोक्तक्रमदिं षट्स्थानवृद्धिरहितमागि एकैकाक्षरदिंद वर्द्धमानमागुत्तिरलु द्वयक्षरत्र्यक्षरादिरूपोनेकपदाक्षरमात्रपर्य्यंतसमुदायश्रवणजनिताक्षरसमासज्ञानविकल्पंगळु संख्येयंगळु द्विरूपोनैकपदाक्षरप्रमितंगळु सलुत्तं विरलु तदनंतरमुत्कृष्टाक्षरसमासविकल्पद मेले एकाक्षरवृद्धियागुत्तिरलु पदनाममनुळ्ळ श्रुतज्ञानमक्कुं ।

सोलससयचउतीसा कोडी तियसीदिलक्खयं चेव ।

सत्तसहस्सट्ठसया अट्ठासीदी य पदवण्णा ॥३३६॥

षोडशशतचतुस्त्रिंशत्कोट्यस्त्र्यशीतिलक्षाणि चैव । सप्तसहस्राष्टशताष्टाशीतिश्च पदवर्णाः ॥

इल्लि अर्त्थपदं प्रमाणपदं मध्यमपदमें दु पदं त्रिविधमक्कुं । अल्लियें निरक्षरसमूहदिंदं विवक्षितार्त्थमरियल्पडुगुमदर्त्थपदमक्कुं । मां दंडेन शालिभ्यो निवारय । त्वमग्निमानय । इत्यादिगळु । अष्टाक्षरादिसंख्येयिदं निष्पन्नमप्पक्षरसमूहं प्रमाणपदमें बुदक्कुं । नमः श्रीवर्द्धमानाय । एंदितु मोदलादुवु । षोडशशतचतुस्त्रिंशत्कोटिर्त्र्यशीतिलक्षाणि । सप्तसहस्राष्टशताष्टाशीतिश्च पदवर्णाः एंदी गाथोक्तक्रमसंख्यदि पुनरुक्ताक्षरंगळ समूहं मध्यमपदमें बुदक्कुं १६३४८३०७८८८

॥३३४॥ अथ गाथाद्वयेन शास्त्रकारः अक्षरसमासं कथयति—

एकाक्षरजनितार्थज्ञानस्योपरि पुनःपुनः पूर्वोक्तषट्स्थानवृद्धिक्रमरहिततया एकैकाक्षरेणैव वर्धमानाः द्व्यक्षरत्र्यक्षरादिरूपोनैकपदाक्षरमात्रपर्यन्तसमुदायश्रवणजनिताक्षरसमासज्ञानविकल्पाः संख्येयाः द्विरूपोनैकपदाक्षरप्रमिताः. तदा अनन्तरमुत्कृष्टस्योपरि एकाक्षरवृद्धौ सत्यां पदनाम श्रुतज्ञानं भवति ॥३३५॥

अथ अर्थपद प्रमाणपद मध्यमपद चेति पद त्रिविधम् । तत्र यावताक्षरसमूहेन विवक्षितार्थो ज्ञायते तदर्थपदम् । दण्डेन शालिभ्यो गां निवारय, त्वमग्निमानय इत्यादयः । अष्टाक्षरादिसंख्यया निष्पन्नोऽक्षरसमूहः प्रमाणपदं 'नमः श्रीवर्धमानाय' इत्यादि । षोडशशतचतुस्त्रिंशत्कोटि- त्र्यशीतिलक्षाणि सप्तसहस्राणि अष्टशतानि

अब शास्त्रकार दो गाथाओंसे अक्षर समासको कहते हैं—

एक अक्षरसे उत्पन्न अर्थज्ञानके ऊपर पूर्वोक्त षट्स्थानपतित वृद्धिके क्रमके बिना एक-एक अक्षर बढ़ते हुए दो अक्षर तीन अक्षर आदि रूप एक हीन पदके अक्षर पर्यन्त अक्षर समूहके सुननेसे उत्पन्न अक्षर समास ज्ञानके विकल्प संख्यात हैं अर्थात् दो हीन पदके अक्षर प्रमाण हैं। उसके अनन्तर उत्कृष्ट अक्षर समासके विकल्पके ऊपर एक अक्षर बढ़नेपर पदनामक श्रुतज्ञान होता है ॥३३५॥

पदके तीन भेद हैं—अर्थपद, प्रमाणपद, मध्यमपद। जितने अक्षरोंके समूहसे विवक्षित अर्थका ज्ञान होता है वह अर्थपद है। जैसे डंडेसे गायको भगाओ। आग लाओ, इत्यादि। आठ आदि अक्षरोंकी संख्यासे बने अक्षर समूहको प्रमाण पद कहते हैं। जैसे 'नमः श्रीवर्धमानाय'। [illegible] सौ चौंतीस करोड़, तेरासी लाख, सात हजार आठ- [illegible] प्रमाण एक पदके अपुनरुक्त अक्षरों-

१. [illegible]

समासज्ञानोत्कृष्टविकल्पद मेलें एकाक्षरमे वृद्धमागुत्तिरलु संघातश्रुतज्ञानमक्कुं– प १००० १ मिदुवुं चतुर्गतिगळोळोंदु गतिस्वरूपनिरूपकमध्यमपदसमुदायरूपसंघातश्रवणजनितार्थज्ञानमक्कुं ।

अनंतरं प्रतिपत्तिकश्रुतज्ञानस्वरूपमं पेळ्दपं :—

एक्कदरगदिणिरूवयसंघादसुदादु उवरि पुव्वं वा ।
वण्णे संखेज्जे संघादे उड्ढम्मि पडिवत्ती ॥३३८॥

एकतमगतिनिरूपकसंघातश्रुतादुपरि पूर्ववत् । वर्णे संख्येये संघाते वृद्धे प्रतिपत्तिः ॥

पूर्व्वोक्तप्रमाणमप्प एकतमगतिनिरूपकसंघातश्रुतद मेलें पूर्व्वपरिपाटियिदमेकैकवर्णवृद्धिसहचरितमप्पेकैकपदवृद्धिक्रमदिदं संख्यातसहस्रपदमात्रसंघातंगळु संख्यातसहस्रप्रमितंगळु रूपोनसंघातसमासज्ञानविकल्पंगळु सलुत्तं विरलु तच्चरमसंघातोत्कृष्टविकल्पद प १००० १ । १००० १–१ वृद्धिय मेले एकाक्षरवृद्धियमेल्लेयागुत्तिरलु प्रतिपत्तिकमेंब श्रुतज्ञानमक्कु १६ = १०००।१।१०००१ । इदुवुं नारकादिचतुर्गतिस्वरूपसविस्तरप्ररूपकप्रतिपत्तिकाख्यग्रंथश्रवणसंजातार्थज्ञानमें दितु निश्चैगल्पडुवुदु ।

अनंतरमनुयोगश्रुतज्ञानमं पेळ्दपरु—

चरमस्य पदसमासज्ञानोत्कृष्टविकल्पस्य उपरि एकस्मिन्नक्षरे वृद्धे सति संघातश्रुतज्ञानं भवति १६ = १०००१ तच्चतसृणां गतीनां मध्ये एकतमगतिस्वरूपनिरूपकमध्यमपदसमुदायरूपसंघातश्रवणजनितार्थज्ञानं ॥३३७॥ अथ प्रतिपत्तिकश्रुतज्ञानस्वरूपं निरूपयति—

पूर्वोक्तप्रमाणस्य एकतमगतिनिरूपकसंघातश्रुतस्य उपरि पूर्वोक्तप्रकारेण एकैकवर्णवृद्धिसहचरितैकैकपदवृद्धिक्रमेण संख्यातसहस्रपदमात्रसंघातेषु संख्यातसहस्रेषु रूपोनेषु संघातसमासज्ञानविकल्पेषु गतेषु तच्चरमस्य संघातसमासोत्कृष्टविकल्पस्य १६ = १००० १ । १००० १–१ एतस्योपरि एकस्मिन्नक्षरे वृद्धे सति प्रतिपत्तिकं नाम श्रुतज्ञानं भवति १६ = १००० १ । १००० १ । तच्च नारकादिचतुर्गतिस्वरूपसविस्तरप्ररूपकप्रतिपत्तिकाख्यग्रन्थश्रवणजनितार्थज्ञानमिति निश्चेतव्यम् ॥३३८॥ अथानुयोगश्रुतज्ञानं प्ररूपयति—

है। इस प्रकार प्रत्येक एक पदके अक्षर मात्र विकल्पोंके बीतनेपर पदज्ञानके चतुर्गुने-पंचगुने होते-होते संख्यात हजार गुणित पदमात्र पदसमास ज्ञानके विकल्पोंमें एक अक्षर घटानेपर जो प्रमाण रहे उतने पदसमास ज्ञानके विकल्प होते हैं। अन्तिम पदसमास ज्ञानके उत्कृष्ट विकल्पके ऊपर एक अक्षर बढ़ानेपर संघात श्रुतज्ञान होता है। सो चार गतियोंमें-से किसी एक गतिके स्वरूपका कथन करनेवाले मध्यमपदके समुदायरूप संघात श्रुतज्ञानके सुननेसे जो अर्थज्ञान होता है वह संघात श्रुतज्ञान है ॥३३७॥

अब प्रतिपत्ति श्रुतज्ञानका स्वरूप कहते हैं—

पूर्वोक्त प्रमाण किसी एक गतिके निरूपक संघात श्रुतके ऊपर पूर्वोक्त प्रकारसे एक-एक अक्षरकी वृद्धिपूर्वक एक-एक पदकी वृद्धिके क्रमसे संख्यात हजार पदप्रमाण संख्यात हजार संघात होते हैं। उनमें एक अक्षर कम करनेपर संघात श्रुतज्ञानके विकल्प होते हैं। उनके अन्तिम संघात समासके उत्कृष्ट विकल्पके ऊपर एक अक्षर बढ़ानेपर प्रतिपत्ति नामक श्रुतज्ञान होता है। नारक आदि चार गतियोंके स्वरूपका विस्तारसे कथन करनेवाले प्रतिपत्तिक नामक ग्रन्थके सुननेसे होनेवाला अर्थज्ञान प्रतिपत्ति श्रुतज्ञान होता है ॥३३८॥

अब अनुयोग श्रुतज्ञानको कहते हैं—

अहियारो पाहुडयं एयट्ठो पाहुडस्स अहियारो।
पाहुडपाहुडणामं होदित्ति जिणेहि णिद्दिट्ठं ॥३४१॥

अधिकारः प्राभृतकमेकार्थः प्राभृतस्याधिकारः प्राभृतकप्राभृतकनामा भवतीति जिनैर्निर्दिष्टं ॥

वस्तुवेंब श्रुतज्ञानद अधिकारः प्राभृतकमें बेरडुमेकार्थंगळु। प्राभृतद अधिकारमं प्राभृतकप्राभृतकमें बुदु अदुकारणदिदमेकार्थपर्य्यायशब्दमें दितु जिनेंद्रभट्टारकरिदं पेळल्पट्टुदु। स्वरुचिविरचितमल्तें बुदर्थं।

द्विकवारप्राभृतानंतरं प्राभृतकस्वरूपमं पेळ्दपरः—

दुगवारपाहुडादो उवरिं वण्णे कमेण चउवीसे।
दुगवारपाहुडे संउड्ढे खलु होदि पाहुडयं ॥३४२॥

द्विकवारप्राभृतकादुपरि वर्णे क्रमेण चतुर्विंशतौ। द्विकवारप्राभृते संवृद्धे खलु भवति प्राभृतकं ॥

द्विकवारप्राभृतकदिदं मेले तदुपरि पूर्व्वोक्तक्रमदिदं प्रत्येकमेकैकवर्णवृद्धिसहचरितपदादिवृद्धिगळिदं चतुर्व्विंशतिप्राभृतकप्राभृतकंगळु पेर्चुत्तिरलु रूपोनतावन्मात्रंगळु प्राभृतकप्राभृतकसमासज्ञानविकल्पंगळु सल्लुत्तं विरलु तच्चरमोत्कृष्ट विकल्पद मेले एकाक्षरवृद्धियागुत्तिरलु प्राभृतकमें ब श्रुतज्ञानमक्कुं।

अनंतरं वस्तुवें ब श्रुतज्ञानस्वरूपमं पेळ्दपं—

वस्तुनामश्रुतज्ञानस्य अधिकारः प्राभृतकं वेति द्वौ एकार्थौ। प्राभृतकस्य अधिकारोऽपि प्राभृतकप्राभृतकनामा भवति ततः कारणात् एकार्थः पर्यायशब्दः इति जिनैः—अर्हद्भट्टारकैः निर्दिष्टं न स्वरुचिविरचितमिदम्. ॥३४१॥ द्विकवारप्राभृतकानन्तरं प्राभृतकस्वरूपं प्ररूपयति—

द्विकवारप्राभृतकात्परं तदुपरि पूर्वोक्तक्रमेण प्रत्येकमेकैकवर्णवृद्धिसहचरितपदादिवृद्धिभिः चतुर्विंशतिप्राभृतकप्राभृतकेषु वृद्धेषु रूपोनतावन्मात्रेषु प्राभृतकप्राभृतकसमासज्ञानविकल्पेषु गतेषु तच्चरमसमासोत्कृष्टविकल्पस्योपरि एकाक्षरवृद्धौ सत्यां प्राभृतकं नाम श्रुतज्ञानं भवति ॥३४२॥ अथ वस्तुनामश्रुतज्ञानस्वरूपमाह—

समास ज्ञानके विकल्प होते हैं। उसके अन्तिम अनुयोग समासके उत्कृष्ट विकल्पके ऊपर एक अक्षरके बढ़नेपर प्राभृतक-प्राभृतक नामक श्रुतज्ञान होता है ॥३४०॥

वस्तु नामक श्रुतज्ञानका अधिकार कहो या प्राभृतक कहो, दोनोंका एक ही अर्थ है। प्राभृतकका अधिकार भी प्राभृतक-प्राभृतक नामक होता है। ऐसा अर्हन्त देवने कहा है, स्वरुचि रचित नहीं है ॥३४१॥

अब प्राभृतकका स्वरूप कहते हैं—

प्राभृतक-प्राभृतकसे आगे उसके ऊपर पूर्वोक्त प्रकारसे प्रत्येक एक-एक अक्षरकी वृद्धिके क्रमसे पद आदिकी वृद्धिके होते-होते चौबीस प्राभृतक प्राभृतकोंकी वृद्धिमें एक अक्षर घटानेपर प्राभृतक-प्राभृतक समासके भेद होते हैं। उसके अन्तिम भेदमें एक अक्षर बढ़ानेपर प्राभृतक श्रुतज्ञान होता है। उसके ऊपर पूर्वोक्त क्रमसे एक-एक अक्षरकी वृद्धिके क्रमसे बीस प्राभृतक नामक अधिकारोंके बढ़नेपर प्राभृतक नामक श्रुतज्ञान होता है। उसमें एक अक्षर कम करनेपर उतने मात्र प्राभृतक समास ज्ञानके विकल्प होते हैं। उसके अन्तिम प्राभृतक समासके उत्कृष्ट विकल्पके ऊपर एक अक्षर बढ़नेपर

[illegible] दस दस दस दस वस्तुगळु वृद्धिंगळागुत्तिरलु।

उप्पायपुव्वगेणिय विरियपवादत्थिणत्थियपवादे।
णाणासच्चपवादे आदाकम्मपवादे य ॥३४५॥
पच्चक्खाणे विज्जाणुवादकल्लाणपाणवादे य।
किरियाविसालपुव्वे कमसोथ तिलोय बिंदुसारे य ॥३४६॥

[illegible] वीर्यप्रवादास्तिनास्तिप्रवादे। ज्ञानसत्यप्रवादे आत्मकर्मप्रवादे च ॥
[illegible] कल्याणप्राणवादे च। क्रियाविशालपूर्वे क्रमशोथ त्रिलोकबिन्दुसारे च ॥

[illegible] वीर्यप्रवादपूर्व्वमस्तिनास्तिप्रवादपूर्व्वं ज्ञानप्रवादपूर्व्वं [illegible] कर्म्मप्रवादपूर्व्वं प्रत्याख्यानपूर्व्वं विद्यानुवादपूर्व्वं कल्याणवादपूर्व्वं [illegible] त्रिलोकबिन्दुसारपूर्व्वं येंदितु चतुर्द्दशपूर्व्वंगळप्पुविवरोळु [illegible] प्रत्येकमेकैकर्गं वृद्धिगळ्गविरतिरावृद्धियिदं दशवस्तुप्रमितवस्तु[illegible] विंतु [illegible] सगुणितसमासज्ञानविकल्पंगळोळु चरमवस्तु[illegible] वृद्धियागुत्तं विरलु [illegible] श्रुतज्ञानमक्कुमल्लिवरलायुत्तार[illegible] [illegible] दशवस्तुगळु वृद्धिंगळु [illegible]

[illegible] वीर्यप्रवादपूर्व अस्तिनास्तिप्रवादपूर्व ज्ञानप्रवादपूर्व सत्यप्रवादपूर्व [illegible] विद्यानुवादपूर्व कल्याणवादपूर्व प्राणवादपूर्व क्रियाविशालपूर्व [illegible] उपरि-उपरि प्रत्येकमेकैकवर्ण[illegible] उत्पादपूर्वश्रुतज्ञानं भवति। तत [illegible] उपरि [illegible]

[illegible] चौदह अधिकारोंमें क्रमसे दस, चौदह, आठ, अठारह, [illegible] बीस, पन्द्रह, दस, दस, दस, दस वस्तु अधिकार होते हैं। [illegible]

[illegible] अग्रायणीपूर्व वीर्य प्रवाद पूर्व, अस्तिनास्ति प्रवाद पूर्व, ज्ञान[illegible] सत्यप्रवादपूर्व, आत्मप्रवादपूर्व, कर्मप्रवादपूर्व, प्रत्याख्यान पूर्व, विद्यानुवाद[illegible] कल्याणवादपूर्व, प्राणावाद पूर्व, क्रियाविशाल पूर्व, त्रिलोकबिन्दुसार पूर्व ये चौदह पूर्व [illegible] अक्षरकी वृद्धिके साथ दस [illegible] वस्तु श्रु[illegible] [illegible] विकल्प [illegible] ऊपर एक [illegible] है। फिर [illegible] पूर्व [illegible] ऊपर एक-[illegible] वृद्धि होनेपर [illegible] विकल्प होते हैं। [illegible]

३९०० वस्तुगळ प्रमाणमनिप्पत्तरिदं गुणिसुतिरलु तत्संख्ये संभविसुगुमप्पुदरिंदं ।

अनंतरं पूर्व्वोक्तविंशतिप्रकारश्रुतज्ञानविकल्पोपसंहारमं गाथाद्वयदिदं पेळ्दपं :—

अत्थक्खरं च पदसंघादं पडिवत्तियाणियोगं च ।
दुगवारपाहुडं च य पाहुडयं वत्थुपुव्वं च ॥३४८॥
कमवण्णुत्तरवड्ढिय ताण समासा य अक्खरगदाणि ।
णाणवियप्पे वीसं गंथे बारस य चोद्दसयं ॥३४९॥

अर्थाक्षरं च पदसंघातं प्रतिपत्तिकानुयोगं च । द्विकवारप्राभृतकं च च प्राभृतकं वस्तु-पूर्वं च ॥ क्रमवर्णोत्तरवर्द्धिततत्समासाश्च अक्षरगतानि । ज्ञानविकल्पे विंशतिः ग्रंथे द्वादश च चतुर्दशकं ॥

अर्थाक्षरमेंबुदु रूपोनैकट्ठविभक्तश्रुतकेवलज्ञानमात्रमेकाक्षरप्रमाणमक्कु के मो / १८= अर्थाक्षरमुं पदमुं संघातमुं प्रतिपत्तिकमुं अनुयोगमुं द्विकवारप्राभृतमुं प्राभृतकमुं वस्तुवुं पूर्व्वमुमेंबी यो भत्तुमीभत्तरक्रमवर्णोत्तरवर्द्धितंगळप्पो भत्तुं समासंगळुमितष्टादशभेदंगळुमक्षरगतंगळु द्रव्यश्रुतविकल्पंगळप्पुवु । तत् द्रव्यश्रुतश्रवणसंजनितश्रुतज्ञानं विवक्षिसल्पडुत्तिरलुमनक्षरात्मकपर्य्याय-पर्य्यायसमासज्ञानद्वयसहितं विंशतिविकल्पं श्रुतज्ञानमक्कुं । ग्रंथे शास्त्रसंदर्भं विवक्षिसल्पडुत्तं विरलु द्वादश आचारांगादि द्वादशांगविकल्पमुमुत्पादपूर्व्वादिचतुर्दशपूर्व्वभेदमुमप्प द्रव्यश्रुतमुं तच्छ्रवणजनितज्ञान-

---

३९०० । वस्तुसंख्यायां विंशत्या गुणितायां तत्संख्यासंभवात् ॥३४७॥ अथ पूर्वोक्तविंशतिविधश्रुतज्ञानविकल्पोपसंहारं गाथाद्वयेनाह—

अर्थाक्षरं तु रूपोनैकट्ठविभक्तश्रुतकेवलमात्रमेकाक्षरज्ञानं के / १८= तच्च तथा पदं च संघातं प्रतिपत्तिकं अनुयोगं द्विकवारप्राभृतकं प्राभृतकं वस्तु, पूर्वं चेति नव पुनः एषामेव नवानां क्रमवर्णोत्तरवर्धिताः समासाश्च नव एवमष्टादशभेदा अक्षरगतद्रव्यश्रुतविकल्पा भवन्ति । तद्द्रव्यश्रुतश्रवणसंजनितश्रुतज्ञानमेव पुनः ज्ञाने विवक्षिते अनक्षरात्मकपर्यायपर्यायसमासज्ञानद्वययुतं सत् विंशतिविधं श्रुतज्ञानं भवति । ग्रन्थे शास्त्रसन्दर्भे विवक्षिते सति आचाराङ्गादिद्वादशाङ्गविकल्पं उत्पादपूर्वादिचतुर्दशपूर्वभेदं च द्रव्यश्रुतं तच्छ्रवणसंजनितज्ञान-

---

क्योंकि एक-एक वस्तुमें बीस-बीस प्राभृत होते हैं अतः वस्तुओंकी संख्या एक सौ पंचानवेमें बीससे गुणा करनेपर प्राभृतकोंकी संख्या उनतालीस सौ होती है ॥३४७॥

अब पूर्वोक्त श्रुतज्ञानके बीस भेदोंका उपसंहार दो गाथाओंसे करते हैं—

अर्थाक्षर, पद, संघात, प्रतिपत्ति, अनुयोग, प्राभृतक-प्राभृतक, प्राभृतक वस्तु, पूर्व ये नौ तथा इन्हीं नौके क्रमसे एक-एक अक्षरसे बढ़े नौ समास, इस प्रकार अठारह भेद अक्षरात्मक द्रव्यश्रुतके होते हैं। इस द्रव्यश्रुतके सुननेसे उत्पन्न हुआ श्रुतज्ञान ही अनक्षरात्मक पर्याय और पर्याय समास ज्ञानोंको मिलानेपर बीस प्रकारका श्रुतज्ञान होता है। ग्रन्थकी विवक्षा होनेपर आचारांग आदि बारह भेदरूप और उत्पाद पूर्व आदि चौदह भेदरूप द्रव्यश्रुत है और उसके सुननेसे उत्पन्न ज्ञानस्वरूप भावश्रुत है। 'च' शब्दसे अंगबाह्य, सामायिक आदि चौदह प्रकीर्णक भेदरूप द्रव्यश्रुत और भावश्रुतका समुच्चय किया जाता है। पुद्गल द्रव्य

यस्यार्थ्या एकदेशेन संत्यस्मिन्निति वस्तुपूर्व्वाधिकारः। पूरयति श्रुतार्थान् संबिभर्त्तीति पूर्व्वं। सं संगृह्य पर्य्यायादीनि पूर्व्वंपर्य्यंतानि स्वीकृत्य अस्यंते क्षिप्यंते विकल्प्यते इति समासाः। पर्य्यायज्ञानदत्तणिनुत्तरविकल्पंगळु पर्य्यायसमासंगळु। अक्षरज्ञानदत्तणिनुत्तरविकल्पंगळक्षरसमासंगळु इंतु मुंदेल्लेडेयोळं पदसमासादिगळु योज्यंगळप्पवु।

इल्लि पूर्व्वंगळु १४ वस्तुगळु १९५ प्राभृतकंगळु ३९०० द्विकवारप्राभृतकंगळु ९३६०० अनुयोगंगळु ३७४४०० प्रतिपत्तिकसंघातपदंगळु संख्यातसहस्रगुणितक्रमंगळु। एकपदाक्षरंगळु १६३४८३०७८८८ समस्ताक्षरंगळु रूपोनेकट्ठप्रमितंगळु १८४४६७४४०७३७०९५५१६१५ ईयक्षरंगळनेकपदाक्षरंगळिं प्रमाणिसुत्तं विरलु द्वादशांगपदप्रमाणमक्कुमें दु लब्धमं पेळ्दपं :—

बारुत्तरसयकोडी तेसीदी तह य होंति लक्खाणं।
अट्ठावण्णसहस्सा पंचेव पदाणि अंगाणं ॥३५०॥

द्वादशोत्तरं शतं कोटयस्त्र्यशीतिस्तथा च भवंति लक्षाणामष्टपंचाशत् सहस्राणि पंचैव पदान्यंगानां ॥

मूर्तं परिपूर्णं प्राभृतं वस्तुनोऽधिकारः, प्राभृतमिति संज्ञा यस्यास्तीति प्राभृतकं, प्राभृतकस्याधिकारः प्राभृतकप्राभृतकम्। वसन्ति पूर्वमहार्णवस्य अर्थाः एकदेशेन यस्मिन्निति वस्तु। पूर्वाधिकारः पूरयति श्रुतार्थान् संबिभर्तीति पूर्वम्। सं-संगृह्य पर्यायादीनि पूर्वपर्यन्तानि स्वीकृत्य अस्यन्ते क्षिप्यन्ते विकल्प्यन्ते इति समासाः। पर्यायज्ञानादुत्तरविकल्पाः पर्यायसमासाः। अक्षरज्ञानादुत्तरविकल्पा अक्षरसमासाः। एवमग्रेऽपि सर्वत्र पदसमासादयो योज्याः। अत्र पूर्वाणि १४, वस्तूनि १९५, प्राभृतकानि ३९००, द्विकवारप्राभृतकानि ९३६००, अनुयोगाः ३७४४००, प्रतिपत्तिकसंघातपदानि संख्यातसहस्रगुणितक्रमाणि एकपदाक्षराणि १६३४८३०७८८८, समस्ताक्षराणि रूपोनैकट्ठप्रमितानि १८४४६७४४०७३७०९५५१६१५। एतेष्वक्षरेषु एकपदाक्षरैः प्रमाणितेषु यल्लब्धं तद्द्वादशाङ्गपदप्रमाणं शेषमङ्गबाह्याक्षराणि ॥३४८–३४९॥ तत्र प्रथमं तत्पदप्रमाणमाह—

सम्बन्धी अर्थोंसे जो 'आभृत' परिपूर्ण है वह प्राभृत है। और प्राभृत संज्ञा होनेसे प्राभृतक है। प्राभृतकके अधिकारको प्राभृतक-प्राभृतक कहते हैं। जिसमें पूर्व नामक महासमुद्रके अर्थ 'वसन्ति' एक देशसे रहते हैं वह वस्तु है। वह पूर्वोंका अधिकार है। श्रुतके अर्थोंका 'पूरयति' पोषण करता है वह पूर्व है। सं अर्थात् पर्यायसे लेकर पूर्व पर्यन्त भेदोंको 'अस्यन्ते' अपनाता है वह समास है। पर्याय ज्ञानसे उत्तर भेद पर्याय समास हैं, अक्षर ज्ञानसे उत्तर भेद अक्षर समास हैं इसी प्रकार आगे भी पदसमास आदिकी योजना कर लेना। पूर्व चौदह हैं। वस्तु एक सौ पंचानबे हैं। प्राभृतक उनतालीस सौ हैं। प्राभृतक-प्राभृतक तिरानबे हजार छह सौ हैं। अनुयोग तीन लाख चौहत्तर हजार चार सौ हैं। प्रतिपत्तिक, संघात और पद उत्तरोत्तर क्रमसे संख्यात हजार गुणित हैं। एक पदके अक्षर सोलह सौ चौंतीस कोटि, तेरासी लाख सात हजार आठ सौ अठासी हैं। समस्त अक्षर एक कम एकट्ठी प्रमाण १८४४६७४४०७३७०९५५१६१५ हैं। इन अक्षरोंमें एक पदके अक्षरोंसे भाग देनेपर जो लब्ध आया वह द्वादशांगके पदोंका प्रमाण है और शेष बचा वह अंगबाह्यके अक्षरोंका प्रमाण है ॥३४८–३४९॥

पहले द्वादशांगके पदोंकी संख्या कहते हैं—

ओ अहो व्यंजनानि अर्द्धमात्रंगळप्प व्यंजनंगळु त्रयस्त्रिंशत्प्रमितंगळप्पुवु ३३ स्वराः स्वरंगळेक द्वित्रिमात्रंगळु सप्तविंशतिः सप्तविंशतिप्रमितंगळु २७ योगवाहाः योगवाहंगळु चत्वारश्च नाल्कु ४ अप्पुवु इंतु मूलवर्णंगळु चतुःषष्टिप्रमितंगळप्पुवेंदु ओ अहो भव्या नीनरियेंदितनादिनिधनपरमागम-दोळु प्रसिद्धंगळा प्रकारदिंदमे पेळल्पट्टुवु।

व्यज्यते स्फुटीक्रियतेऽर्थो यैस्तानि व्यंजनानि। स्वरंत्यर्थं कथयंतीति स्वराः। योगमन्या-क्षरसंयोगं वहंतीति योगवाहाः। मूलानि संयुक्तोत्तरवर्णोत्पत्तिकारणभूता वर्णा मूलवर्णाः एंदितु समासार्थबलदिदमसंयुक्तमागिये चतुःषष्टिवर्णंगळु ग्राह्यंगळप्पुवु। ई वर्णंगळ संस्कृतदोळु दीर्घा-भावमादोडमनुकरणदोळं देशांतर भाषेगळोळं सद्भावमक्कुं। ए ऐ ओ औ एंबी नाल्कक्कं संस्कृत-दोळु ह्रस्वाभावमादोडं प्राकृतदोळं देशांतरभाषेगळोळं सद्भावमक्कुं।

चउसट्ठिपदं विरलिय दुगं च दाऊण संगुणं किच्चा।
रूऊणं च कए पुण सुदणाणस्सक्खरा होंति ॥३५३॥

चतुःषष्टिपदं विरलयित्वा द्विकं च दत्वा संगुणं कृत्वा। रूपोनं च कृते पुनः श्रुतज्ञानस्या-क्षराणि भवंति ॥

ओ-अहो भव्य! व्यञ्जनानि अर्धमात्राणि क् ख् ग् घ् ङ्। च् छ् ज् झ् ञ्। ट् ठ् ड् ढ् ण्। त् थ् द् ध् न्। प् फ् ब् भ् म्। य् र् ल् व् श् ष् स् ह्। इत्येतानि त्रयस्त्रिंशत् ३३। स्वराः एकद्वित्रि-मात्राः। अ इ उ ऋ ऌ ए ऐ ओ औ इत्येते नव, प्रत्येकं ह्रस्वदीर्घप्लुतभेदैस्त्रिभिर्गुणिताः अ आ आ ३, इ ई ई ३, उ ऊ ऊ ३, ऋ ॠ ॠ ३, ऌ ॡ ॡ ३, ए १ ए २ ए ३, ऐ १ ऐ २ ऐ ३, ओ १ ओ २ ओ ३, औ १ औ २ औ ३ इत्येते सप्तविंशतिः २७। योगवाहाः अं अः ᳵक ᳵप इत्येते चत्वारः ४, एवं मिलित्वा मूलवर्णाश्चतुःषष्टिः ६४। यथानादिनिधने परमागमे प्रसिद्धास्तथैवात्र भणिताः संजानीहि। व्यज्यते स्फुटीक्रियते अर्थो यैस्तानि व्यञ्जनानि। स्वरन्ति-अर्थं कथयन्तीति स्वराः। योगं-अन्याक्षरसंयोगं वहन्तीति योगवाहाः। मूलानि संयुक्तोत्तरवर्णोत्पत्तिकारणानि वर्णाः मूलवर्णाः इति समासार्थबलेन असंयुक्ता एव चतुःषष्टिरिति लभ्यते। ऌवर्णः संस्कृते दीर्घो नास्ति तथापि अनुकरणे देशान्तरभाषायां चास्ति। ए ऐ ओ औ इति चत्वारोऽपि संस्कृते ह्रस्वा न सन्ति तथापि प्राकृते देशान्तरभाषायां च सन्ति ॥३५२॥

'ओ' अर्थात् हे भव्य! अर्धमात्रा जिनमें होती है ऐसे सब व्यंजन तैंतीस हैं—

क् ख् ग् घ् ङ्। च् छ् ज् झ् ञ्। ट् ठ् ड् ढ् ण्। त् थ् द् ध् न्। प् फ् ब् भ् म्। य् र् ल् व् श् ष् स् ह्। एक-दो-तीन मात्रावाले स्वर सत्ताईस होते हैं—अ, इ उ ऋ ऌ ए ऐ ओ औ ये नौ। प्रत्येकको ह्रस्व, दीर्घ और प्लुत तीनसे गुणा करनेपर सत्ताईस होते हैं। अ आ आ ३। इ ई ई ३। उ ऊ ऊ ३। ऋ ॠ ॠ ३। ऌ ॡ ॡ ३। ए १ ए २ ए ३। ऐ १ ऐ २ ऐ ३। ओ १ ओ २ ओ ३। औ १ औ २ औ ३। अं अः ᳵक ᳵप ये चार योगवाह। इस प्रकार सब मिलकर मूल अक्षर चौंसठ हैं। जैसा अनादिनिधन परमागममें प्रसिद्ध हैं वैसा ही यहाँ कहे हैं।

'व्यज्यते' जिनके द्वारा अर्थ प्रकट किया जाता है वे व्यंजन हैं। 'स्वरन्ति' जो अर्थको कहते हैं वे स्वर हैं। योग अर्थात् अन्य अक्षरोंके संयोगको जो 'वहन्ति' वहन करते हैं वे योगवाह हैं। 'मूल' अर्थात् संयुक्त उत्तर वर्णोंकी उत्पत्तिके कारण वर्ण मूल वर्ण हैं। इस समासके अर्थके बलसे असंयुक्त अक्षर ही चौंसठ हैं यह ज्ञान होता है। ऌ वर्ण संस्कृत भाषामें दीर्घ नहीं है, तथापि देशान्तरकी भाषामें है। ए ऐ ओ औ ये चारों संस्कृतमें ह्रस्व नहीं हैं। तथापि प्राकृत और देशभाषामें हैं ॥३५२॥

इवेकद्वित्रिसंयोगादिचतुःषष्ठिसंयोगपर्य्यंतमप्प संयोगाक्षरसंजनिताक्षरंगळ संख्येयप्पुदरि ना एकद्वित्रिसंयोगाक्षरंगळिनुत्पत्तिक्रमं तोरल्पडुगुमदें तें दोडे व्यंजनंगळु त्रयस्त्रिंशत्प्रमितंगळु। स्वरंगळु सप्तविंशतिप्रमितंगळु। योगवहंगळु चतुःप्रमितंगळितु मूलवर्णंगळु चतुःषष्टिप्रमितंगळिवं क्रमदिदमय्वत्तनाल्कॆडॆयोळु बेरॆ बेरॆ तिर्य्यग्रूपदिदं स्थापिसि प्रत्येकं द्विसंयोगादिगळं माळ्पुदें तें दोडे कवर्णदोळु प्रत्येकभंगमो देयक्कुं १। द्विसंयोगमुळ्ळ खवर्णंदोळु प्रत्येकभंगदु १। द्विसंयोगभंग १। अंतु २। गवर्णंदोळु प्र १। द्वि २ त्रि ३। अंतु ४। घवर्णंदोळु प्र १। द्वि २ त्रि ३ च १ अंतु ८। ङवर्णंदोळु प्र १ द्वि ४ त्रि ६ च ४ पं १ अंतु १६। च वर्णंदोळु प्र १ द्वि ५ त्रि १० च १० पं ५ ष १ अंतु ३२। छवर्णंदोळु प्र १ द्वि ६ त्रि १५ च २० पं १५ ष ६ सप्त १ अंतु ६४। जवर्णंदोळु प्र १ द्वि ७ त्रि २१ च ३५ पं ३५ ष २१ सप्त ७ अष्ट १ अंतु १२८। झवर्णंदोळु प्र १ द्वि ८ त्रि २८

रूपोने कृते सति श्रुतज्ञानस्य द्वादशाङ्गप्रकीर्णकरूपश्रुतस्कन्धस्य द्रव्यश्रुतस्य अपुनरुक्ताक्षराणि भवन्ति। वाक्यार्थप्रतीत्यर्थं गृहीतानां पुनरुक्ताक्षराणां संख्यानियमाभावात् ॥३५३॥ तदपुनरुक्ताक्षरप्रमाणं कियदिति चेदाह—

एकाष्टचतुश्चतुःषट्सप्तकं चतुश्चतुःशून्यसप्तत्रिकसप्तशून्यं नवपञ्चपञ्च एकं षट्कैकश्च पञ्चकं च इत्येकाद्यङ्कादिपञ्चाङ्कावसानविंशतिस्थानात्मकद्विरूपवर्गधारोत्पन्नरूपोनषष्ठवर्गप्रमाणाक्षराणि भवन्ति— १८४४६७४४०७३७०९५५१६१५। एतानि अक्षराणि एकद्वित्रिसंयोगादीनि चतुःषष्टिसंयोगपर्यन्तानि सन्ति तेषामुत्पत्तिक्रमो दर्श्यते तद्यथा—उक्तमूलवर्णचतुःषष्टि तिर्यक्पङ्क्त्या लिखित्वा तत्र कवर्णे प्रत्येकभङ्ग एकः १। द्विसंयोगो नास्ति। खवर्णे प्रत्येकभङ्गः १ द्विसंयोगभङ्गः १ एवं २। गवर्णे प्र १ द्वि २ त्रि १ एवं ४। घवर्णे प्र १ द्वि ३ त्रि ३ च १ एवं ८। ङवर्णे प्र १ द्वि ४ त्रि ६ च ४ पं १ एवं १६। चवर्णे प्र १ द्वि ५ त्रि १० च १० पं ५ ष १ एवं ३२। छवर्णे प्र १ द्वि ६ त्रि १५ च २० पं १५ ष ६ सप्त १ एवं ६४। जवर्णे प्र १ द्वि ७ त्रि २१ च ३५ पं ३५ ष २१ सप्त ७ अष्ट १ एवं १२८। झवर्णे प्र १ द्वि ८ त्रि २८

दोका अंक देकर परस्परमें गुणा करनेपर जो लब्ध प्राप्त हो उसमें एक कम करनेपर द्वादशांग और प्रकीर्णक श्रुतस्कन्ध रूप द्रव्य श्रुतके अपुनरुक्त अक्षर होते हैं। वाक्यके अर्थका ज्ञान करानेके लिए गृहीत पुनरुक्त अक्षरोंकी संख्याका कोई नियम नहीं है ॥३५३॥

एक आठ चार चार छह सात चार चार शून्य सात तीन सात शून्य नौ पाँच पाँच एक छह एक पाँच १८४४६७४४०७३७०९५५१६१५ इस प्रकार एक अंकसे लेकर पाँच अंक पर्यन्त बीस स्थानरूप अपुनरुक्त अक्षर होते हैं। सो द्विरूप वर्गधारामें उत्पन्न एक हीन छठे वर्ग प्रमाण हैं। ये अक्षर एक संयोगी दो संयोगी तीन संयोगी आदि चौंसठ संयोग पर्यन्त होते हैं। उनकी उत्पत्तिका क्रम दिखलाते हैं—

उक्त मूल वर्ण चौंसठ एक पंक्तिमें लिखें। उनमें-से कवर्णमें प्रत्येक भंग एक है। द्विसंयोगी आदि नहीं है। खवर्णमें प्रत्येक भंग एक द्विसंयोगी भंग एक है। इस प्रकार दो भंग हैं। गवर्णमें प्रत्येक एक, दो संयोगी दो, तीन संयोगी एक, इस तरह चार भंग हैं। घवर्णमें प्रत्येक एक, दो संयोगी तीन, तीन संयोगी तीन, चार संयोगी एक, इस तरह आठ भंग हैं। ङवर्णमें प्रत्येक एक, दो संयोगी चार, तीन संयोगी छह, चार संयोगी चार, पाँच संयोगी एक, इस तरह सोलह भंग हैं। चवर्णमें प्रत्येक एक, दो संयोगी पाँच, त्रिसंयोगी दस, चार संयोगी दस, पाँच संयोगी पाँच, छह संयोगी एक, इस तरह बत्तीस भंग हैं। छवर्णमें प्रत्येक एक, दो संयोगी छह, तीन संयोगी पन्द्रह, चार संयोगी बीस, पाँच संयोगी पन्द्रह, छह संयोगी छह, सात संयोगी एक, इस तरह चौंसठ भंग हैं। जवर्णमें प्रत्येक एक दो, संयोगी सात, तीन

प्रमा त्रिसंयोगचतुःसंयोगपंचसंयोगादिस्वसंभवसंयोगंगळ प्रमाणं रूपाधिकवारहीनपदसंकलितं भवति। रूपाधिकैकद्वित्रिवारादिस्वसंभवसंकलनसंख्या १ १ १ १ १ १ १ १ विहीनविवक्षित-
१ २ ३ ४ ५ ६ ७ ८
पदं :—१०।–२।१०।–३।१०।–४।१०।–५।१०।–६।१०।–७।१०।–८।१०।–९। ई पदंगळ तत्तद्वारसंकलितं यावत्तावद्भवति। त्रियोगंगळु रूपाधिकैकवारसंकलनसंख्याहीनपद-देकवारसंकलितमक्कुं १०—२।१०। अपवर्त्तितमिदु।३६। चतुःसंयोगंगळु त्रिरूपोनपदद्विकवार-
२ १
संकलितमक्कुं ७।८।९ अपवर्त्तितमिदु।८४। पंचसंयोगंगळु चतूरूपोनपदत्रिवारसंकलितमक्कुं
३।२।१
६।७।८।९ अपवर्त्तितमिदु। १२६। षट्संयोगंगळु पंचरूपोनपदचतुर्वारसंकलितमक्कुं
४।३।२।१
५।६।७।८।९ अपवर्त्तितमिदु–१२६। सप्तसंयोगंगळु षड्रूपोनपदपंचवारसंकलितमक्कुं
५।४।३।२।१

विवक्षितपदस्य यावत्तावद्भवति। यथा दशमे अवर्णे त्रिसंयोगाः द्विरूपोनपदस्य एकवारसंकलनमात्राः—
१०—२।१०—१ अपवर्तिताः ३६ चतुःसंयोगाः त्रिरूपोनपदस्य द्विकवारसंकलनमात्राः—
२ । १
७।८।९ अपवर्तिताः ८४। पञ्चसंयोगाः चतूरूपोनपदस्य त्रिकवारसंकलनमात्राः ६।७।८।९
३।२।१ ४।३।२।१
अपवर्तिताः १२६। षट्संयोगाः पञ्चरूपोनपदस्य चतुर्वारसंकलनमात्राः ५।६।७।८।९ अपवर्तिताः
५।४।३।२।१

आदिका प्रमाण यथाक्रम एक अधिक वार हीन गच्छका संकलन धन मात्र है। जितनी बार संकलन हो उतने बारोंकी संख्यामें एक अधिक करके और उसे विवक्षित गच्छमें घटानेपर जो शेष प्रमाण रहे उतनेका संकलन करना चाहिए। जैसे दसवें अवर्णमें त्रिसंयोगी भंग लानेके लिए एक बार संकलनका प्रमाण एक होनेसे उसमें एक अधिक करनेपर दो हुए। इस दोको गच्छ दसमें-से घटानेपर शेष आठ रहे। इस आठका एक बार संकलन धन मात्र त्रिसंयोगी भंग होते हैं। संकलन धन लानेके लिए कहे गये करणसूत्रके अनुसार विवक्षित दसवें अवर्णमें प्रत्येक भंग दस, द्विसंयोगी एक कम गच्छ प्रमाण नौ, त्रिसंयोगी भंग दो हीन गच्छ प्रमाण आठका एक बार संकलन धन मात्र हैं। सो संकलन धन लानेके सूत्रके अनुसार आठ और नौको दो और एकसे भाग देकर अपवर्तन करनेपर छत्तीस होते हैं। अर्थात् आठ और नौको परस्परमें गुणा करनेपर बहत्तर हुए। और दो-एकको परस्परमें गुणा करनेपर दो हुए। दोसे बहत्तरमें भाग देनेपर छत्तीस रहते हैं। इसी तरह चतुःसंयोगी भंग तीन हीन गच्छका दो बार संकलन धन मात्र हैं। सो सात, आठ, नौको तीन, दो, एकका भाग देनेपर ७।८।९। अपवर्तन करनेपर चौरासी होते हैं। पंचसंयोगी भंग चार हीन
३।२।१।
गच्छका तीन बार संकलन धन मात्र हैं। सो छह, सात, आठ, नौ को चार, तीन, दो, एकसे भाग देकर ६।७।८।९। अपवर्तन करनेपर एक सौ छब्बीस होते हैं। षट्संयोगी भंग
४।३।२।१।

संकलनवारसंख्याहीनपदंगळ ६४-२। -६४-३। -६४-४। ६४-५। ०००० । ६-४-६३ तत्तद्वार-संकलितं यावत्तावद्भवति एंदितु त्रिसंयोगंगळु रूपाधिकैकवारसंकलनसंख्याहीनपदद एकवार-संकलितमक्कुं ६४-२। ६४। १ अपर्वाततमिदु १९५३ चतुःसंयोगंगळु त्रिरूपोनपदद्विकवार-
२ १
संकलितमक्कुं ६१। ६२। ६३ अपवर्तितमिदु ३९७११ पंचसंयोगंगळु चतूरूपोनपदत्रिवारसंकलित-
३ २ १
मक्कुं ६०। ६१। ६२ अपवर्तितमिदु ५९५६६५ षट्संयोगंगळु पंचरूपोनपदचतुर्व्वारसंकलित-
४। ३। २
मक्कुं ५९। ६०। ६१। ६२। ६३ अपवर्तितमिदु ७०२८८४७ सप्तसंयोगंगळु षड्रूपोनपदपंच-
५ ४ ३ २ १
वारसंकलितमक्कुं ५८। ५९। ६०। ६१। ६२। ६३ अपवर्तितमिदु गुणितमिदु ६७९४५५२१
६ ५ ४ ३ २ १
अष्टसंयोगंगळु सप्तरूपोनपद षड्वारसंकलितमक्कुं ५७। ५८। ५९। ६०। ६१। ६२। ६३
७ ६ ५ ४ ३ २ १
अपवर्तितगुणितमिदु ५५३२७०६७१ नवसंयोगंगळु अष्टरूपोनपदसप्तवारसंकलितमक्कु अपवर्तिते-

---

६४—२। ६४—१ अपवर्तितगुणिता १९५३। चतुःसंयोगाः त्रिरूपोनपदस्य द्विकवारसंकलनमात्राः
२ । १
६१। ६२। ६३। अपवर्तिताः ५९५६६५। षट्संयोगाः पञ्चरूपोनपदस्य चतुर्वारसंकलनमात्राः
३। २। १।
५९। ६०। ६१। ६२। ६३ अपवर्तिताः ७०२८८४७। सप्तसंयोगाः षड्रूपोनपदस्य पञ्चवारसंकलन-
५। ४। ३। २। १
मात्राः। अपवर्तिता ५८। ५९। ६०। ६१। ६२। ६३। ६७९४५५२१। अष्टसंयोगाः सप्तरूपोन-
६। ५। ४। ३। २। १।
पदस्य षड्वारसंकलनमात्राः। ५७। ५८। ५९। ६०। ६१। ६२। ६३। अपवर्तिताः ५५३२७०६७१।
७। ६। ५। ४। ३। २। १।

स्थानोंमें जानना। अन्तके चौसठवें स्थानमें प्रत्येक भंग एक, द्विसंयोगी भंग एक हीन गच्छ मात्र तिरसठ, त्रिसंयोगी भंग दो हीन गच्छका एक बार संकलन धन मात्र। सो बासठ और तिरसठको दो और एकका भाग देनेपर उन्नीस सौ तिरपन होते हैं। तथा चतुःसंयोगी भंग तीन हीन गच्छका दो बार संकलन धन मात्र। सो इकसठ, बासठ, तिरसठको तीन, दो, एकका भाग देनेपर उनतालीस हजार सात सौ ग्यारह भंग होते हैं। पंच संयोगी भंग चार हीन गच्छका तीन बार संकलन धन मात्र। सो साठ, इकसठ, बासठ, तिरसठको चार, तीन, दो, एकका भाग देनेपर पाँच लाख पंचानवे हजार छह सौ पैंसठ होते हैं। छह संयोगी भंग पाँच हीन गच्छका चार बार संकलन धन मात्र। सो उनसठ, साठ, इकसठ, बासठ, तिरसठको पाँच, चार, तीन, दो, एकका भाग देनेपर सत्तर लाख अठाईस हजार आठ सौ सैंतालीस होते हैं। सात संयोगी भंग छह हीन गच्छका पाँच बार संकलन मात्र। सो अठावन, उनसठ, साठ, इकसठ, बासठ, तिरसठको छह, पाँच, चार, तीन, दो, एकका भाग देनेपर छह करोड़ उन्यासी लाख पैंतालीस हजार पाँच सौ इक्कीस होते हैं। आठ संयोगी

१ म[५८।५९।६०।]।

द्रव्यश्रुतमनधिकरिसिकोंडे निरुक्तियुं प्रतिपाद्यार्थमुं पदसंख्याविशेषंगळुमें वि पूर्व्वंगळोळु प्ररूपणे माडल्पडुगुमेकेंदोडे भावश्रुतदोळु निरुक्त्याद्यसंभवमप्पुदरिदं। द्वा गळ मोदलोळाचारांगं पेळल्पट्टुदेकेंदोडे मोक्षहेतुगळप्प संवरनिर्जराकारणपंचाच चारित्रप्रतिपादकत्वदिदं। मुमुक्षुगळिनादरिसल्पडुव मोक्षांगमप्प परमागमशास्त्रक्क वक्तव्यत्वं युक्तिसिद्धमेंदितु।

चतुर्ज्ञानसप्तर्द्धिसंपन्नरप्प गणधरदेवरुगळिदं तीर्थंकरमुखसरोजसंभू समस्तदिव्यध्वनिश्रवणावधारितसमस्तशब्दार्थंगळिदं शिष्यप्रतिशिष्यानुग्रहार्थमागि श्रुतस्कंधद्वादशांगंगळोळगे मोदळोळाचारांग विरचिसल्पट्टुदु। आचरंति समंततोऽ मोक्षमार्गमाराधयंत्यस्मिन्ननेनेति वा आचारस्तस्मिन् आचारांगे इंतप्पाचारांगदोळु—

जदं चरे जदं चिट्ठे जदं आसे जदं सये।
जदं भुंजेज्ज भासेज्ज एवं पावं ण बज्झइ ॥

कथं चरेत् कथमासीत कथं शयीत कथं भाषेत कथं भुंजीत कथं पापं न बध्यते। गणधरप्रश्नानुसारदिदं यतं चरेत् यतं तिष्ठेत् यतमासीत यतं शयीत। यतं भाषेत यतं

द्रव्यश्रुतमधिकृत्य निरुक्तिप्रतिपाद्यार्थपदसंख्याविशेषाणां तत्तदङ्गपूर्वेषु प्ररूपणा क्रियते भा निरुक्त्याद्यसंभवात्। अत्र द्वादशाङ्गेषु प्रथमाचाराङ्गं कथितम्। कुतः? मोक्षहेतुभूतसंवरनिर्जराकारण चारादिसकलचारित्रप्रतिपादकत्वेन मुमुक्षुभिराद्रियमाणस्य मोक्षाङ्गभूतस्य परमागमशास्त्रस्य प्रथमतो वक्तव्यत युक्तिसिद्धत्वात्। चतुर्ज्ञानसप्तर्द्धिसंपन्नगणधरदेवैः तीर्थंकरमुखसरोजसंभूतसर्वभाषात्मकदिव्यध्वनिश्रवण धारितसमस्तशब्दार्थैः शिष्यप्रशिष्यानुग्रहार्थं विरचितश्रुतस्कन्धद्वादशाङ्गानां मध्ये प्रथममाचाराङ्गं विरचितम् आचरन्ति समन्ततोऽनुतिष्ठन्ति मोक्षमार्गमाराधयन्ति अस्मिन्ननेनेति वा आचारः तस्मिन् आचाराङ्गे—

जदं चरे जदं चिट्ठे जदं आसे जदं सये।
जदं भुञ्जेज्ज भासेज्ज एवं पावं ण बज्झई ॥१॥

कथं चरेत्? कथं तिष्ठेत्? कथमासीत्? कथं शयीत? कथं भाषेत? कथं भुञ्जीत? कथं पापं न बध्यते? इति गणधरप्रश्नानुसारेण यतं चरेत्। यतं तिष्ठेत्। यतमासीत। यतं शयीत। यतं भाषेत। यतं

द्रव्यश्रुतको अधिकृत करके उस-उस अंग और पूर्वोंमें निरुक्ति, प्रतिपादित अर्थ और पदोंकी संख्याका कथन करते हैं क्योंकि भावश्रुतमें निरुक्ति आदि सम्भव नहीं हैं। द्वादशांग में पहला आचारांग कहा है क्योंकि मोक्षके हेतु संवर निर्जराके कारण पंचाचार आदि सकल चारित्रका प्रतिपादक होनेसे मुमुक्षुओंके द्वारा आदरणीय तथा मोक्षके अंगभूत आचार-का परमागम शास्त्रमें प्रथम वक्तव्य होना युक्तिसिद्ध है। चार ज्ञान और सात ऋद्धियोंसे सम्पन्न गणधरदेवने तीर्थंकरके मुखकमलसे उत्पन्न सर्वभाषामयी दिव्यध्वनिको सुनकर समस्त शब्दार्थको अवधारण करके शिष्य-प्रशिष्योंके अनुग्रहके लिए विरचित द्वादशांग श्रुत स्कन्धमें प्रथम आचारांगकी रचना की। जिसमें या जिसके द्वारा 'आचरन्ति' अच्छी रीतिसे आचरण करते हैं, मोक्ष मार्गकी आराधना करते हैं वह आचार है। उस आचारांगमें कैसे चलना, कैसे खड़े होना, कैसे बैठना, कैसे सोना, कैसे बोलना, कैसे भोजन करना कि पापका बन्ध न हो। इस गणधरके प्रश्नके अनुसार सावधानतापूर्वक चलिए, सावधानतापूर्वक खड़े होइए, सावधानता पूर्वक बैठिए सावधानता

पुद्गलः विशेषार्पणया अणुस्कंधभेदाद्द्वितयः इत्यादि पुद्गलादीनां च एकाद्येकोत्तरस्थानानि वर्ण्यंते इति स्थानं नाम तृतीयमंगं ।

सम्संग्रहेण सादृश्यसामान्येन अवेयंते ज्ञायंते जीवादिपदार्थाः द्रव्यक्षेत्रकालभावानाश्रित्य तस्मिन्निति समवायांगं । तत्र द्रव्याश्रयेण धर्मास्तिकायेनाधर्मास्तिकायः सदृशः, संसारिजीवेन संसारिजीवः सदृशः, मुक्तजीवेन मुक्तजीवः सदृशः इत्यादिद्रव्यसमवायः । क्षेत्राश्रयेण सीमंतनरक मनुष्यक्षेत्र ऋत्विकसिद्धक्षेत्राणि प्रदेशतः सदृशानि । अवधिस्थाननरकजंबूद्वीपसर्वार्थसिद्धि-विमानमेतानि सदृशानीत्यादि क्षेत्रसमवायः । एकसमयः एकसमयेन सदृशः । आवलिरावल्या सदृशी । प्रथमपृथ्वीनारकभावनव्यंतराणां जघन्यायूंषि सदृशानि । सप्तमपृथ्वीनारक सर्वार्थसिद्धि-देवानामुत्कृष्टायुषी सदृशी । इत्यादि कालसमवायः । केवलज्ञानं केवलदर्शनेन सदृशमित्यादिर्भाव-समवायः । इति समवायाख्यं चतुर्थमंगं । विशेषैर्बहुप्रकारैराख्या किमस्ति जीवः किं नास्ति जीवो किमेको जीवः किमनेको जीवः किं नित्यो जीवः किमनित्यो जीवः किमवक्तव्यो जीवः किं वक्तव्यो जीव इत्यादीनि (६००००) षष्टिसहस्रसंख्यानि भगवदर्हत्तीर्थंकरसन्निधौ गणधरदेवप्रश्न-

---

द्वित्रिचतुःपञ्चेन्द्रियभेदाद् दशस्थानकः इत्यादीनि जीवस्य, सामान्यार्पणादेकः पुद्गलः विशेषार्पणया अणुस्कन्धभेदाद् द्वितयः, इत्यादि पुद्गलादीनां च एकाद्येकोत्तरस्थानानि वर्ण्यन्ते इति स्थानं नाम तृतीयमङ्गम् । सं-संग्रहेण सादृश्यसामान्येन अवेयन्ते ज्ञायन्ते जीवादिपदार्था द्रव्यक्षेत्रकालभावानाश्रित्य अस्मिन्निति समवायाङ्गम् । तत्र द्रव्याश्रयेण धर्मास्तिकायेन अधर्मास्तिकायः सदृशः । संसारिजीवेन संसारिजीवः सदृशः । मुक्तजीवेन मुक्तजीवः सदृशः इत्यादिर्द्रव्यसमवायः । क्षेत्राश्रयेण सीमन्तनरक-मनुष्यक्षेत्र-ऋतुविमानेन्द्रक-सिद्ध-क्षेत्राणि प्रदेशतः सदृशानि । अवधिस्थान-नरक-जम्बूद्वीप-सर्वार्थसिद्धिविमानानि सदृशानि इत्यादि क्षेत्र-समवायः । एकसमयः एकसमयेन सदृशः, आवलिः आवल्या सदृशी, प्रथमपृथ्वीनारकभावनव्यन्तराणां जघन्यायूंषि सदृशानि । सप्तमपृथ्वीनरकसर्वार्थसिद्धिदेवानां उत्कृष्टायुषी सदृशे इत्यादिः कालसमवायः । केवलज्ञानं केवलदर्शनेन सदृशमित्यादिर्भावसमवायः इति समवायाख्यं चतुर्थमङ्गं । विशेषैः बहुप्रकारैराख्यातं किमस्ति जीवः ? किं नास्ति जीवः ? किमेको जीवः ? किमनेको जीवः ? किं नित्यो जीवः ? किमनित्यो जीवः ? किं वक्तव्यो जीवः ? किमवक्तव्यो जीव इत्यादीनि षष्टिसहस्रसंख्यानि भगवदर्हत्तीर्थंकरसन्निधौ

ये नौ पदार्थ उसके विषय होनेसे नौ अर्थरूप हैं, पृथिवी अप् तेज वायु प्रत्येक साधारण दोइन्द्रिय त्रीन्द्रिय चतुरिन्द्रिय और पंचेन्द्रियके भेदसे दस स्थानवाला है, इत्यादि जीवका और सामान्यसे पुद्गल एक है, विशेषकी अपेक्षा अणु और स्कन्धके भेदसे दो प्रकार है, इत्यादि पुद्गल आदिके एकादि एक-एक अधिक स्थानोंका वर्णन रहता है। इस प्रकार स्थान नामक तीसरा अंग है। 'सं' अर्थात् सादृश्य सामान्यरूप संग्रहनयसे 'अवेयन्ते' द्रव्य क्षेत्र काल भावको लेकर जीवादि पदार्थ जिसमें जाने जाते हैं वह समवायांग है। उसमें द्रव्यकी अपेक्षा धर्मास्तिकायसे अधर्मास्तिकाय समान है, संसारी जीवसे संसारी जीव समान है, मुक्त जीवसे मुक्त जीव समान है, इत्यादि द्रव्यसमवाय है। क्षेत्रकी अपेक्षा सीमन्त नरक, मनुष्यलोक, ऋतु नामक इन्द्रक विमान, सिद्धक्षेत्र प्रदेशसे समान हैं, सातवें नरकका अवधि-स्थान नामक इन्द्रकबिला, जम्बूद्वीप, सर्वार्थसिद्धि विमान समान हैं इत्यादि क्षेत्रसमवाय है। एक समय एक समयके समान है, आवली आवलीके समान है, प्रथम पृथिवीके नारकी, भवनवासी और व्यन्तरोंकी जघन्य आयु समान है, सातवें नरकके नारकी और सर्वार्थ-सिद्धिके देवोंकी उत्कृष्ट आयु समान है, इत्यादि कालसमवाय है। केवलज्ञान केवलदर्शनके समान है इत्यादि भावसमवाय है। इत्यादि समवायोंका कथन समवाय नामके चतुर्थ

[illegible] विशेषापेक्षया अणुस्कंधभेदाद्द्वितयः इत्यादि पुद्गलादीनां च एकाद्येकोत्तरस्थानानि [illegible] इति स्थानं नाम तृतीयमंगं।

[illegible] सादृश्यसामान्येन अवेयंते ज्ञायंते जीवादिपदार्थाः द्रव्यक्षेत्रकालभावानाश्रित्य [illegible] समवायांगं। तत्र द्रव्याश्रयेण धर्म्मास्तिकायेनाधर्म्मास्तिकायः सदृशः, संसारिजीवेन [illegible] सदृशः, मुक्तजीवेन मुक्तजीवः सदृशः इत्यादिद्रव्यसमवायः। क्षेत्राश्रयेण सीमंतनरक [illegible] प्रदेशतः सदृशानि। अवधिस्थाननरकजंबूद्वीपसर्व्वार्थसिद्धि[illegible] सदृशान्यपि क्षेत्रसमवायः। एकसमयः एकसमयेन सदृशः। आवलिरावल्या [illegible]। [illegible] अधन्यायूंषि सदृशानि। सप्तमपृथ्वीनारक सर्व्वार्थसिद्धि[illegible] सदृशे। इत्यादि कालसमवायः। केवलज्ञानं केवलदर्शनेन सदृशमित्यादिभाव[illegible]। इति [illegible] चतुर्थमंगं। विशेषैर्बहुप्रकारैराख्या किमस्ति जीवः किं नास्ति [illegible] किमेको जीवः किमनेको जीवः किं नित्यो जीवः किमनित्यो जीवः किमवक्तव्यो जीवः किं [illegible] इत्यादीनि (६००००) षष्टिसहस्रसंख्यानि भगवदर्हत्तीर्थंकरसन्निधौ गणधरदेवप्रश्न-

[illegible] इत्यादीनि जीवस्य, सामान्यापेक्षयैकः पुद्गलः विशेषापेक्षया [illegible] इत्यादि पुद्गलादीनां च एकाद्येकोत्तरस्थानानि वर्ण्यन्ते इति स्थानं नाम तृतीयमङ्गम्। [illegible] जीवादिपदार्था द्रव्यक्षेत्रकालभावानाश्रित्य [illegible] । [illegible] अधर्मास्तिकायः सदृशः। संसारिजीवेन संसारिजीवः सदृशः। [illegible] इत्यादिद्रव्यसमवायः। क्षेत्राश्रयेण सीमन्तनरक-मनुष्यक्षेत्र-ऋजुविमान-सिद्ध[illegible] सदृशानि। अवधिस्थान-नरक-जम्बूद्वीप-सर्वार्थसिद्धिविमानानि सदृशानि इत्यादि क्षेत्र[illegible]। [illegible] सदृशः, आवलिः आवल्या सदृशी, प्रथमपृथ्वीनारकभावनव्यन्तराणां [illegible]। [illegible]सर्वार्थसिद्धिदेवानां उत्कृष्टायुषी सदृशे इत्यादिः कालसमवायः। [illegible] समवायाख्यं चतुर्थमङ्गम्। विशेषैः बहुप्रकारैराख्यान [illegible] ? किं नास्ति जीवः ? किमेको जीवः ? किमनेको जीवः ? किं नित्यो जीवः ? किमनित्यो [illegible] ? [illegible] ? किमवक्तव्यो जीवः इत्यादीनि षष्टिसहस्रसंख्यानि भगवदर्हत्तीर्थकरसन्निधौ

[illegible] विषय होनेसे जो अपेक्षा है, पृथिवी अप् तेज वायु प्रत्येक साधारण [illegible] चतुरिन्द्रिय और पञ्चेन्द्रियके भेदसे दस स्थानवाला है, इत्यादि जीवका [illegible] पुद्गल एक है, विशेषकी अपेक्षा अणु और स्कन्धके भेदसे दो प्रकार है, [illegible] एक-एक अधिक स्थानोंका वर्णन रहता है। इस प्रकार स्थान [illegible] है। [illegible] अर्थात् सादृश्य सामान्यरूप संग्रहनयसे 'अवेयन्ते' द्रव्य क्षेत्र [illegible] पदार्थ जिसमें जाने जाते हैं वह समवायांग है। उसमें द्रव्यकी [illegible] अधर्मास्तिकाय समान है, संसारी जीवसे संसारी जीव समान है, [illegible] समान है, इत्यादि द्रव्यसमवाय है। क्षेत्रकी अपेक्षा सीमन्त नरक, [illegible] विमान, सिद्धक्षेत्र प्रदेशसे समान है, सातवें नरकका अवधि[illegible], जम्बूद्वीप, सर्वार्थसिद्धि विमान समान हैं इत्यादि क्षेत्रसमवाय है। [illegible] समान है, आवली आवलीके समान है, प्रथम पृथिवीके नारकी, [illegible] उत्कृष्ट आयु समान है, सातवें नरकके नारकी और सर्वार्थ[illegible] आयु समान है, इत्यादि कालसमवाय है। केवलज्ञान केवलदर्शनके समान है इत्यादि [illegible] है। इत्यादि समवायोंका कथन समवाय नामके चतु-

पुद्गलः विशेषार्प्पणया अणुस्कंधभेदाद्द्वितयः इत्यादि पुद्गलादीनां च एकाद्येकोत्तरस्थानानि वर्ण्यंत इति स्थानं नाम तृतीयमंगं।

सम्संग्रहेण सादृश्यसामान्येन अवेयंते ज्ञायंते जोवादिपदार्त्थाः द्रव्यक्षेत्रकालभावानाश्रित्य तस्मिन्निति समवायांगं। तत्र द्रव्याश्रयेण धर्म्मास्तिकायेनाधर्म्मास्तिकायः सदृशः, संसारिजीवेन संसारिजीवः सदृशः, मुक्तजीवेन मुक्तजीवः सदृशः इत्यादिद्रव्यसमवायः। क्षेत्राश्रयेण सीमंतनरक मनुष्यक्षेत्र ऋत्विकसिद्धक्षेत्राणि प्रदेशतः सदृशानि। अवधिस्थाननरकजंबूद्वीपसर्व्वार्त्थसिद्धि-विमानमेतानि सदृशानीत्यादि क्षेत्रसमवायः। एकसमयः एकसमयेन सदृशः। आवलिरावल्या सदृशी। प्रथमपृथ्वीनारकभावनव्यंतराणां जघन्यायूंषि सदृशानि। सप्तमपृथ्वीनारक सर्व्वार्त्थसिद्धि-देवानामुत्कृष्टायुर्षी सदृशी। इत्यादि कालसमवायः। केवलज्ञानं केवलदर्शनेन सदृशमित्यादिर्भाव-समवायः। इति समवायाख्यं चतुर्त्थमंगं। विशेषैर्ब्बहुप्रकारैराख्या किमस्ति जीवः किं नास्ति जीवो किमेको जीवः किमनेको जीवः किं नित्यो जीवः किमनित्यो जीवः किमवक्तव्यो जीवः किं वक्तव्यो जीव इत्यादीनि (६००००) षष्टिसहस्रसंख्यानि भगवदर्हत्तीर्त्थंकरसन्निधौ गणधरदेवप्रश्न-

---

द्वित्रिचतुःपञ्चेन्द्रियभेदाद् दशस्थानकः इत्यादीनि जीवस्य, सामान्यार्पणादेकः पुद्गलः विशेषार्पणया अणुस्कन्धभेदाद् द्वितयः, इत्यादि पुद्गलादीनां च एकाद्येकोत्तरस्थानानि वर्ण्यन्ते इति स्थानं नाम तृतीयमङ्गम्। सं-संग्रहेण सादृश्यसामान्येन अवेयन्ते ज्ञायन्ते जीवादिपदार्था द्रव्यक्षेत्रकालभावानाश्रित्य अस्मिन्निति समवायाङ्गम्। तत्र द्रव्याश्रयेण धर्मास्तिकायेन अधर्मास्तिकायः सदृशः। संसारिजीवेन संसारिजीवः सदृशः। मुक्तजीवेन मुक्तजीवः सदृशः इत्यादिर्द्रव्यसमवायः। क्षेत्राश्रयेण सीमन्तनरक-मनुष्यक्षेत्र-ऋत्विन्द्रक-सिद्ध-क्षेत्राणि प्रदेशतः सदृशानि। अवधिस्थान-नरक-जम्बूद्वीप-सर्वार्थसिद्धिविमानानि सदृशानि इत्यादि क्षेत्र-समवायः। एकसमयः एकसमयेन सदृशः, आवलिः आवल्या सदृशी, प्रथमपृथ्वीनारकभावनव्यन्तराणां जघन्यायूंषि सदृशानि। सप्तमपृथ्वीनरकसर्वार्थसिद्धिदेवानां उत्कृष्टायुषी सदृशी इत्यादिः कालसमवायः। केवलज्ञानं केवलदर्शनेन सदृशमित्यादिर्भावसमवायः इति समवायाख्यं चतुर्थमङ्गं। विशेषैः बहुप्रकारैराख्यानं किमस्ति जीवः ? किं नास्ति जीवः ? किमेको जीवः ? किमनेको जीवः ? किं नित्यो जीवः ? किमनित्यो जीवः ? किं वक्तव्यो जीवः ? किमवक्तव्यो जीव इत्यादीनि षष्टिसहस्रसंख्यानि भगवदर्हत्तीर्थंकरसन्निधौ

ये नौ पदार्थ उसके विषय होनेसे नौ अर्थरूप हैं, पृथिवी अप् तेज वायु प्रत्येक साधारण दोइन्द्रिय त्रीन्द्रिय चतुरिन्द्रिय और पंचेन्द्रियके भेदसे दस स्थानवाला है, इत्यादि जीवका और सामान्यसे पुद्गल एक है, विशेषकी अपेक्षा अणु और स्कन्धके भेदसे दो प्रकार है, इत्यादि पुद्गल आदिके एकादि एक-एक अधिक स्थानोंका वर्णन रहता है। इस प्रकार स्थान नामक तीसरा अंग है। 'सं' अर्थात् सादृश्य सामान्यरूप संग्रहनयसे 'अवेयन्ते' द्रव्य क्षेत्र काल भावको लेकर जीवादि पदार्थ जिसमें जाने जाते हैं वह समवायांग है। उसमें द्रव्यकी अपेक्षा धर्मास्तिकायसे अधर्मास्तिकाय समान है, संसारी जीवसे संसारी जीव समान है, मुक्त जीवसे मुक्त जीव समान है, इत्यादि द्रव्यसमवाय है। क्षेत्रकी अपेक्षा सीमन्त नरक, मनुष्यलोक, ऋतु नामक इन्द्रक विमान, सिद्धक्षेत्र प्रदेशसे समान है, सातवें नरकका अवधि-स्थान नामक इन्द्रकबिला, जम्बूद्वीप, सर्वार्थसिद्धि विमान समान है इत्यादि क्षेत्रसमवाय है। एक समय एक समयके समान है, आवली आवलीके समान है, प्रथम पृथिवीके नारकी, भवनवासी और व्यन्तरोंकी जघन्य आयु समान है, सातवें नरकके नारकी और सर्वार्थ-सिद्धिके देवोंकी उत्कृष्ट आयु समान है, इत्यादि कालसमवाय है। केवलज्ञान केवलदर्शनके समान है इत्यादि भावसमवाय है। इत्यादि समवायोंका कथन समवाय नामके चतुर्थ

पुद्गलः विशेषार्पणया अणुस्कंधभेदाद्द्वितयः इत्यादि पुद्गलादीनां च एकाद्येकोत्तरस्थानानि वर्ण्यंते इति स्थानं नाम तृतीयमंगं।

सम्संग्रहेण सादृश्यसामान्येन अवेयंते ज्ञायंते जीवादिपदार्थाः द्रव्यक्षेत्रकालभावानाश्रित्य तस्मिन्निति समवायांगं। तत्र द्रव्याश्रयेण धर्म्मास्तिकायेनाधर्म्मास्तिकायः सदृशः, संसारिजीवेन संसारिजीवः सदृशः, मुक्तजीवेन मुक्तजीवः सदृशः इत्यादिद्रव्यसमवायः। क्षेत्राश्रयेण सीमंतनरक मनुष्यक्षेत्र ऋत्विन्द्रकसिद्धक्षेत्राणि प्रदेशतः सदृशानि। अवधिस्थाननरकजंबूद्वीपसर्व्वार्त्थसिद्धिविमानमेतानि सदृशानीत्यादि क्षेत्रसमवायः। एकसमयः एकसमयेन सदृशः। आवलिरावल्या सदृशी। प्रथमपृथ्वीनारकभावनव्यंतराणां जघन्यायूंषि सदृशानि। सप्तमपृथ्वीनारक सर्व्वार्त्थसिद्धिदेवानामुत्कृष्टायुषी सदृशी। इत्यादि कालसमवायः। केवलज्ञानं केवलदर्शनेन सदृशमित्यादिर्भावसमवायः। इति समवायाख्यं चतुर्त्थमंगं। विशेषैर्ब्बहुप्रकारैराख्या किमस्ति जीवः किं नास्ति जीवो किमेको जीवः किमनेको जीवः किं नित्यो जीवः किमनित्यो जीवः किमवक्तव्यो जीवः किं वक्तव्यो जीव इत्यादीनि (६००००) षष्टिसहस्रसंख्यानि भगवदर्हत्तीर्त्थंकरसन्निधौ गणधरदेवप्रश्न-

द्वित्रिचतुःपञ्चेन्द्रियभेदाद् दशस्थानकः इत्यादीनि जीवस्य, सामान्यार्पणादेकः पुद्गलः विशेषार्पणया अणुस्कन्धभेदाद् द्वितयः, इत्यादि पुद्गलादीनां च एकाद्येकोत्तरस्थानानि वर्ण्यन्ते इति स्थानं नाम तृतीयमङ्गम्। सं-संग्रहेण सादृश्यसामान्येन अवेयन्ते ज्ञायन्ते जीवादिपदार्था द्रव्यक्षेत्रकालभावानाश्रित्य अस्मिन्निति समवायाङ्गम्। तत्र द्रव्याश्रयेण धर्मास्तिकायेन अधर्मास्तिकायः सदृशः। संसारिजीवेन संसारिजीवः सदृशः। मुक्तजीवेन मुक्तजीवः सदृशः इत्यादिर्द्रव्यसमवायः। क्षेत्राश्रयेण सीमन्तनरक-मनुष्यक्षेत्र-ऋत्विन्द्रक-सिद्धक्षेत्राणि प्रदेशतः सदृशानि। अवधिस्थान-नरक-जम्बूद्वीप-सर्वार्थसिद्धिविमानानि सदृशानि इत्यादि क्षेत्रसमवायः। एकसमयः एकसमयेन सदृशः, आवलिः आवल्या सदृशी, प्रथमपृथ्वीनारकभावनव्यन्तराणां जघन्यायूंषि सदृशानि। सप्तमपृथ्वीनारकसर्वार्थसिद्धिदेवानां उत्कृष्टायुषी सदृशे इत्यादिः कालसमवायः। केवलज्ञानं केवलदर्शनेन सदृशमित्यादिर्भावसमवायः इति समवायाख्यं चतुर्थमङ्गं। विशेषैः बहुप्रकारैराख्यातं किमस्ति जीवः? किं नास्ति जीवः? किमेको जीवः? किमनेको जीवः? किं नित्यो जीवः? किमनित्यो जीवः? किं वक्तव्यो जीवः? किमवक्तव्यो जीव इत्यादीनि षष्टिसहस्रसंख्यानि भगवदर्हत्तीर्थंकरसन्निधौ

ये नौ पदार्थ उसके विषय होनेसे नौ अर्थरूप है, पृथिवी अप् तेज वायु प्रत्येक साधारण दोइन्द्रिय तीइन्द्रिय चतुरिन्द्रिय और पंचेन्द्रियके भेदसे दस स्थानवाला है, इत्यादि जीवका और सामान्यसे पुद्गल एक है, विशेषकी अपेक्षा अणु और स्कन्धके भेदसे दो प्रकार है, इत्यादि पुद्गल आदिके एकादि एक-एक अधिक स्थानोंका वर्णन रहता है। इस प्रकार स्थान नामक तीसरा अंग है। 'सं' अर्थात् सादृश्य सामान्यरूप संग्रहनयसे 'अवेयन्ते' द्रव्य क्षेत्र काल भावको लेकर जीवादि पदार्थ जिसमें जाने जाते हैं वह समवायांग है। उसमें द्रव्यकी अपेक्षा धर्मास्तिकायसे अधर्मास्तिकाय समान है, संसारी जीवसे संसारी जीव समान है, मुक्त जीवसे मुक्त जीव समान है, इत्यादि द्रव्यसमवाय है। क्षेत्रकी अपेक्षा सीमन्त नरक, मनुष्यलोक, ऋतु नामक इन्द्रक विमान, सिद्धक्षेत्र प्रदेशसे समान है, सातवें नरकका अवधिस्थान नामक इन्द्रकबिला, जम्बूद्वीप, सर्वार्थसिद्धि विमान समान है इत्यादि क्षेत्रसमवाय है। एक समय एक समयके समान है, आवली आवलीके समान है, प्रथम पृथिवीके नारकी, भवनवासी और व्यन्तरोंकी जघन्य आयु समान है, सातवें नरकके नारकी और सर्वार्थसिद्धिके देवोंकी उत्कृष्ट आयु समान है, इत्यादि कालसमवाय है। केवलज्ञान केवलदर्शनके समान है इत्यादि भावसमवाय है। इत्यादि समवायोंका कथन समवाय नामके चतुर्थ

पुद्गलः विशेषार्पणया अणुस्कंधभेदाद्द्वितयः इत्यादि पुद्गलादीनां च एकाद्येकोत्तरस्थानानि वर्ण्यंत इति स्थानं नाम तृतीयमंगं। सम्संग्रहेण सादृश्यसामान्येन अवेयंते ज्ञायंते जीवादिपदार्थाः द्रव्यक्षेत्रकालभावानाश्रित्य तस्मिन्निति समवायांगं। तत्र द्रव्याश्रयेण धर्मास्तिकायेनाधर्मास्तिकायः सदृशः, संसारिजीवेन संसारिजीवः सदृशः, मुक्तजीवेन मुक्तजीवः सदृशः इत्यादिद्रव्यसमवायः। क्षेत्राश्रयेण सीमंतनरक मनुष्यक्षेत्र ऋत्विकसिद्धक्षेत्राणि प्रदेशतः सदृशानि। अवधिस्थाननरकजंबूद्वीपसर्व्वार्थसिद्धि-विमानमेतानि सदृशानीत्यादि क्षेत्रसमवायः। एकसमयः एकसमयेन सदृशः। आवलिरावल्या सदृशी। प्रथमपृथ्वीनारकभावनव्यंतराणां जघन्यायूंषि सदृशानि। सप्तमपृथ्वीनारक सर्व्वार्थसिद्धि-देवानामुत्कृष्टायुर्षी सदृशी। इत्यादि कालसमवायः। केवलज्ञानं केवलदर्शनेन सदृशमित्यादिर्भाव-समवायः। इति समवायाख्यं चतुर्थमंगं। विशेषैर्ब्बहुप्रकारैराख्या किमस्ति जीवः किं नास्ति जीवो किमेको जीवः किमनेको जीवः किं नित्यो जीवः किमनित्यो जीवः किमवक्तव्यो जीवः किं वक्तव्यो जीव इत्यादीनि (६००००) षष्टिसहस्रसंख्यानि भगवदर्हत्तीर्थंकरसन्निधौ गणधरदेवप्रश्न-

द्वित्रिचतुःपञ्चेन्द्रियभेदाद् दशस्थानकः इत्यादीनि जीवस्य, सामान्यार्पणादेकः पुद्गलः विशेषार्पणया अणुस्कन्धभेदाद् द्वितयः, इत्यादि पुद्गलादीनां च एकाद्येकोत्तरस्थानानि वर्ण्यन्ते इति स्थानं नाम तृतीयमङ्गम्। सं-संग्रहेण सादृश्यसामान्येन अवेयन्ते ज्ञायन्ते जीवादिपदार्था द्रव्यक्षेत्रकालभावानाश्रित्य अस्मिन्निति समवायाङ्गम्। तत्र द्रव्याश्रयेण धर्मास्तिकायेन अधर्मास्तिकायः सदृशः। संसारिजीवेन संसारिजीवः सदृशः। मुक्तजीवेन मुक्तजीवः सदृशः इत्यादिर्द्रव्यसमवायः। क्षेत्राश्रयेण सीमन्तनरक-मनुष्यक्षेत्र-ऋत्विन्द्रक-सिद्ध-क्षेत्राणि प्रदेशतः सदृशानि। अवधिस्थान-नरक-जम्बूद्वीप-सर्वार्थसिद्धिविमानानि सदृशानि इत्यादि क्षेत्र-समवायः। एकसमयः एकसमयेन सदृशः, आवलिः आवल्या सदृशी, प्रथमपृथ्वीनारकभावनव्यन्तराणां जघन्यायूंषि सदृशानि। सप्तमपृथ्वीनरकसर्वार्थसिद्धिदेवानां उत्कृष्टायुषी सदृशे इत्यादिः कालसमवायः। केवलज्ञानं केवलदर्शनेन सदृशमित्यादिर्भावसमवायः इति समवायाख्यं चतुर्थमङ्गं। विशेषैः बहुप्रकारैराख्यातं किमस्ति जीवः? किं नास्ति जीवः? किमेको जीवः? किमनेको जीवः? किं नित्यो जीवः? किमनित्यो जीवः? किं वक्तव्यो जीवः? किमवक्तव्यो जीव इत्यादीनि षष्टिसहस्रसंख्यानि भगवदर्हत्तीर्थंकरसन्निधौ

ये नौ पदार्थ उसके विषय होनेसे नौ अर्थरूप है, पृथिवी अप् तेज वायु प्रत्येक साधारण दोइन्द्रिय त्रीन्द्रिय चतुरिन्द्रिय और पंचेन्द्रियके भेदसे दस स्थानवाला है, इत्यादि जीवका और सामान्यसे पुद्गल एक है, विशेषकी अपेक्षा अणु और स्कन्धके भेदसे दो प्रकार है, इत्यादि पुद्गल आदिके एकादि एक-एक अधिक स्थानोंका वर्णन रहता है। इस प्रकार स्थान नामक तीसरा अंग है। 'सं' अर्थात् सादृश्य सामान्यरूप संग्रहनयसे 'अवेयन्ते' द्रव्य क्षेत्र काल भावको लेकर जीवादि पदार्थ जिसमें जाने जाते हैं वह समवायांग है। उसमें द्रव्यकी अपेक्षा धर्मास्तिकायसे अधर्मास्तिकाय समान है, संसारी जीवसे संसारी जीव समान है, मुक्त जीवसे मुक्त जीव समान है, इत्यादि द्रव्यसमवाय है। क्षेत्रकी अपेक्षा सीमन्त नरक, मनुष्यलोक, ऋतु नामक इन्द्रक विमान, सिद्धक्षेत्र प्रदेशसे समान है, सातवें नरकका अवधि-स्थान नामक इन्द्रकबिला, जम्बूद्वीप, सर्वार्थसिद्धि विमान समान है इत्यादि क्षेत्रसमवाय है। एक समय एक समयके समान है, आवली आवलीके समान है, प्रथम पृथिवीके नारकी, भवनवासी और व्यन्तरोंकी जघन्य आयु समान है, सातवें नरकके नारकी और सर्वार्थ-सिद्धिके देवोंकी उत्कृष्ट आयु समान है, इत्यादि कालसमवाय है। केवलज्ञान केवलदर्शनके समान है इत्यादि भावसमवाय है। इत्यादि समवायोंका कथन समवाय नामके चतुर्थ

अल्लिदं वळिकं उपासते आहारादिदानैर्न्नित्यमहादिपूजाविधानैश्च संघमाराधयंतीत्युपासकाः। ते अधीयंते पठचंते दर्शनिकव्रतिकसामायिकप्रोषधोपवाससचित्तविरतरात्रिभक्तव्रतब्रह्मचार्य्यारंभपरिग्रहनिवृत्ताऽनुमतोद्दिष्टविरतभेदैकादशनिलयसंबंधिव्रतगुणशीलाचारक्रियामंत्रादि-विस्तरैर्व्वर्ण्यंतेऽस्मिन्निति उपासकाध्ययनं नाम सप्तममंगं।

प्रतितीर्त्थं दशदशमुनीश्वरास्तीव्रं चतुर्व्विधोपसर्गं सोढ्वा इंद्रादिभिर्व्विरचितं पूजादि, प्रातिहार्य्यसंभावनां लब्ध्वा कर्म्मक्षयानंतरं संसारस्यांतमवसानं कृतवंतोऽन्तकृतः। श्रीवर्द्धमानतीर्त्थे नमि मतंग सोमिल रामपुत्र सुदर्शन यमलोकवलिककिष्कंविल पालंबष्टपुत्रा इति दश। एवं वृषभादितीर्त्थेष्वपि दश दशांतकृतो वर्ण्यते यस्मिन्तदन्तकृद्दशं नामाष्टममंगं। तथा उपपादः प्रयोजनमेषां ते इमे औपपादिकाः अनुत्तरेषु विजयवैजयंतजयंतापराजितसर्व्वार्त्थसिद्धचाख्येषु औपपादिकाः अनुत्तरौपपादिकाः। प्रतिती र्त्थं दश दश मुनयः दारुणान्महोपसर्गान्सोढ्वा लब्धप्रातिहार्य्याः समाधिविधिना त्यक्तप्राणा ये विजयाद्यनुत्तरविमानेषूपपन्नास्ते वर्ण्यते यस्मिन् तदनुत्तरौपपादिकदशं नाम नवममंगं। तत्र श्रीवर्द्धमानतीर्त्थे ऋजुदास धन्य सुनक्षत्र कार्त्तिकेय नंद नंदन शालिभद्र

अतः परं उपासते आहारादिदानैर्नित्यमहादिपूजाविधानैश्च संघमाराधयन्तीति उपासकाः ते अधीयन्ते पठ्यन्ते दर्शनिकव्रतिकसामयिकप्रोषधोपवाससचित्तविरतरात्रिभक्तव्रतब्रह्मचर्यारम्भपरिग्रहनिवृत्तानुमतोद्दिष्टविरतभेदैकादशनिलयसंबन्धिव्रतगुणशीलाचारक्रियामन्त्रादिविस्तरैर्वर्ण्यन्ते अस्मिन्निति उपासकाध्ययनं नाम सप्तममङ्गम्। प्रति तीर्थं दश दश मुनीश्वराः तीव्रं चतुर्विधोपसर्गं सोढ्वा इन्द्रादिभिर्विरचितां पूजादिप्रातिहार्यसंभावनां लब्ध्वा कर्मक्षयानन्तरं संसारस्यान्तं अवसानं कृतवन्तोऽन्तकृतः। श्रीवर्धमानतीर्थे नमि-मतङ्ग-सोमिल-रामपुत्र-सुदर्शन-यमलीक-वलिक-किष्कम्बिल-पालंबष्ट-पुत्रा इति दश। एवं वृषभादितीर्थेष्वपि दश दशान्तकृतो वर्ण्यन्ते यस्मिंस्तदन्तकृद्दशनामाष्टममङ्गम्। तथा उपपादः प्रयोजनमेषां ते इमे औपपादिकाः। अनुत्तरेषु विजयवैजयन्तजयन्तापराजितसर्वार्थसिद्धयाख्येषु औपपादिकाः अनुत्तरौपपादिकाः। प्रति तीर्थं दश दश मुनयो दारुणान् महोपसर्गान् सोढ्वा लब्धप्रातिहार्याः समाधिविधिना त्यक्तप्राणाः ये विजयाद्यनुत्तरविमानेषूत्पन्नाः ते वर्ण्यन्ते यस्मिंस्तदनुत्तरौपपादिकदशं नाम नवममङ्गम्। तत्र श्रीवर्धमानतीर्थे ऋजुदास-

---

'उपासते' जो आहार आदि दानके द्वारा और नित्यमह आदि पूजाविधानके द्वारा संघकी आराधना करते हैं वे उपासक हैं। वे उपासक दर्शनिक, व्रतिक, सामयिक, प्रोषधोपवास, सचित्तविरत, रात्रिभक्तव्रत, ब्रह्मचर्य, आरम्भविरत, परिग्रहविरत, अनुमतविरत, उद्दिष्टविरत इन गृहस्थोंके ग्यारह भेदोंसे सम्बद्ध व्रत, गुण, शील, आचार, क्रिया, मन्त्र आदि विस्तारसे जिसमें 'अधीयन्ते' पढ़े जाते हैं वह उपासकाध्ययन नामक सातवाँ अंग है। प्रत्येक तीर्थमें दस-दस मुनीश्वर तीव्र चार प्रकारके उपसर्गको सहकर इन्द्रादिके द्वारा रचित पूजादि प्रतिहार्योंकी सम्भावनाको प्राप्त करके कर्मोंके क्षयके अनन्तर संसारका अन्त करते हुए। इसलिए उन्हें 'अन्तकृत' कहते हैं। श्री वर्धमान तीर्थंकरके तीर्थमें नमि, मतंग, सोमिल, रामपुत्र, सुदर्शन, यमलीक, वलीक, किष्कंविल, पालम्बु, अष्टपुत्र ये दस अन्तकृत् हुए। इसी प्रकार ऋषभदेव आदिके भी तीर्थमें हुए। जिसमें दस-दस अन्तकृतोंका वर्णन हो वह अंग अन्तकृद्दश नामक है। उपपाद जिनका प्रयोजन है वे औपपादिक हैं। विजय, वैजयन्त, जयन्त, अपराजित और सर्वार्थसिद्धि नामक अनुत्तरोंमें उपपाद जन्म लेनेवाले अनुत्तरौपपादिक होते हैं। प्रत्येक तीर्थमें दस-दस मुनि दारुण महान् उपसर्गोंको सहकर प्रातिहार्य प्राप्त करके समाधिपूर्वक प्राणोंको त्यागकर विजयादि अनुत्तरोंमें उत्पन्न हुए। उनका जिसमें वर्णन हो वह अनुत्तरौपपादिकदश नामक नौवाँ अंग है। उनमें-से श्रीवर्धमान

[illegible] । [illegible] । हरिश्मश्रु । माध्यंदिक । रोमश । हारीत । मुण्ड । आश्वलायननेंब्रियवर्गळु [illegible] १८० । मरीचि । कपिल । उलूक । गार्ग्य । व्याघ्रभूति । [illegible] । [illegible] । मौद्गलायनं मोदलादवर्गळु अक्रियावादह्ष्टिगळप्पर्वर्गळें बत्तनाल्कु ८४ । [illegible] । [illegible] । [illegible] । [illegible] । नारायण । कठ । माध्यंदिन । मौद । पैप्पलाद । [illegible] । [illegible] । [illegible] । बादरायण । मनु जैमिनिगळिवरु अज्ञानदृष्टिगळु इवर्गळप्पत्तेळु ६७ । [illegible] । [illegible] । [illegible] । वाल्मीकि । रोमहर्षिणि । सत्यदत्त । व्यास । एलापुत्र औपमन्यव । [illegible] । [illegible] वैनयिकवादिगळु मूवत्तेरडु । ३२ । मितु कूडि मूनूरष्वत्तमूरु [illegible] । ३६३ ।

[illegible] सोलसुरय तियालपण्णासी ।
[illegible] पुण पदमाणिओगमदो ॥३६१॥
[illegible] आणणपद्धगमिमा पंच ।
[illegible] तेसु पमाणं इमं कमसो ॥३६२॥

[illegible] । परिकर्म पंचविधं सूत्रं प्रथमानुयोगोक्तः ॥
[illegible] चूलिकाः तेषु प्रमाणमिदं क्रमशः ॥

[illegible] परिकर्म । सूत्र । प्रथमानुयोगः । पूर्वगतं । [illegible] कर्माणि गणितकरणसूत्राणि यस्मिन् तत्परिकर्म । ई परि-

[illegible] १८० । [illegible] ८४ । [illegible]

[illegible] प्रथमानुयोग पूर्वगत चूलिका भेदि । [illegible]

[illegible] हरिश्मश्रु, माध्यंदिक, रोमश, हारीत, मुंड, [illegible] । मरीचि, कपिल, उलूक, गार्ग्य, [illegible] । [illegible], कठ, माध्यंदिन, मौद, पैप्पलाद, बादरायण, [illegible] । वसिष्ठ, [illegible], [illegible], औपमन्यव, ऐलापुत्र, [illegible]

[illegible] —परिकर्म, सूत्र, प्रथमानुयोग, पूर्वगत, चूलिका ।

[illegible]

चतुर्व्विंशतितीर्थंकरद्वादश चक्रवर्त्तिगळ नवबलदेव नववासुदेव नवप्रतिवासुदेवरगळ शलाकापुरुषपुराणंगळं वर्णिसुगुं। मुंदे पूर्व्वं चतुर्द्दशविधं विस्तरदिदं पेळल्पट्टपुदु।

चूलिकेयुमय्दु प्रकारमक्कुमदे ते दोडे जलगता स्थलगता मायागता आकाशगता एंदितिवरोळु जलगताचूलिके जलस्तंभन जलगमनाग्निस्तंभनाग्निभक्षणाग्न्यासनाग्निप्र कारणमंत्रतंत्रतपश्चरणादिगळं वर्णिसुगुं। स्थलगता चूलिकेयुं मेरुकुलशैलभूम्या प्रवेशन शीघ्रगमनादिकारणमंत्रतंत्रतपश्चरणादिगळं वर्णिसुगुं। मायागता चूलिकेयुं रूपेंद्रजालविक्रियाकारणमंत्रतंत्रतपश्चरणादिगळं वर्णिसुगुं। रूपगताचूलिकेयुं सिंहक तुरग तरुहरिणशशवृषभव्याघ्रादिरूपपरावर्तनकारणमंत्रतंत्रतपश्चरणादिगळं चित्रकाष्ठ खननादिलक्षणधातुवादरसवादखन्यावादादिगळं वर्णिसुगुं।

आकाशगताचूलिकेयुं आकाशगमनकारणमंत्रतंत्रतपश्चरणादिगळं वर्णिसुगुं। पेररे पेळ्द चंद्रप्रज्ञप्त्यादिगळोळु क्रमशः यथाक्रमदिदं पदप्रमाणमनंतरमे वक्ष्यमाण जानीहि एंदितु संबोधनमध्याहार्य्यं।

चक्रवर्तिनवबलदेवनववासुदेवनवप्रतिवासुदेवरूपत्रिषष्टिशलाकापुरुषपुराणानि वर्णयति। पूर्वं चतुर्दशविधं विस्त अग्रे वक्ष्यति। चूलिकापि पञ्चविधा जलगता स्थलगता मायागता आकाशगता रूपगता चेति। तत्र जलग चूलिका जलस्तम्भनजलगमनाग्निस्तम्भनाग्निभक्षणाग्न्यासनाग्निप्रवेशनादिकारणमन्त्रतन्त्रतपश्चरणादीन् वर्णयति स्थलगता चूलिका मेरुकुलशैलभूम्यादिषु प्रवेशनशीघ्रगमनादिकारणमन्त्रतन्त्रतपश्चरणादीन् वर्णयति मायागता चूलिका मायारूपेन्द्रजालविक्रियाकारणमन्त्रतन्त्रतपश्चरणादीन् वर्णयति। रूपगता चूलिक सिंहकरितुरगरुरुनरतरुहरिणशशकवृषभव्याघ्रादिरूपपरावर्तनकारणमन्त्रतन्त्रतपश्चरणादीन् चित्रकाष्ठलेप्योत्खन नादिलक्षणधातुवादरसवादखन्यावादादींश्च वर्णयति। आकाशगता चूलिका आकाशगमनकारणमन्त्रतन्त्र तपश्चरणादीन् वर्णयति। प्रागुक्तचन्द्रप्रज्ञप्त्यादिषु क्रमशो यथाक्रमं पदप्रमाणं अनन्तरमेव वक्ष्यमाणं जानीहि इति संबोधनमध्याहार्यम् ॥३६१-३६२॥

प्रथम अर्थात् मिथ्यादृष्टि, अव्रती या अव्युत्पन्न व्यक्तिके लिए जो अनुयोग रचा गया वह प्रथमानुयोग है। यह चौबीस तीर्थंकर, बारह चक्रवर्ती, नौ बलदेव, नौ वासुदेव, नौ प्रति-वासुदेव, इन तिरसठ शलाका प्राचीन पुरुषोंका वर्णन करता है। चौदह प्रकारके पूर्वोंके सम्बन्धमें आगे विस्तारसे कहेंगे। चूलिका भी पाँच प्रकार की है—जलगता, स्थलगता, मायागता, आकाशगता और रूपगता। जलगता चूलिका जलका स्तम्भन, जलमें गमन, अग्निका स्तम्भन, अग्निका भक्षण, अग्निपर बैठना, अग्निमें प्रवेश आदिके कारण मन्त्र, तन्त्र, तपश्चरण आदिका वर्णन करती है। स्थलगता चूलिका मेरु, कुलाचल, भूमि आदिमें प्रवेश करने तथा शीघ्र गमन आदिके कारण मन्त्र, तन्त्र, तपश्चरण आदिका वर्णन करती है। मायागता चूलिका मायावी रूप, इन्द्रजाल (जादूगरी) विक्रियाके कारण मन्त्र, तन्त्र, तपश्चरण आदिका वर्णन करती है। रूपगता चूलिका सिंह, हाथी, घोड़ा, मृग, खरगोश, बैल, व्याघ्र आदिके रूप बदलनेमें कारण मन्त्र, तन्त्र, तपश्चरण आदिका तथा चित्र, काष्ठ, लेप्य, उत्खनन आदिका लक्षण व धातुवाद, रसवाद, खदान आदि वादोंका कथन करती है। आकाशगता चूलिका आकाशमें गमन करनेमें कारण मन्त्र, तन्त्र, तपश्चरण आदिका कथन करती है। इन चन्द्रप्रज्ञप्ति आदिमें क्रमसे पदोंका प्रमाण आगे कहते हैं ॥३६१-३६२॥

---

1. ब °सन्धा° ।

२०९८९२०० रूपगतंगळु २०९८९२००। याजकनामेनाननं एककोटयेकाशीतिलक्षंगळुमय्दुसहस्र-पदंगळु चंद्रप्रज्ञप्त्यादि पंचप्रकारमनुळ्ळ परिकर्म्मंगुतियोळप्पुवु १८१०५००० कानवधिवाचनाननं दशकोटयेकोनपंचाशल्लक्षषट्चत्वारिंशत्सहस्रपदंगळु पुनः मत्ते जलगतादि पंचप्रकारभूतचूलिका-योगमिदु १०४९४६०००।

पण्णट्ठदाल पणतीस तीस पण्णास पण्ण तेरसदं ।
णउदी दुदाल पुव्वे पणवण्णा तेरससयाइं ॥३६५॥
छस्सयपण्णासाइं चउसयपण्णास छसयपणुवीसा ।
बिहि लक्खेहि दु गुणिया पंचम रूऊण छज्जुदा छट्ठे ॥३६६॥

पंचाशदष्टचत्वारिंशत्पंचत्रिंशत् त्रिंशत् पंचाशत् पंचाशत् त्रयोदशशतं नवतिर्द्वाचत्वारिंशत् पूर्व्वे पंच पंचाशत् त्रयोदशशतानि । षट्छतपंचाशच्चतुःशतपंचाशत् षट्शतपंचविंशतिद्वाभ्यां लक्षाभ्यां गुणितास्तु पंचमरूपोन षड्युताः षष्टि।

५०। ४८। ३५। ३०। ५०। ५०। १३००। ९०। ४२। ५५। १३००।—६५०। ४५०। ६२५।

पूर्व्वे उत्पादादि पूर्व्वंदोळु चतुर्द्दशविषदोळं यथाक्रमदिदमी संख्ये पेळल्पट्टुदु। वस्तुविन द्रव्यद उत्पादव्ययध्रौव्यादि अनेकधर्म्मपूरकमुत्पादपूर्व्वमक्कु—मदु जीवादिद्रव्यंगळ नानानय-विषयक्रम यौगपद्यसंभावितोत्पादव्ययध्रौव्यंगळु त्रिकालगोचरंगळु। नवधर्म्मंगळप्पुवु। तत्परिणत द्रव्यमुं नवविधमक्कुं। उत्पन्नमुत्पद्यमानमुत्पत्स्यमानं नष्टं नश्यत् नंक्ष्यत् स्थितं तिष्ठत् स्थास्यदिति इंतु नवप्रकारंगळप्पुवुत्पन्नत्वादिगळगे प्रत्येकं नवविधत्वसंभवदत्तणिदमेकाशीतिविकल्पधर्म्म-

चन्द्रप्रज्ञप्त्यादिपञ्चविधपरिकर्मयुतौ याजकनामेनाननं—एककोट्येकाशीतिलक्षपञ्चसहस्राणि पदानि १८१०५०००। जलगतादिपञ्चविधचूलिकायोगः पुनः कानवधिवाचनाननं—दशकोट्येकोनपञ्चाशल्लक्षषट्चत्वारिंशत्सहस्राणि पदानि १०४९४६००० ॥३६३–३६४॥

उत्पादादिचतुर्दशपूर्वेषु यथाक्रमं पदसंख्योच्यते—वस्तुनो—द्रव्यस्य उत्पादव्ययध्रौव्याद्यनेकधर्मपूरक-मुत्पादपूर्वं तच्च जीवादिद्रव्याणां नानानयविषयक्रमयौगपद्यसंभावितोत्पादव्ययध्रौव्याणि त्रिकालगोचराणि नवधर्मा भवन्ति। तत्परिणतं द्रव्यमपि नवविधं। उत्पन्नं उत्पद्यमानं उत्पत्स्यमानं। नष्टं नश्यत् नंक्ष्यत्। स्थितं तिष्ठत् स्थास्यदिति नवप्रकारा भवन्ति। उत्पन्नादीनां प्रत्येकं नवविधत्वसंभवादेकाशीतिविकल्पधर्मपरि-

प्रत्येक चूलिकामें 'रनधजधरानन' दो कोटि नौ लाख नवासी हजार दो सौ पद हैं २०९८९-२००। चन्द्रप्रज्ञप्ति आदि पाँच परिकर्मोंमें मिलाकर 'याजकनामेनानन' एक कोटि इक्यासी लाख पाँच हजार पद हैं १८१०५०००। जलगता आदि पाँचों चूलिकाओंके पदोंका जोड़ 'कानवधिवाचनान' दस कोटि उनचास लाख छियालीस हजार १०४९४६००० है ॥३६३-३६४॥

उत्पाद आदि चौदह पूर्वोंमें क्रमसे पद संख्या कहते हैं—द्रव्यके उत्पाद-व्यय आदि अनेक धर्मोंका पूरक उत्पादपूर्व है। जीवादि द्रव्योंके नाना नय विषयक क्रम और युगपत् होनेवाले तीन कालके उत्पाद-व्यय-ध्रौव्यरूप नौ धर्म होते हैं अतः उन धर्मरूप परिणत द्रव्य भी नौ प्रकारका है—उत्पन्न, उत्पद्यमान, उत्पत्स्यमान, जो नष्ट हो चुका, हो रहा है, होगा, स्थिर हुआ, हो रहा है, होगा ये नौ प्रकार हैं। उत्पाद आदि प्रत्येकके नौ

द्विसंयोगत्रिसंयोगजंगळ त्रिश्येकसंख्यंगळु ७ मेलेनंत सप्तभंगियं प्रश्नवशदिदमो दे वस्तुविनोळविरोधदिद संभविपुदं नानानयमुख्यगोणभावदिदं प्ररूपिसुगुमिल्लि । द्विलक्षगुणितत्रिशत्पदंगळु पत्तिलक्षपदंगळप्पुवेंबुदर्थं ६००००००। ४।

ज्ञानानां प्रवादः प्ररूपणमस्मिन्निति ज्ञानप्रवादं। पंचमं पूर्व्वमिदु। मतिश्रुतावधिमनःपर्य्यय केवलमें दु पंच सम्यज्ञानंगळु। कुमतिकुश्रुतविभंगमें य त्र्यज्ञानंगळिवे[२]र स्वरूपसंख्याविषयफळंगळनाश्रयिसियवक्के प्रामाण्याप्रामाण्यविभागमुमं वर्णिसुगुमल्लि द्विलक्षगुणितपंचाशत्पदंगळु रूपोनकोटिगळप्पुवेकेंदोडे पंचमरूऊणमें बुदरिदं पंचमप्पूर्व्वदोळु द्विलक्षगुणितपंचाशत्पदलब्धदोळो दु कोटियोळो दु गुंदुगुमें दु पेळदुदरिदं ५ = अ = ९९९९९९९। सत्यस्प्रवादः प्ररूपणमस्मिन्निति सत्यप्रवादं षष्ठपूर्व्वमिदु वाग्गुप्तियुमं वाक्संस्कारकारणंगळुमं वाक्प्रयोगमुमं द्वादशभाषेगळुमं वक्तृभेदगळुमं बहुविधमृषाभिधानमुमं दशविधसत्यमुमं प्ररूपिसुगु

वाक्तव्यं च स्वद्रव्यक्षेत्रकालभावान् युगपत् स्वपरद्रव्यक्षेत्रकालभावद्वयं च संयुक्तमाश्रित्य। स्यान्नास्त्यवक्तव्यं च परद्रव्यक्षेत्रकालभावान् युगपत्स्वपरद्रव्यक्षेत्रकालभावद्वयं च संयुक्तमाश्रित्य। स्यादस्ति च नास्ति चावक्तव्य च क्रमेण स्वपरद्रव्यक्षेत्रकालभावद्वय युगपत्स्वपरद्रव्यक्षेत्रकालभावद्वयं च संयुक्तमाश्रित्य। इत्येकानेकनित्यानित्याद्यनन्तधर्माणां विधिनिषेधावक्तव्यभङ्गानां प्रत्येकद्विसंयोगत्रिसंयोगजानां त्रिद्व्येकसंख्यानां मेलनात् सप्तभङ्गी प्रश्नवशादेकस्मिन्नेव वस्तुनि अविरोधेन संभवन्ती नानानयमुख्यगौणभावेन प्ररूपयति। तत्र द्विलक्षगुणितत्रिंशल्लक्षाणि षष्टिर्लक्षाणि इत्यर्थः। ६०००००० । ज्ञानानां प्रवादः प्ररूपणमस्मिन्निति ज्ञानप्रवादं पञ्चम पूर्वं, तच्च मतिश्रुतावधिमनःपर्ययकेवलानि पञ्च सम्यग्ज्ञानानि, कुमतिकुश्रुतविभङ्गाख्यानि त्रीण्यज्ञानानि स्वरूपसंख्याविषयफलानि आश्रित्य तेषां प्रामाण्याप्रामाण्यविभागं च वर्णयति। तत्र द्विलक्षगुणितपञ्चाशल्लक्षाणि किन्तु पञ्चमरूऊणमिति कथनादेकरूपोना कोटिरित्यर्थः ९९९९९९९। सत्यस्य प्रवादः प्ररूपणमस्मिन्निति सत्यप्रवादं षष्ठं पूर्वं, तच्च वाग्गुप्तिः वाक्संस्कारकारणानि वाक्प्रयोगं द्वादश भाषा

भावकी अपेक्षा स्यात् अस्ति नास्ति है। एक साथ स्वपर द्रव्यक्षेत्रकाल भावकी अपेक्षा अवक्तव्य है क्योंकि एक साथ दोनों धर्मोंका कहना शक्य नहीं है। स्वद्रव्यक्षेत्रकाल भाव तथा युगपत् स्वपरद्रव्यक्षेत्रकाल भावकी अपेक्षा स्यादस्ति अवक्तव्य है। परद्रव्यक्षेत्रकालभाव और युगपत् स्वपरद्रव्यक्षेत्रकालभावकी अपेक्षा स्यात् नास्ति अवक्तव्य है। तथा क्रमसे स्वपरद्रव्यक्षेत्रकालभाव और युगपत् स्वपरद्रव्यक्षेत्रकालभावकी अपेक्षा स्यात् अस्तिनास्ति अवक्तव्य है। इस प्रकार एक अनेक, नित्य अनित्य आदि अनन्त धर्मोंके विधि निषेध और अवक्तव्य भंगोंके प्रत्येक, दो संयोगी, तीन संयोगी तीन, तीन और एक भंगोंकी संख्याको मिलानेसे सप्तभंगी होती है। वह प्रश्नके अनुसार एक वस्तुमें किसी विरोधके बिना नाना नयोंकी मुख्यता और गौणतासे कथन करती है। उसमें दो लाखसे गुणित तीस अर्थात् साठ लाख पद हैं। ज्ञानका जिसमें प्रवाद अर्थात् प्ररूपण हो वह ज्ञानप्रवाद नामक पंचम पूर्व है। वह मति, श्रुत, अवधि, मनःपर्यय और केवल इन पाँच सम्यग्ज्ञानोंका तथा कुमति, कुश्रुत कुअवधि इन तीन अज्ञानोंका स्वरूप, संख्या, विषय और फलको लेकर कथन करता है। उसमें दो लाखसे गुणित पचास किन्तु 'पंचमरूऊण' कहनेसे एक कम एक करोड़ पद होते हैं। सत्यका प्रवाद अर्थात् कथन जिसमें हो वह सत्यप्रवाद पूर्व है। वह वचन गुप्ति, वचनके संस्कारके कारण, वचन प्रयोग, बारह भाषा, वक्ताके भेद, अनेक प्रकारका असत्य और

१. म पेळल्प ए। २. म र्दिनिवर।

यंगळप्पु कारणदिदं। व्यवहाराश्रयदिदं कर्म्मनोकर्म्मरूपमूर्त्तद्रव्यानादिसंबंधदिदं मूर्त्तनु निश्चयनयाश्रयदिनमूर्त्तमेंबित्याद्यात्मधर्म्मंगळ समुच्चयं माडल्पडुगुमीयात्मप्रवाददोळु द्विलक्षगुणितत्रयोदशशतपदंगळु षड्विंशतिकोटिगळप्पुवें बुदत्थं। २६००००००० २६ को।

कर्म्मणः प्रवादः प्ररूपणमस्मिन्निति कर्म्मप्रवादमष्टमं पूर्व्वमदु। मूलोत्तरप्रकृतिभेदभिन्नं बहुविधबन्धोदयोदीरणासत्वाद्यवस्थं ज्ञानावरणादिकर्म्मस्वरूपं सांपरायिकेर्य्यापथतपस्याऽऽधाकर्म्मादिगळुमं वर्णिसुगुमल्लि द्विलक्षगुणितनवतिपदंगळेककोटियुमशीतिलक्षंगळप्पुवें बुदत्थं १८०००००० १८० ल। प्रत्याख्यायते निषिध्यते सावद्यमस्मिन्ननेनेति वा प्रत्याख्यानं नवमं पूर्व्वमदु नामस्थापनाद्रव्यक्षेत्रकालभावंगळनाश्रयिसि पुरुषसंहननबलाद्यनुसारदिदं परिमितकालमेनपरिमितकालं प्रत्याख्यानं सावद्यवस्तुनिवृत्तियनुपवासविधियं तद्भावनांगमुमं पंचसमितित्रिगुप्त्यादिगळुमं वर्णिसुगुमल्लि द्विलक्षगुणितद्वाचत्वारिंशत्पदंगळु चतुरशीतिलक्षपदंगळप्पुवें बुदत्थं ८४००००० ८४ ल। विद्यानामनुवादोऽनुक्रमेण वर्णनं यस्मिन् तद्विद्यानुवादं दशमं पूर्व्वमदु। अल्लि अंगुष्ठप्रसेनाद्यल्पविद्येगळुं रोहिण्यादिपंचशतमहाविद्येगळुमं तत्स्वरूपसामर्थ्यसाधनमंत्रतंत्रपूजाविधानंगळुमं सिद्धमादविद्येगळ फलविशेषंगळुमनें टु महानिमित्तंगळुमनयायुवं दोडे अंतरिक्ष

नियनयेन मूर्तः निश्चयनयेनामूर्तः इत्यादय आत्मधर्माः समुच्चीयन्ते। तस्मिन्नात्मप्रवादे द्विलक्षगुणितत्रयोदशशतानि पदानि षड्विंशतिकोट्य इत्यर्थः २६०००००००। कर्मणः प्रवादः प्ररूपणमस्मिन्निति कर्मप्रवादमष्टमं पूर्वं। तच्च मूलोत्तरोत्तरप्रकृतिभेदभिन्नं बहुविकल्पबन्धोदयोदीरणसत्वाद्यवस्थं ज्ञानावरणादिकर्मस्वरूपं समवदानेर्यापथतपस्याधाकर्मादि च वर्णयति। तत्र द्विलक्षगुणितनवतिपदानि एककोट्यशीतिलक्षाणीत्यर्थः १८००००००। प्रत्याख्यायते निषिध्यते सावद्यमस्मिन्ननेनेति वा प्रत्याख्यानं नवमं पूर्वं। तच्च नामस्थापनाद्रव्यक्षेत्रकालभावानाश्रित्य पुरुषसंहननबलाद्यनुसारेण परिमितकालं अपरिमितकालं वा प्रत्याख्यानं सावद्यवस्तुनिवृत्तिं उपवासविधिं तद्भावनाङ्गं पञ्चसमितित्रिगुप्त्यादिकं च वर्णयति। तत्र द्विलक्षगुणितद्वाचत्वारिंशत्पदानि चतुरशीतिलक्षाणीत्यर्थः। ८४ ल.। विद्याना अनुवादः अनुक्रमेण वर्णनं यस्मिन् तद्विद्यानुवादं दशमं पूर्वं, तच्च सप्तशतानि अङ्गुष्ठप्रसेनाद्यल्पविद्याः रोहिण्यादिपञ्चशतमहाविद्याः तत्स्वरूपसामर्थ्यसाधनमन्त्र-

स्वभाववाला होनेसे अन्तरात्मा है। 'इति और च' शब्द उक्त और अनुक्त अर्थके समुच्चयके लिए है। इससे व्यवहारनयसे कर्म-नोकर्मरूप मूर्त द्रव्य आदिके सम्बन्धसे मूर्तिक है और निश्चयनयसे अमूर्तिक है, इत्यादि आत्मधर्मका समुच्चय किया जाता है। इस आत्मप्रवादमें दो लाखसे गुणित तेरह सौ अर्थात् छब्बीस कोटि पद हैं। कर्मका प्रवाद अर्थात् कथन जिसमें हो वह कर्मप्रवाद नामक आठवाँ पूर्व है। वह मूल और उत्तर प्रकृतिके भेदसे भिन्न, अनेक प्रकारके बन्ध उदय उदीरणा सत्ता आदि अवस्थाको लिये हुए ज्ञानावरण आदि कर्मोंके स्वरूपको तथा समवदान, ईर्यापथ, तपस्या, आधाकर्म आदिका कथन करता है। इसमें दो लाखसे गुणित नब्बे अर्थात् एक कोटि अस्सी लाख पद हैं। जिसमें 'प्रत्याख्यायते' अर्थात् सावद्य कर्मका निषेध किया गया है वह प्रत्याख्यान नामक नौवाँ पूर्व है। वह नाम, स्थापना, द्रव्य, क्षेत्र, काल, भावके आश्रयसे पुरुषके संहनन और बलके अनुसार परिमित काल या अपरिमित कालके लिए प्रत्याख्यान अर्थात् सावद्य वस्तुओंसे निवृत्ति, उपवासकी विधि, उसकी भावना, पाँच समिति, तीन गुप्ति आदिका वर्णन करता है। इसमें दो लाखसे गुणित बयालीस अर्थात् चौरासी लाख पद हैं। विद्याओंका अनुवाद अर्थात् अनुक्रमसे वर्णन जिसमें हो वह विद्यानुवाद पूर्व है। वह अंगुष्ठप्रसेना आदि सात सौ अल्पविद्याएँ,

१. ब कम्मर्म्मादिगळु।

[illegible] र्गिमुगुर्नल्लि द्विशतगुणितपंचाशदधिकचतुःशतपदंगळु नवकोटि- [illegible] ९ को ९०००००००। त्रिलोकानां त्रिलोकचयस्य सारं च वर्ण्यंतेऽस्मिन्निति [illegible] चतुर्दशपूर्व्वंमक्कु। त्रिलोकबिंदुसारमें बुदरोळ परिकर्म्मंगळं एंटु व्यवहारंगळुमं [illegible] मोक्षगुणस्वरूपमुमं पेळगुमल्लि द्विशा- [illegible] द्वादशकोटिगळं पंचाशल्लक्षंगळप्पुवे पदमुं १२५००००००।

[illegible] तदो वंदणा पडिक्कमणं।
[illegible] किदियम्मं दस वेयालं च उत्तरज्झयणं॥३६७॥

[illegible] ततो वंदना प्रतिक्रमणं। वैनयिकं कृतिकर्म्मं दशवैकालिकं च [illegible]।

[illegible] कप्पियमहकप्पियं च पुंडरियं।
[illegible] चोद्दसमंगबाहिरयं॥३६८॥

[illegible] महाकल्प्यं च पुंडरीकं। महापुंडरीकं निषिद्धिकेति चतुर्दशांग- [illegible]।

चतुस्त्रिंशदतिशयाष्टमहाप्रातिहार्य्यपरमौदारिकदिव्यदेहसमवसरणसभाधर्म्मोपदेशनादितीर्थंकरत्व- महिमेय स्तुतियु चतुर्व्विंशतिस्तवनमें बुदु । तत्प्रतिपादकशास्त्रमुं चतुर्व्विंशतिस्तवनमें बु पेळल्पड्डुदु । ततः परं एकतीर्थंकरालंबनचैत्यचैत्यालयादिस्तुतियं वंदनेयें बुदु तत्प्रतिपादकशास्त्रमुं वंदनेयें दु पेळल्पट्टुदु । प्रतिक्रम्यते प्रमादकृतदैवसिकादिदोषो निराक्रियते इनेनेति प्रतिक्रमणं। दैवसिक रात्रिक पाक्षिक चातुर्म्मासिक सांवत्सरिकैर्य्यापथिकोत्तमार्त्थभेददि सप्तविधमक्कुं। भरतादिक्षेत्रमं दुःषमादिकालमं षट्संहननसमन्वितस्थिरास्थिरादिपुरुषभेदंगळुमनाश्रयिसि तत्प्रति- पादकमप्प शास्त्रं प्रतिक्रमणमें बुदक्कुं । विनयः प्रयोजनमस्येति वैनयिकमें दु ज्ञानदर्शनचारित्र- तपउपचारविषयमप्प पंचविधविनयविधानमं पेळ्गु ।

कृतेः क्रियायाः कर्म्म विधानमस्मिन् वर्ण्यंत इति कृतिकर्म्म । ई कृतिकर्म्मशास्त्रमर्हत्सिद्धा- चार्य्यबहुश्रुतसाधुगळमोदलाद नवदेवतावंदनानिमित्तमं आत्माधीनता प्रादक्षिण्य त्रिवारत्र्यवनति चतुःशिरोद्वादशावर्त्तादिलक्षणनित्यनैमित्तिकक्रियाविधानमं वर्णिसुगुं । विशिष्टाः कालाः विकालाः तेषु भवानि वैकालिकानि । दशवैकालिकानि वर्ण्यंन्तेस्मिन्निति दशवैकालिकं । ई दशवैकालिक-

नामस्थापनाद्रव्यभावानाश्रित्य पञ्चमहाकल्याणचतुस्त्रिंशदतिशयाष्टमहाप्रातिहार्यपरमौदारिकदिव्यदेहसमवसरण- सभाधर्मोपदेशनादितीर्थंकरत्वमहिमस्तुतिः चतुर्विंशतिस्तवः तस्य प्रतिपादकं शास्त्रं वा चतुर्विंशतिस्तव इत्युच्यते। तस्मात्परं एकतीर्थंकरालम्बना चैत्यचैत्यालयादिस्तुतिः वन्दना तत्प्रतिपादकं शास्त्रं वा वन्दना इत्युच्यते। प्रतिक्रम्यते प्रमादकृतदैवसिकादिदोषो निराक्रियते अनेनेति प्रतिक्रमणं तच्च दैवसिकरात्रिकपाक्षिकचातुर्मासिक- सांवत्सरिकैर्यापथिकौत्तमार्थिकभेदात्सप्तविधं, भरतादिक्षेत्रं दुःषमादिकालं षट्संहननसमन्वितस्थिरास्थिरादिपुरुष- भेदांश्च आश्रित्य तत्प्रतिपादकं शास्त्रमपि प्रतिक्रमणम् । विनयः प्रयोजनमस्येति वैनयिकं तच्च ज्ञानदर्शनचारित्र- तपउपचारविषयं पञ्चविधविनयविधानं कथयति । कृतेः क्रियायाः कर्म विधानं अस्मिन् वर्ण्यते इति कृतिकर्म। तच्च अर्हत्सिद्धाचार्यबहुश्रुतसाध्वादिनवदेवतावन्दनानिमित्तमात्माधीनताप्रादक्षिण्यत्रिवारत्रिनवतिचतुःशिरो- द्वादशावर्तादिलक्षणनित्यनैमित्तिकक्रियाविधानं च वर्णयति । विशिष्टाः काला विकालास्तेषु भवानि वैकालिकानि

यिक शास्त्रमें उपयुक्त उसका ज्ञाता, अथवा सामायिक पर्यायरूप परिणत व्यक्ति भावसामा- यिक है । इस-इस कालसम्बन्धी चौबीस तीर्थंकरोंके नाम, स्थापना, द्रव्य और भावको लेकर पंच महाकल्याणक, चौंतीस अतिशय, आठ महाप्रातिहार्य, परम औदारिक दिव्य शरीर, सम- वसरण सभा, धर्मोपदेशना आदिके द्वारा, तीर्थंकरकी महिमाका स्तवन चतुर्विंशतिस्तव है। अथवा उसका कथन करनेवाला शास्त्र चतुर्विंशतिस्तव कहा जाता है। उसके पश्चात् एक तीर्थंकरको लेकर चैत्य-चैत्यालय आदिकी स्तुति वन्दना है। अथवा उसका प्रतिपादक शास्त्र वन्दना कहलाता है। जिसके द्वारा 'प्रतिक्रम्यते' अर्थात् प्रमादसे किये हुए दैवसिक आदि दोषोंका निराकरण किया जाता है वह प्रतिक्रमण है। वह दैवसिक, रात्रिक, पाक्षिक, चातुर्मासिक, सांवत्सरिक, ऐर्यापथिक और पारमार्थिकके भेदसे सात प्रकारका है। भरत आदि क्षेत्र, दुःषमादि काल, छह संहननोंसे युक्त स्थिर-अस्थिर आदि पुरुषोंके भेदोंको लेकर प्रतिक्रमणका कथन करनेवाला शास्त्र भी प्रतिक्रमण है। विनय जिसका प्रयोजन है वह वैनयिक है। वह ज्ञान, दर्शन, चारित्र, तप और उपचारके भेदसे पाँच प्रकारकी विनयका कथन करता है। जिसमें कृति अर्थात् क्रियाकर्मका विधान कहा जाता है वह क्रियाकर्म है। उसमें अर्हन्त, सिद्ध-आचार्य, बहुश्रुत (उपाध्याय), साधु आदि नौ देवताओंकी वन्दनाके निमित्त आत्माधीनता (अपने अधीन होना), तीन बार प्रदक्षिणा, तीन बार नमस्कार, चार

रासम्यक्त्वसंयमादिविधानमं तत्तदुपपादस्थानवैभवविशेषमुमं वर्णिसुगुं।

महापुंडरीकमें ब शास्त्रं महर्द्धिकरप्पेंद्रप्रतींद्रादिगळोळुत्पत्तिकारण तपोविशेषाद्याचारमं वर्णिसुगुं।

निषेधनं प्रमाददोषनिराकरणं निषिद्धिः संज्ञेयोळु कप्रत्ययमागुत्तिरलु निषिद्धिका। एंदितु प्रायश्चित्तशास्त्रमें बुदर्त्थंमदु प्रमाददोषविशुद्ध्यर्थं बहुप्रकारमप्प प्रायश्चित्तमं वर्णिसुगुं। निशीतिका मा एंदितु क्वचित्पाठं काणल्पडुगुं।

इंतु चतुर्द्दशविधमप्प अंगबाह्यश्रुतं परिभाविसल्पडुवुदु। अनंतरं शास्त्रकारं श्रुतज्ञानमाहात्म्यमं पेळ्दपं।

सुदकेवलं च णाणं दोण्णिवि सरिसाणि होंति बोहादो।
सुदणाणं तु परोक्खं पच्चक्खं केवलं णाणं ॥३६९॥

श्रुतं केवलं च ज्ञानं द्वे अपि सदृशे भवतो बोधात्। श्रुतज्ञानं तु परोक्षं प्रत्यक्षं केवलं ज्ञानम्।

श्रुतज्ञानमुं केवलज्ञानमुमें बेरडुं ज्ञानंगळु बोधात् अरिविनिंदं समस्तवस्तुद्रव्यगुणपर्य्यायपरिज्ञानदिंदं समानंगळेयप्पुवु। तु मत्ते इदु विशेषमुंटदें तेंदोडे परमोत्कर्षपर्य्यंतप्राप्तमादुदादोडं श्रुतकेवलज्ञानं सकलपदार्थंगळोळु परोक्षं अविशदमस्पष्टममूर्त्तंगळोळमर्त्थपर्य्यायंगळोळमुळिद सूक्ष्मांशंगळोळं विशदत्वदिंदं प्रवृत्त्यभावमप्पुदरिंदं। मूर्त्तंगळोळु व्यंजनपर्य्यायंगळप्प स्थूलांशंगळप्प सर्व्वस्थंगळोळु अवधिज्ञानादियंते साक्षात्करणाभावदिदमुं सकलावरणवीर्य्यांतराय निरवशेषक्षयो-

---

तत्र महर्द्धिकेषु इन्द्रप्रतीन्द्रादिषु उत्पत्तिकारणतपोविशेषाद्याचरणं वर्णयति। निषेधनं प्रमाददोषनिराकरणं निषिद्धिः संज्ञायां कप्रत्यये निषिद्धिका प्रायश्चित्तशास्त्रमित्यर्थः, तत्र प्रमाददोषविशुद्ध्यर्थं बहुप्रकारं प्रायश्चित्तं वर्णयति। निशीतिका इति क्वचित्पाठो दृश्यते। एवं चतुर्दशविधं अङ्गबाह्यश्रुतं परिभावनीयम् ॥३६७-३६८॥ अथ शास्त्रकारः श्रुतज्ञानमाहात्म्यं वर्णयति—

श्रुतज्ञानं केवलज्ञानं चेति द्वे ज्ञाने बोधात् समस्तवस्तुद्रव्यगुणपर्यायपरिज्ञानात् सदृशे समाने भवतः तु-पुनः अयं विशेषः। स कः? परमोत्कर्षपर्यन्तं प्राप्तमपि श्रुतकेवलज्ञानं सकलपदार्थेषु परोक्षं अविशदं अस्पष्टं अमूर्तेषु अर्थपर्यायेषु अन्येषु सूक्ष्मांशेषु विशदत्वेन प्रवृत्त्यभावात्। मूर्तेष्वपि व्यञ्जनपर्यायेषु स्थूलांशेषु

पुण्डरीक शास्त्रको महापुण्डरीक कहते हैं। उसमें महर्द्धिक इन्द्र-प्रतीन्द्र आदिमें उत्पत्तिके कारण तपोविशेष आदि आचरणका कथन होता है। निषेधन अर्थात् प्रमादसे लगे दोषोंका निराकरण निषिद्धि है। संज्ञामें 'क' प्रत्यय करनेपर निषिद्धिका होता है, उसका अर्थ है प्रायश्चित्त शास्त्र। उसमें प्रमादसे लगे दोषोंकी विशुद्धिके लिए बहुत प्रकारके प्रायश्चित्तोंका वर्णन है। कहींपर 'निशीतिका' पाठ भी देखा जाता है। इस प्रकार चौदह प्रकारका अंगबाह्य श्रुत जानना ॥३६७-३६८॥

अब शास्त्रकार श्रुतज्ञानके माहात्म्यको कहते हैं—

श्रुतज्ञान और केवलज्ञान ये दोनों ज्ञान समस्त वस्तुओंके द्रव्य-गुण-पर्यायोंको जाननेकी अपेक्षा समान हैं। किन्तु इतना विशेष है कि परम उत्कर्ष पर्यन्तको प्राप्त भी श्रुतज्ञान समस्त पदार्थोंमें परोक्ष होता है, अस्पष्ट जानता है, अमूर्त अर्थ पर्यायोंमें तथा अन्य सूक्ष्म अंशोंमें स्पष्ट रूपसे उसकी प्रवृत्ति नहीं होती। मूर्त भी व्यंजन पर्यायोंको अपने विषयके

विहितमुक्तं भवगुणप्रत्ययविहितं भवप्रत्ययपत्वदिदं गुणप्रत्ययपत्वदिवं पेळल्पट्टुदं तद्विविधमवधिज्ञानमिति। अंतप्पिदनवधिज्ञानमें दितु ब्रुवंति अर्हदादिगळु पेळ्वरु। सीमाविषयमनुळ्ळवधिज्ञानं भवप्रत्ययमें दु गुणप्रत्ययमें दितु द्विविधमक्कुमें बुदु तात्पर्य्यं।

भवपच्चइगो सुरणिरयाणं तित्थेवि सव्वअंगुत्थो।
गुणपच्चइगो णरतिरियाणं संखादिचिण्हंभवो ॥३७१॥

भवप्रत्ययकं सुरनारकाणां तीर्त्थेपि सर्व्वांगोत्थं। गुणप्रत्ययकं नरतिरश्चां शंखादिचिह्नभवं ॥

भवप्रत्ययावधिज्ञानं देवक्कंळोळं नारकरोळं चरमभवतीर्थंकरोळं संभविसुगुमदुवुमवरोळु सर्व्वांगोत्थमक्कुं। सर्व्वात्मप्रदेशस्थावधिज्ञानावरणवीर्य्यांतरायद्वयक्षयोपशमोत्पन्नमें बुदर्थं। गुणप्रत्ययावधिज्ञानं पर्य्याप्तमनुष्यर्गं संज्ञिपंचेंद्रियपर्य्याप्ततिर्य्यंचर्गं संभविसुगुमदुवुमवरोळु शंखादिचिह्नभवं नाभिप्रदेशदिदं मेगण शंखपद्मवज्रस्वस्तिकझषकलशादिशुभचिह्नलक्षितात्मप्रदेशस्थावधिज्ञानावरणवीर्य्यांतरायकर्म्मद्वयक्षयोपशमोत्थमें बुदर्थं। भवप्रत्ययावधिज्ञानदोळु दर्शनविशुद्ध्यादिगुणसद्भावमावोडमदनपेक्षिसदे भवप्रत्ययत्वमरियल्पडुगुं। गुणप्रत्ययावधिज्ञानदोळु तिर्य्यग्मनुष्यभवसद्भावमावोडमदनपेक्षिसदे गुणप्रत्ययत्वमरियल्पडुगुं।

विधं भवगुणप्रत्ययविहितं—भवः नरकादिपर्यायः, गुणः सम्यग्दर्शनविशुद्ध्यादिः भवगुणौ प्रत्ययौ कारणे ताभ्यां विहितमुक्तं भवगुणप्रत्ययविहितं भवप्रत्ययत्वेन गुणप्रत्ययत्वेन अवधिज्ञानं द्विविधं कथितमित्यर्थः ॥३७०॥

तत्र भवप्रत्ययावधिज्ञानं सुराणां नारकाणां चरमभवतीर्थंकराणां च संभवति। तच्च तेषां सर्वांगोत्थं भवति। सर्वात्मप्रदेशस्थावधिज्ञानावरणवीर्यान्तरायकर्मद्वयक्षयोपशमोत्थं भवतीत्यर्थः। गुणप्रत्ययं अवधिज्ञानं नराणां पर्याप्तमनुष्याणां तिरश्चां च संज्ञिपञ्चेन्द्रियपर्याप्ततिरश्चां संभवति। तच्च तेषां शङ्खादिचिह्नभवं भवति, नाभेरुपरि शङ्खपद्मवज्रस्वस्तिकझषकलशादिशुभचिह्नलक्षितात्मप्रदेशस्थावधिज्ञानावरणवीर्यान्तरायकर्मद्वयक्षयोपशमोत्पन्नमित्यर्थः। भवप्रत्यये अवधिज्ञाने दर्शनविशुद्ध्यादिगुणसद्भावेऽपि तदनपेक्षयैव भवप्रत्ययत्वं ज्ञातव्यम्। गुणप्रत्ययेऽवधिज्ञाने तिर्यग्मनुष्यभवसद्भावेऽपि तदनपेक्षयैव गुणप्रत्ययत्वं ज्ञातव्यम् ॥३७१॥

अपरिमित है ऐसा इसका नहीं है। परमागममें जो तीसरा सीमा विषयक ज्ञान कहा है उसे अर्हन्त आदि अवधिज्ञान कहते हैं। भव अर्थात् नरकादि पर्याय और गुण अर्थात् सम्यग्दर्शन विशुद्धि आदि। भव और गुण जिनके कारण हैं वे भवप्रत्यय और गुणप्रत्यय नामक अवधिज्ञान हैं। इस तरह अवधिज्ञानके दो भेद हैं ॥३७०॥

इनमें-से भवप्रत्यय अवधिज्ञान देवों, नारकियों और चरमशरीरी तीर्थंकरोंके होता है। तथा यह समस्त आत्माके प्रदेशोंमें वर्तमान अवधिज्ञानावरण और वीर्यान्तराय नामक दो कर्मोंके क्षयोपशमसे उत्पन्न होता है इसलिए इसे सर्वांगसे उत्पन्न कहा जाता है। गुणप्रत्यय अवधिज्ञान पर्याप्त मनुष्योंके और संज्ञी पंचेन्द्रिय पर्याप्त तिर्यंचोंके होता है। और वह उनके शंख आदि चिह्नोंसे उत्पन्न होता है। अर्थात् नाभिसे ऊपर शंख, पद्म, वज्र, स्वस्तिक, मच्छ, कलश आदि शुभ चिह्नोंसे युक्त आत्मप्रदेशोंमें स्थित अवधिज्ञानावरण और वीर्यान्तराय कर्मोंके क्षयोपशमसे उत्पन्न होता है। भवप्रत्यय अवधिज्ञानमें भी सम्यग्दर्शन, विशुद्धि आदि गुण रहते हैं फिर भी उसकी उत्पत्तिमें उन गुणोंकी अपेक्षा नहीं होती, मात्र भवधारण करनेसे ही अवधिज्ञान होता है इसीलिए उसे भवप्रत्यय कहते हैं। गुणप्रत्यय अवधिज्ञानमें यद्यपि मनुष्य और तिर्यंचका भव रहता है फिर भी अवधिज्ञानकी उत्पत्तिमें उसकी अपेक्षा

ननुगामियें बुदक्कुमावुदोंदु भवांतरमं बळिसल्वुदल्तु तां पुट्टिद भववोळे केडुगुं। क्षेत्रांतरमं बळिसल्के मेणमाणे अदु भवाननुगामियें बुदक्कुमावुदोंदु क्षेत्रांतरमं भवांतरमुमं बळिसल्वुदल्तु। स्वोत्पन्नक्षेत्रभवंगळोळे केडुगुमदुभयाननुगामियें बुदक्कुमावुदोंदु हानियुं वृद्धियुं इल्लदे सूर्य्यमंडलदंतेकप्रकारमागिरुत्तिर्क्कुमदु अवस्थितावधियें बुदक्कुमावुदोंदु ओम्मे पेर्च्चुगुमोम्में कुंदुगुमोम्में यवस्थितमागिक्कुमदनवस्थितावधिज्ञानमें बुदक्कु। मावुदोंदु शुक्लपक्षद चंद्रमंडलदंते स्वोत्कृष्टपर्य्यंतं पेर्च्चुगुमदु वर्द्धमानदेशावधियें बुदक्कुं। आवुदोंदु कृष्णपक्षद चंद्रमंडलदंते स्वक्षयपर्य्यंतं कुंदुगुमदु हीयमानदेशावधियेंबुदक्कुमंते सामान्यदिदमवधिज्ञानं देशावधियेंदुं दक्के परमावधियेंदुं सर्व्वावधियुमेंदितु त्रिधा त्रिप्रकारमक्कुमिनितु गुणप्रत्ययमप्प देशावधिये षट्प्रकारमक्कुं परमावधिसर्व्वावधिगळल्तेंबुदर्त्थं।

भवपच्चइगो ओहो देसोही होदि परमसव्वोही।
गुणपच्चइगो णियमा देसोही वि य गुणे होदि ॥३७३॥

भवप्रत्ययावधिर्देशावधिर्भवति परमसर्व्वावधिः। गुणप्रत्ययो नियमाद् भवतः देशावधिरपि च गुणे भवति ॥

आवुदोंदु पूर्व्वोक्तभवप्रत्ययावधियदुनियमादवश्यंभावात् देशावधियेयक्कुं। देवनारकरुगळगं गृहस्थतीर्त्थकरर्गेयुं परमावधियुं सर्व्वावधियुं संभविसवप्पुदरिदं, परमावधियुं सर्व्वावधियुं नियमदिदं गुणप्रत्ययंगळेयप्पुवेक्केंदोडे संयमलक्षणगुणभवदोळा येरडक्कभावमप्पुदरिदं देशावधियुं-

तद्भवाननुगामि। यत् क्षेत्रान्तरं भवान्तरं च नानुगच्छति स्वोत्पन्नक्षेत्रभवयोरेव विनश्यति तत् क्षेत्रभवाननुगामि। यद्धानिवृद्धिभ्यां विना सूर्यमण्डलवत् एकप्रकारमेव तिष्ठति तदवस्थितम्। यत् कदाचिद्वर्धते कदाचिद्धीयते कदाचिदवतिष्ठते च तदनवस्थितम्। यत् शुक्लपक्षस्य चन्द्रमण्डलवत् स्वोत्कृष्टपर्यन्तं वर्द्धते तद् वर्धमानम्। यत् कृष्णपक्षचन्द्रमण्डलवत् स्वक्षयपर्यन्तं हीयते तद्धीयमानं देशावधिज्ञानं भवति। तथा सामान्येन अवधिज्ञानं देशावधिः परमावधिः सर्वावधिश्च इति त्रिधा त्रिप्रकारं भवति। एवं गुणप्रत्ययो देशावधिः षोढा न परमावधिसर्वावधी इत्यर्थः ॥३७२॥

यः पूर्वोक्तो भवप्रत्ययोऽवधिः स नियमात्—अवश्यंभावात् देशावधिरेव भवति देवनारकयोर्गृहस्थतीर्थंकरस्य च परमावधिसर्वावध्योरसंभवात्। परमावधिः सर्वावधिश्च द्वावपि नियमेन गुणप्रत्ययावेव भवतः

भवान्तरमें जाये या न जावे, वह क्षेत्राननुगामी है। जो अन्य भवमें साथ नहीं जाता अपने उत्पत्तिभवमें ही छूट जाता, अन्य क्षेत्रमें जाये या न जाये, वह भवाननुगामी है। जो न अन्य क्षेत्रमें साथ जाता है और न अन्य भवमें साथ जाता है अपने उत्पत्तिक्षेत्र और भवमें ही छूट जाता है वह क्षेत्र भवाननुगामी है। जो हानि-वृद्धिके विना सूर्यमण्डलकी तरह एक रूप ही रहता है वह अवस्थित है। जो कभी बढ़ता है, कभी घटता है, कभी तदवस्थ रहता है वह अनवस्थित है। जो शुक्लपक्षके चन्द्रमण्डलकी तरह अपने उत्कृष्टपर्यन्त बढ़ता है वह वर्धमान है। जो कृष्णपक्षके चन्द्रमण्डलकी तरह अपने क्षयपर्यन्त घटता है वह हीयमान है। तथा सामान्यसे अवधिज्ञान देशावधि, परमावधि, सर्वावधिके भेदसे तीन प्रकार है। इस प्रकार गुणप्रत्यय देशावधि छह प्रकारका है परमावधि सर्वावधि नहीं ॥३७२॥

पूर्वोक्त भवप्रत्यय अवधि नियमसे देशावधि ही होता है, क्योंकि देव, नारकी और गृहस्थ अवस्थामें तीर्थंकरके परमावधि सर्वावधि नहीं होते। परमावधि और सर्वावधि

इनितु क्षेत्रदोळु पूर्व्वोक्तजघन्यद्रव्यंगळेनितोळवनितुमं जघन्यदेशावधिज्ञानमरिगुमल्लियं पोरगिद्दुंदनरियदें दितु क्षेत्रसोमे पेळल्पट्टुदु।

अवरोहिखेत्तदीहं वित्थारुस्सेहयं ण जाणामो।
अण्णं पुण समकरणे अवरोगाहणपमाणं तु ॥३७९॥

अवरावधिक्षेत्रदैर्घ्यं विस्तारोत्सेधकं न जानीमः। अन्यत्पुनः समकरणे अवरावगाहनप्रमाणं तु।

जघन्यावधिविषयक्षेत्रदैर्घ्यविस्तारोत्सेधप्रमाणमं नामरियेवु ईगळवरुपदेशाभावमप्पुदरिदं। तु मत्ते परमगुरूपदेशपरंपरायातं मत्तों दुंदु समकरणदोळु भुजकोटियेदिगळ्गे होनाधिकभावमिल्लदे समीकरणमागुत्तिरलु पुट्टिद क्षेत्रफलं जघन्यावगाहनप्रमाणं घनांगुलासंख्यातेकभागमात्रमक्कुमें बिदने बल्लेवु।

अवरोगाहणमाणं उस्सेहंगुलअसंखभागस्स।
सूइस्स य घणपदरं होदि हु तक्खेत्तसमकरणे ॥३८०॥

अवरावगाहनमानमुत्सेधांगुलासंख्यातभागस्य। सूच्याश्च घनप्रतरं भवति खलु तत् क्षेत्रसमकरणे।

अंतादोडा सूक्ष्मनिगोद लब्ध्यपर्य्याप्तकन जघन्यावगाहनमेंतुटेंदितु प्रश्नमागुत्तिरलुत्तरवचनमिदु तज्जघन्यावगाहनमनियतसंस्थानमक्कुमादोडं क्षेत्रखंडनविधानदिदं भुजकोटि वेधेगळगे समकरणमागुत्तिरलुत्सेधांगुलमं परिभाषानिष्पन्नव्यवहारसूच्यंगुलमनागुदानुमों द संख्यातदिदं खंडिसि-

ज्ञानविषयभूतक्षेत्रप्रमाणं भवति ६ । ८ । २२ । एतावति क्षेत्रे पूर्वोक्तजघन्यद्रव्याणि यावन्ति संति तावन्ति

प १९ । ८ । ९ । ८ । २२ । ९ ९

जघन्यदेशावधिज्ञानं जानाति न तद्बहिःस्थितानीति क्षेत्रसीमा कथिता ॥३७८॥

जघन्यावधिविषयक्षेत्रस्य दैर्घ्यविस्तारोत्सेधप्रमाणं न जानीमः। इदानी तदुपदेशाभावात्। तु पुनः परमगुरूपदेशपरम्परायातं जघन्यावगाहनप्रमाणं समकरणे-समीकरणे कृते सति घनाङ्गुलासंख्यातैकभागमात्रं भवति इत्यन्यत्पुनर्जानीमः ॥३७९॥

तर्हि तत्सूक्ष्मनिगोदलब्ध्यपर्याप्तकस्य जघन्यावगाहनं कीदृग् अस्ति ? इति चेत्, तदवगाहनं अनियतसंस्थानमस्ति तथापि क्षेत्रखण्डनविधानेन भुजकोटिवेधानां समकरणे सति उत्सेधाङ्गुलपरिभाषानिष्पन्नव्यवहार-

क्षेत्रमें पूर्वोक्त प्रमाणवाले जितने जघन्य द्रव्य होते हैं उन सबको जघन्य देशावधिज्ञान जानता है। उस क्षेत्रसे बाहर स्थितको नहीं जानता। इस प्रकार जघन्य देशावधिज्ञानके क्षेत्रकी सीमा कही ॥३७८॥

इस जघन्य देशावधि ज्ञानके विषयभूत क्षेत्रकी लम्बाई, चौड़ाई, ऊँचाई नहीं जानते, क्योंकि इस कालमें उसका उपदेश नहीं प्राप्त है। किन्तु परम गुरुके उपदेशकी परम्परासे इतना जानते हैं कि जघन्य अवगाहनाके प्रमाणका समीकरण करनेपर क्षेत्रफल घनांगुलके असंख्यातवें भाग मात्र होता ॥३७९॥

प्रश्न होता है कि वह सूक्ष्म निगोद लब्ध्यपर्याप्तककी जघन्य अवगाहना कैसी है ? इसका उत्तर यह है कि उस जघन्य अवगाहनाका आकार नियत नहीं है। फिर भी क्षेत्र

नप्रमाणं जघन्यदेशावधिक्षेत्रमक्कु कारणदिदं व्यवहारांगुलमनाश्रयिसियें पेळल्पट्टुदु। तज्जघन्याव-गाहनमुं परमागमदोळु देहगेहग्रामनगरादिप्रमाणमुत्सेधांगुलदिदमे येंदितु नियमितमप्पुदरिदं व्यवहारांगुलाश्रितमे यक्कुं। मेले यावुदों देडयोळंगुलमावलिया एकभागमसंखेज्जमित्यादिगाथा सूत्रोक्तकांडकंगळोळु अंगुलग्रहणमल्लि प्रमाणांगुलमे ग्राह्यमक्कुमुत्तरोत्तर निर्दिश्यमानहस्तगव्यूति-योजनभरतादिक्षेत्रंगळ्गे प्रमाणांगुलाश्रितत्वदिदं।

अवरोहिखेत्तमज्झे अवरोही अवरदव्वमवगमइ।
तद्दव्वस्सवगाहो उस्सेहासंखघणपदरो ॥३८२॥

अवरावधिक्षेत्रमध्ये अवरावधिरवरद्रव्यमवगच्छति। तद्द्रव्यस्यावगाहः उत्सेधासंख्य-घनप्रतरः।

जघन्यावधिक्षेत्रमध्यदोळिर्दतिर्द्द पूर्वोक्तजघन्यद्रव्यमं जघन्यदेशावधिज्ञानमरिगुं। तत् क्षेत्रमध्यदोळिर्दतिर्द्द असंख्यातंगळनौदारिकशरीरसंचयलोकभक्तैकभागप्रमितखंडंगळननितुमनरिगु-मेंदुदर्थं। तज्जघन्यपुद्गलस्कंधद मेले एकद्व्यादिप्रदेशोत्तरपुद्गलस्कंधंगळनरियुमेंबुवनिल्लि पेळल्वेडेकें बोडे सूक्ष्मविषयज्ञानक्के स्थूलाववोधनदोळु सुघटत्वमप्पुदरिदं। द्रव्यावगाहक्षेत्रं जघन्या-वधिविषयक्षेत्रमं नोडलसंख्येयगुणहीनमक्कुमादोडं उत्सेधघनांगुलासंख्यातभागमात्रमक्कुं। मवर

सूक्ष्मनिगोदलब्ध्यपर्याप्तकजघन्यावगाहनप्रमाणं जघन्यदेशावधिक्षेत्रं ततः कारणात्, देहगेहग्रामनगरादिप्रमाणं उत्सेधाङ्गुलेनैवेति परमागमे नियमितत्वात् व्यवहाराङ्गुलमेवाश्रितं भवति। उपरि यत्र "अङ्गुलमावलियाए भागमसंखेज्जदो वि संखेज्जो, इत्यादिगाथासूत्रोक्तकाण्डकेषु अङ्गुलग्रहणं तत्र प्रमाणाङ्गुलमेव ग्राह्यं, उत्तरोत्तर-निर्दिश्यमानहस्तगव्यूतियोजनभरतादिक्षेत्राणां प्रमाणाङ्गुलाश्रितत्वात् ॥३८१॥

जघन्यावधिक्षेत्रमध्ये स्थितं पूर्वोक्तं जघन्यद्रव्यं जघन्यदेशावधिज्ञानं जानाति तत्क्षेत्रमध्यस्थितानि औदारिकशरीरसंचयस्य लोकविभक्तैकभागप्रमितखण्डानि असंख्यातानि जानातीत्यर्थः। तज्जघन्यपुद्गलस्कन्ध-स्योपरि एकद्व्यादिप्रदेशोत्तरपुद्गलस्कन्धान् न जानातीति न वाच्यं, सूक्ष्मविषयज्ञानस्य स्थूलाववोधने सुघटत्वात्। द्रव्यावगाहक्षेत्रं तु जघन्यावधिविषयक्षेत्रादसंख्यातगुणहीनं भवति, तथाप्युत्सेधघनाङ्गुलासंख्यात

या आत्मांगुलकी अपेक्षा नहीं, क्योंकि सूक्ष्म निगोद लब्ध्यपर्याप्तककी जघन्य अवगाहन प्रमाण जघन्य देशावधिका क्षेत्र है। और परमागममें यह नियम कहा है कि शरीर, घ ग्राम, नगर आदिका प्रमाण उत्सेधांगुलसे ही मापा जाता है। इसलिये व्यवहार अंगुलका आश्रय लिया है। आगे 'अंगुलमावलियाए' आदि गाथासूत्रोंमें कहे गये काण्डकोंमें अंगुल प्रमाण प्रमाणांगुलसे लिया है। उससे आगे भी जो हस्त, गव्यूति, योजन भरत आदि प्रम क्षेत्र कहा है वह सब प्रमाणांगुलसे ही लिया है॥३८१॥

जघन्य अवधिज्ञानके क्षेत्रके मध्यमें स्थित पूर्वोक्त जघन्य द्रव्यको जघन्य देशाव ज्ञान जानता है। अर्थात् उस क्षेत्रके मध्यमें औदारिक शरीरके संचयको लोकसे भाग दे एक भाग प्रमाण जो असंख्यात खण्ड स्थित हैं उनको जानता है। उस जघन्य पु स्कन्धसे ऊपर एक-दो आदि अधिक प्रदेशवाले स्कन्धोंको वह नहीं जानता ऐसा नहीं क्योंकि जो ज्ञान सूक्ष्मको जानता है वह स्थूलको जाननेमें समर्थ होता है। द्र अवगाहनाका प्रमाण जघन्य अवधिके विषयभूत क्षेत्रके प्रमाणसे असंख्यात गु

१. ब, 'तत्खण्डसंख्यातखण्डानि वा°।

त्प्रमाणं जघन्यदेशावधिक्षेत्रमक्कु कारणदिदं व्यवहारांगुलमनाश्रयिसियें पेळल्पट्टुदु। तज्जघन्याव-गाहनमुं परमागमदोळ् देहगेहग्रामनगरादिप्रमाणमुत्सेधांगुलदिदमें येंदितु नियमितमप्पुदरिदं व्यवहारांगुलाश्रितमे यक्कुं। मेले यावुदोंदेडेयोळंगुलमावळिया एकभागमसंखेज्जमित्यादिगाथा सूत्रोक्तकांडकंगळोळ् अंगुलग्रहणमल्लि प्रमाणांगुलमे ग्राह्यमक्कुमुत्तरोत्तर निर्द्दिश्यमानहस्तगव्यूति-योजनभरतादिक्षेत्रंगळगे प्रमाणांगुलाश्रितत्वदिदं।

> अवरोहिखेत्तमज्झे अवरोही अवरदव्वमवगमइ।
> तद्दव्वस्सवगाहो उस्सेहासंखघणपदरो ॥३८२॥

अवरावधिक्षेत्रमध्ये अवरावधिरवरद्रव्यमवगच्छति। तद्द्रव्यस्यावगाहः उत्सेधासंख्य-घनप्रतरः।

जघन्यावधिक्षेत्रमध्यदोळिर्द्दतिर्द्द पूर्वोक्तजघन्यद्रव्यमं जघन्यदेशावधिज्ञानमरिगुं। तद् क्षेत्रमध्यदोळिर्द्दतिर्द्द असंख्यातंगळनौदारिकशरीरसंचयलोकभक्तैकभागप्रमितखंडंगळननितुमनरिगु-में बुदत्थं। तज्जघन्यपुद्गलस्कंधद मेले एकद्व्यादिप्रदेशोत्तरपुद्गलस्कंधंगळनरिगुमेंबुदनिल्लि पेळल्वेडेकें दोडे सूक्ष्मविषयज्ञानक्के स्थूलावबोधनदोळ् सुघटत्वमप्पुदरिदं। द्रव्यावगाहक्षेत्रं जघन्या-वधिविषयक्षेत्रमं नोडलसंख्येयगुणहीनमक्कुमादोडं उत्सेधघनांगुलासंख्यातभागमात्रमक्कुं। मदर

सूक्ष्मनिगोदलब्ध्यपर्याप्तकजघन्यावगाहनप्रमाणं जघन्यदेशावधिक्षेत्रं ततः कारणात्, देहगेहग्रामनगरादिप्रमाणं उत्सेधाङ्गुलेनैवेति परमागमे नियमितत्वात् व्यवहाराङ्गुलमेवाश्रितं भवति। उपरि यत्र "अङ्गुलमावलियाए भागमसंखेज्जदो वि संखेज्जो, इत्यादिगाथासूत्रोक्तकाण्डकेषु अङ्गुलग्रहणं तत्र प्रमाणाङ्गुलमेव ग्राह्यं, उत्तरोत्तर-निर्दिश्यमानहस्तगव्यूतियोजनभरतादिक्षेत्राणां प्रमाणाङ्गुलाश्रितत्वात् ॥३८१॥

जघन्यावधिक्षेत्रमध्ये स्थितं पूर्वोक्तं जघन्यद्रव्यं जघन्यदेशावधिज्ञानं जानाति तत्क्षेत्रमध्यस्थितानि औदारिकशरीरसंचयस्य लोकविभक्तैकभागप्रमितखण्डानि असंख्यातानि[1] जानातीत्यर्थः। तज्जघन्यपुद्गलस्कन्ध-स्योपरि एकद्व्यादिप्रदेशोत्तरपुद्गलस्कन्धान् न जानातीति न वाच्यं, सूक्ष्मविषयज्ञानस्य स्थूलावबोधने सुघटत्वात्। द्रव्यावगाहक्षेत्रं तु जघन्यावधिविषयक्षेत्रादसंख्यातगुणहीनं भवति, तथाप्युत्सेधघनाङ्गुलासंख्यात-

या आत्मांगुलकी अपेक्षा नहीं, क्योंकि सूक्ष्म निगोद लब्ध्यपर्याप्तककी जघन्य अवगाहना प्रमाण जघन्य देशावधिका क्षेत्र है। और परमागममें यह नियम कहा है कि शरीर, घर, ग्राम, नगर आदिका प्रमाण उत्सेधांगुलसे ही मापा जाता है। इसलिये व्यवहार अंगुलका ही आश्रय लिया है। आगे 'अंगुलमालियाए' आदि गाथासूत्रोंमें कहे गये काण्डकोंमें अंगुलका प्रमाण प्रमाणांगुलसे लिया है। उससे आगे भी जो हस्त, गव्यूति, योजन भरत आदि प्रमाण क्षेत्र कहा है वह सब प्रमाणांगुलसे ही लिया है ॥३८१॥

जघन्य अवधिज्ञानके क्षेत्रके मध्यमें स्थित पूर्वोक्त जघन्य द्रव्यको जघन्य देशावधि-ज्ञान जानता है। अर्थात् उस क्षेत्रके मध्यमें औदारिक शरीरके संचयको लोकसे भाग देनेपर एक भाग प्रमाण जो असंख्यात खण्ड स्थित हैं उनको जानता है। उस जघन्य पुद्गल स्कन्धसे ऊपर एक-दो आदि अधिक प्रदेशवाले स्कन्धोंको वह नहीं जानता ऐसा नहीं है। क्योंकि जो ज्ञान सूक्ष्मको जानता है वह स्थूलको जाननेमें समर्थ होता है। द्रव्यकी अवगाहनाका प्रमाण जघन्य अवधिके विषयभूत क्षेत्रके प्रमाणसे असंख्यात गुणाहीन

1. ब. 'ख्यसंख्यातखण्डानि जा°।

अवरद्व्वादुवरिमदव्ववियप्पाय होदि धुवहारो ।
सिद्धाणंतिमभागो अभव्वसिद्धादणंतगुणो ॥३८४॥

अवरद्रव्यादुपरितनद्रव्यविकल्पाय भवति ध्रुवहारः। सिद्धानंतैकभागोऽभव्यसिद्धादनंतगुणः ॥

जघन्यदेशावधिज्ञानविषयद्रव्यविदं मेलणनंतरदेशावधिज्ञानविकल्पविषयद्रव्यविकल्पमं तरल्वेडि सिद्धानंतैकभागमुमभव्यसिद्धानंतगुणमुमप्प ध्रुवभागहारमरियल्पडुगुं ।

धुवहारकम्मवग्गणगुणगारं कम्मवग्गणं गुणिदे ।
समयपबद्धपमाणं जाणिज्जो ओहिविसयम्मि ॥३८५॥

ध्रुवहारकार्म्मणवर्ग्गणागुणकारं कार्म्मणवर्ग्गणां गुणिते। समयप्रबद्धप्रमाणं ज्ञातव्यमवधिविषये ॥

कार्म्मणवर्ग्गणाया गुणकाराः कार्म्मणवर्ग्गणागुणकाराः ध्रुवहाराश्चैते कार्म्मणवर्ग्गणागुणकाराश्च ध्रुवहारकार्म्मणवर्ग्गणागुणकारास्तान् । कार्म्मणवर्ग्गणां च गुणितेऽवधिविषये समयप्रबद्धप्रमाणं भवतीति ज्ञातव्यं । गुण्यरूपदिनिद्दं कार्म्मणवर्ग्गणेगे गुणकाररूपदिनिर्द्द ध्रुवहारंगळं कार्म्मणवर्ग्गणेयुमं गुणिसुत्तिरलु अवधिविषयसमयप्रबद्धप्रमाणमक्कुमेंदु ज्ञातव्यमक्कुं ।

जघन्यदेशावधिविषयद्रव्यात् उपरितनद्वितीयाद्यवधिज्ञानविकल्पविषयद्रव्याणि आनेतु सिद्धानन्तैकभागः, अभव्यसिद्धेभ्योऽनन्तगुणः ध्रुवभागहारः स्यात् ॥३८४॥

द्विरूपोनदेशावधिविकल्पमात्रध्रुवहाराद् गत्युत्पन्नेन कार्मणवर्गणागुणकारेण द्विरूपाधिकपरमावधिज्ञानविकल्पमात्रध्रुवहारसंवर्गसमुत्पन्नकार्मणवर्गणा गुणिता सती अवधिविषये समयप्रबद्धमात्रप्रमाणं स्यादिति

जघन्य देशावधि ज्ञानके विषयभूत द्रव्यसे ऊपर द्वितीय आदि अवधिज्ञानके भेदोंके विषयभूत द्रव्योंको लानेके लिए सिद्ध राशिका अनन्तवाँ भाग और अभव्य राशिसे अनन्तगुणा ध्रुवभागहार होता है ॥

विशेषार्थ—पूर्वपूर्व द्रव्यमें जिस भागहारका भाग देनेसे आगेके भेदके विषयभूत द्रव्यका प्रमाण आता है वह ध्रुव भागहार है। जैसे जघन्य देशावधिज्ञानके विषयभूत द्रव्यमें भाग देनेसे जो प्रमाण आता है वह उसके दूसरे भेदके विषयभूत द्रव्यका प्रमाण होता है ॥३८४॥

देशावधिज्ञानके विकल्पोंमें दो घटानेपर जितना प्रमाण रहे उतनी जगह ध्रुवहारोंको स्थापित करके परस्परमें गुणा करनेपर जितना प्रमाण होता है उतना कार्मण वर्गणाका गुणकार होता है। और परमावधिज्ञानके विकल्पोंमें दो अधिक करनेपर जितना प्रमाण हो उतनी जगह ध्रुवहारोंको स्थापित करके परस्परमें गुणा करनेपर जितना प्रमाण हो वह कार्मणवर्गणा होती है। कार्मणवर्गणाके गुणकारसे कार्मणवर्गणाको गुणा करनेपर जो प्रमाण हो वह अवधिज्ञानका विषय समयप्रबद्ध जानना। अर्थात् जो जघन्य देशावधिका विषय-

१. ध्रुवहारक्कें संदृष्टि मर्गांकं वक्ष्यमाणं मुंदे पेळल्पडुगुमीग पेळ्वुदेकेंदोडे देशावधिय चरमद्रव्याविकल्पंगळं विरलु विवरमदोळोंदागि प्रथमविकल्पपर्यंतमेकारूपेकोत्तरक्रमदिनिळिदिळिदु बंदु प्रथमविकल्पदोळ्, तावन्मात्रध्रुवहारंगळि कार्मणवर्ग्गणेयं गुणियिसिद लब्धप्रमाणसमानं प्रथमद्रव्यमें बुदत्थं ॥

जघन्यमनोद्रव्यवर्गणाप्रमाणमनंत मदर । ज । अनंतैकभागदिनधिकमुत्कृष्टमनोद्रव्यवर्गणाप्रमाणमक्कु ज ख / ख मितु मुंपेळ्द क्रमदिंदमादियंते सुद्धे इत्यादिविधानदिदं तरल्पट्टु मनोद्रव्यवर्गणाविकल्पंगळ ज / ख १ अनंतैकभागदोडने ज / ख ख १ अवधिविषयद्रव्यविकल्पंगळोळु पुगुव ध्रुवहारप्रमाणं समानमें दु निश्चयिसुवुदु ॥ अथवा :—

धुवहारस्स पमाणं सिद्धाणंतिमपमाणमेत्तं पि ।
समयपबद्धणिमित्तं कम्मणवग्गणगुणादो दु ॥३८८॥

ध्रुवहारस्य प्रमाणं सिद्धानंतैकभागप्रमाणमात्रमपि । समयप्रबद्धनिमित्तं कार्म्मणवर्गणागुणात् ॥

होदि अणंतिमभागो तग्गुणगारोवि देसओहिस्स ।
दोऊणदव्वभेदपमाणं धुवहारसंवग्गो ॥३८९॥

भवत्यनंतैकभागस्तद्गुणकारोपि देशावधेर्द्विरूपोनद्रव्यभेदप्रमाणध्रुवहारसंवर्गः ॥

ध्रुवहारप्रमाणं सिद्धानंतैकभागप्रमाणमात्रमादोडमवधिविषयसमयप्रबद्धनिश्चयनिमित्तं कार्म्मणवर्गणागुणकारमं नोडलु मत्ते अनंतैकभागमक्कुमा कार्म्मणवर्गणागुणकारमुं देशावधिज्ञानद्विरूपोनद्रव्यविकल्पप्रमितध्रुवहारंगळ संवर्गमक्कुमा देशावधिज्ञानद्रव्यविकल्पंगळेनितें दोडे पेळल्पडुगु ।

देशावधिद्रव्यविकल्परचनेयोळु द्विचरमदेशावधिद्रव्यविकल्पदोळु गुण्यरूपकार्म्मणवर्गणेगे

मनोद्रव्यवर्गणाजघन्यं अनन्तो भवति । तदनन्तैकभागेनाधिकमुत्कृष्टं भवति इत्येवमुक्तरीत्या मनोद्रव्यवर्गणाविकल्पानामनन्तैकभागः ज / ख ख अवधिविषयद्रव्यविकल्पेषु ध्रुवहारप्रमाणं ज्ञातव्यम् । अथवा—

ध्रुवहारप्रमाणं सिद्धानन्तैकभागमात्रमपि अवधिविषयसमयप्रबद्धप्रमाणमानेतुं उक्तस्य कार्मणवर्गणागुणकारस्य अनन्तैकभागमात्रं स्यात् । स च गुणकारोऽपि कियान् ? देशावधिज्ञानस्य द्विरूपोनद्रव्यभेदमात्र-

मनोवर्गणाका जघन्य भेद अनन्त प्रमाण है। अर्थात् अनन्त परमाणुओंके स्कन्धरूप जघन्य मनोवर्गणा है। उसमें अनन्तका भाग देनेसे जो प्रमाण आवे उसे उस जघन्य भेदमें जोड़नेपर वर्गणाके उत्कृष्ट भेदका प्रमाण होता है। इस प्रकार मनोद्रव्य वर्गणाके विकल्पोंके अनन्तवें भाग अवधिज्ञानके विषयभूत द्रव्योंके विकल्पोंमें ध्रुवहारका प्रमाण है ॥३८७॥

यद्यपि ध्रुवहारका प्रमाण सिद्ध राशिके अनन्तवें भाग है किन्तु अवधिज्ञानके विषयभूत समयप्रबद्धका प्रमाण लानेके लिए पहले कहे कार्मणवर्गणाके गुणकारका अनन्तवाँ भाग है। और यह गुणकार देशावधिज्ञानके द्रव्यकी अपेक्षा भेदोंमें दो घटाकर जो प्रमाण शेष रहे उतनी जगह ध्रुवहारोंको रखकर परस्परमें गुणा करनेसे जो प्रमाण हो उतना है। इतना प्रमाण कैसे कहा, सो कहते हैं—देशावधिज्ञानके विषयभूत द्रव्यकी रचनामें उत्कृष्ट

संचयलोकविभक्तैकखंडप्रमाणमेयक्कुमेंदु निरूपिसुवुदु स ० १२—१६ ल (≡) इन्तु देशावधिविषयसर्व्वद्रव्यविकल्पंगळेनितें दोडे पेळ्दपं :—

अंगुल असंखगुणिदा खेत्तवियप्पा य दव्वभेदा हु।
खेत्तवियप्पा अवरुक्कस्सविसेसं हवे एत्थ ॥३९०॥

अंगुलासंख्यातगुणिताः क्षेत्रविकल्पाश्च द्रव्यभेदाः खलु। क्षेत्रविकल्पा अवरोत्कृष्टविशेषो भवेदत्र।

सूच्यंगुलासंख्यातैकभागगुणितक्षेत्रविकल्पंगळु देशावधिज्ञानविषयसर्व्वद्रव्यभेदंगळप्पुवु। खलु स्फुटमागि। अंतादोडा क्षेत्रविकल्पंगळ्तामेनितें दोडे अत्र इल्लि अवधिविषयदोळु क्षेत्रविकल्पाः क्षेत्रविकल्पंगळु अवरोत्कृष्टविशेषो भवेत्। जघन्यदेशावधिज्ञानविषय सूक्ष्मनिगोदलब्ध्यपर्य्याप्तक-जघन्यावगाहप्रमितजघन्यक्षेत्रमनिद ६।८।२२ (०) प १९।८९।८।२२।७९ (० ० ०) मपवर्त्तितमं घनांगुलासंख्यातैकभागमात्रम ६/प/० नुत्कृष्टदेशावधिज्ञानविषयक्षेत्रंलोकप्रमित ≡ मवरोत्कृष्टदोळु कळेदुळिदुदेनितोळ्यनितेयप्पुवु ≡ ६/प/■ इदं सूच्यंगुलासंख्यातदिदं गुणिसिलब्धराशियोळेकरूपं कूडुत्तिरलु देशावधिद्रव्यविकल्पंगळप्पुवु ≡ – ६/प/० । २/० एकें दोडे देशावधि जघन्यद्रव्य विकल्पं मोदल्गों डु ध्रुवहारभक्तै-

---

स्यात्।—स ० १२—१६ ल (≡) ३।८ ॥३८९॥ देशावधिद्रव्यविकल्पान् प्रमाणयति—

सूच्यंगुलासंख्यातैकभागगुणितदेशावधिविषयसर्वक्षेत्रविकल्पाः खलु तद्विषयद्रव्यविकल्पा भवन्ति, ते च क्षेत्रविकल्पाः अत्र देशावधिविषये अवरे जघन्यक्षेत्रे ६/प/० तद्विषयोत्कृष्टक्षेत्रे ≡ विशोधिते शेषमात्रा भवन्ति ≡ – ६/प/०

विषयभूत द्रव्यका प्रमाण है जो लोकसे भाजित नोकर्म औदारिक शरीरका संचय प्रमाण है।

विशेषार्थ—यहाँ उत्कृष्ट भेदसे लेकर जघन्य भेद पर्यन्त रचना कही है इससे इस प्रकार गुणकारका प्रमाण कहा है। यदि जघन्यसे लेकर उत्कृष्ट भेदपर्यन्त रचनाकी जावे तो क्रमसे ध्रुवहारका भाग देते जाइए। अन्तिम भेदमें कार्मणवर्गणाको एक बार ध्रुवहारसे भाग देनेपर द्रव्यका प्रमाण आ जाता है ॥३८८-३८९॥

अब देशावधिके द्रव्यकी अपेक्षा विकल्प कहते हैं—

देशावधिके विषयभूत क्षेत्रकी अपेक्षा जितने विकल्प हैं उनको सूच्यंगुलके असंख्यातवें भागसे गुणा करनेपर देशावधिके विषयभूत द्रव्यकी अपेक्षा भेद होते हैं।

द्रव्यविकल्पंगळल्लु द्विरूपहीनद्रव्यविकल्पमात्रध्रुवहारसंवर्गमे वर्गणागुणकारमें बल्लि येळु मावें टक्के प्रसंगमक्कुमंतुमल्लवेयुं रूपयुतमल्लद क्षेत्रविकल्पमं । ४ । कांडकदिदं गुणिसि लब्धदोळेक-रूपं कूडिदोडे । ४ । २ । अदु देशावधिद्रव्यविकल्पप्रमाणमल्तु । द्विरूपोनद्रव्यविकल्पमात्र ध्रुवहार-संवर्गमे वर्गणागुणकारमें बल्लि एळुमादारक्के प्रसंगमक्कुमप्पुदरिदमन्तुमल्तु वृथ्यविरोधमुमागम-विरोधमुमप्पुदरिदं रूपयुतमल्लद क्षेत्रविकल्पमं कांडकदिदं गुणिसि लब्धदोळोंदु रूपं कूडिदोडे देशावधिद्रव्यविकल्पमों भक्तेयप्पुविदुनिर्व्याधबोधविषयमक्कुं । अंतादोडा जघन्योत्कृष्टदेशावधिज्ञान-विषयजघन्योत्कृष्टक्षेत्रविकल्पंगळावुवें वोडे पेळ्दपं ।

अंगुलअसंखभागं अवरं उक्कस्सयं हवे लोगो ।
इदि वग्गणगुणगारो असंख धुवहारसंवग्गो ॥३९१॥

अंगुलासंख्यातभागोऽवरः उत्कृष्टो भवेल्लोकः । इतिवर्गणागुणकारोऽसंख्यध्रुवहारसंवर्गः । अंगुलासंख्यातभागः मुंपेळ्द घनांगुलासंख्यातैकभागमप्प लब्ध्यपर्याप्तकजघन्यावगाहप्रमाणमे अवरः जघन्यक्षेत्रविकल्पप्रमाणमक्कुमुत्कृष्टो भवेल्लोकः । उत्कृष्टक्षेत्रविकल्पं संपूर्णलोकप्रमाण-मक्कु–। मितु वर्गणागुणकारमसंख्य ध्रुवहारसंवर्गप्रमितमक्कुं । द्विरूपोनदेशावधिज्ञानविषयसर्व-द्रव्यविकल्प प्रमित ध्रुवहारसंवर्गजनितलब्धप्रमितं वर्गणागुणकारप्रमाणमें बुदर्थं ।

वर्धते अनेन क्रमेण लोकमात्रक्षेत्रोत्पत्तिपर्यन्तं गमनिकासद्भावात् अवशिष्टप्रथमद्रव्यविकल्पस्य पश्चात्प्रक्षेपात् ॥३९०॥ ते जघन्योत्कृष्टक्षेत्रे संख्याति—

अवरं जघन्यदेशावधिविषयक्षेत्रं सूक्ष्मनिगोदलब्ध्यपर्याप्तकजघन्यावगाहप्रमाणमिदं-

६ । ८ । २२
    a   १–
प १९ । ८ । ९ । ८ । २२ । ९ । ९
a   a   a

अपवर्तितं घनाङ्गुलासंख्यातभागमात्रं भवति ६/प/a उत्कृष्टं लोकः जगच्छ्रेणिघनो भवति इत्येवं द्विरूपोनदेशावधि-सर्वद्रव्यविकल्पमात्रासंख्यध्रुवहारसंवर्ग एव कार्मणवर्गणागुणकारः स्यात् ॥३९१॥ अथ क्रमप्राप्तं वर्गणा-प्रमाणमाह—

भाग द्रव्यके विकल्प होने तक क्षेत्र एक प्रदेश अधिक उतना ही रहता है। उसके पश्चात् क्षेत्रमें पुनः एक प्रदेश बढ़ता है। इस तरह प्रत्येक सूच्यंगुलके असंख्यातवें भाग द्रव्यके विकल्प होनेपर क्षेत्रमें एक-एक प्रदेशकी वृद्धि उत्कृष्ट क्षेत्र लोक पर्यन्त प्राप्त होने तक होती है। इसीसे क्षेत्रकी अपेक्षा विकल्पोंको सूच्यंगुलके असंख्यातवें भागसे गुणा करनेपर द्रव्यकी अपेक्षा विकल्प कहे हैं। इनमें पहला द्रव्यका भेद पीछेसे मिलाया वह अवशेष था अतः एकको मिलाना कहा ॥३९०॥

अब देशावधिके घन जघन्य और उत्कृष्ट क्षेत्रोंको कहते हैं—

जघन्य देशावधिका विषयभूत क्षेत्र सूक्ष्म निगोद लब्ध्यपर्याप्तककी जघन्य अवगाहना प्रमाण घनांगुलका असंख्यातवें भाग मात्र होता है। उत्कृष्ट क्षेत्र जगत् श्रेणिका घनरूप लोक-प्रमाण है। इस प्रकार देशावधिके समस्त द्रव्यकी अपेक्षा विकल्पोंमें दो कम करके

वगाहभिदु ६।८।८ आदी अंते सुद्धे इत्यादि सूत्राभिप्रायदिदं तरल्पट्टराशियिन्तयाव-
 ८
प ६ ८ ८।१९
ə ८

गाहविकल्पंगळिनितप्पुवु ६ ८ ई तेजस्कायिक सर्व्वावगाहनविकल्पराशियिदं गुणिसुतिरलु-
प
८

दों दु लब्धं तल्लब्धमात्रं परमावधिज्ञानविकल्पंगळप्पुवु = ६ ८ ई परमावधिज्ञानविकल्पराशियं
प
८

द्विरूपयुक्तं माडि विरलिसि प्रतिरूपं ध्रुवहारमनित्तु वर्गितसंवर्गं माडुतिरलु आवुदों दु लब्धमदु
५ कार्म्मणवर्गणाराशियक्कुं। व। इदि इंतु ध्रुवहारप्रमाणमुं वर्गणागुणकारप्रमाणमुं वर्गणाप्रमाणमुं व्यक्तमागि मूरुं राशिगळुं पेळल्पट्टुववं नीनु जानीहि अरिवें दु शिष्यसंबोधनं माडल्पट्टुदु।

देसोहि अवरदव्वं धुवहारेणवहिदे हवे बिदियं।
तदियादिवियप्पेसु वि असंखवारोत्ति एस कमो ॥३९४॥

देशावधेरवरद्रव्यं ध्रुवहारेणापहृते भवेद्द्वितीयं। तृतीयादिविकल्पेष्वपि असंख्यवारपर्यंत-
१० मेष क्रमः॥

देशावधिज्ञानविषयजघन्यद्रव्यमं स ə १२।१६ ख ध्रुवभागहारदिदं भागिसिदेक-
≡

भागं देशावधिज्ञानविषयद्वितीयद्रव्यविकल्पमक्कुं स ० ə १२।१६ ख तृतीयविकल्पंगळोळमो
≡ ९

तदुत्कृष्टे ६।८।८ विशोध्य शेषमपवर्त्य ६।ə एकरूपे निक्षिप्ते एतावन्तः ६।ə। इत्येवं
 ८ प प
▪ ६।८ ८।१९ ८ ८
ə ८

ध्रुवहारप्रमाणं वर्गणागुणकारप्रमाणं वर्गणाप्रमाणं च जानीहि ॥३९३॥

१५ मत्प्रागुक्तं देशावधिज्ञानविषयजघन्यद्रव्यं–स ə १२–१६ ख। ध्रुवहारेण एकेन भक्तं द्वितीयदेशावधि-
≡

को अग्निकायिककी उत्कृष्ट अवगाहनाके प्रमाणमें-से घटाकर जो शेष बचे उसमें एक जोड़नेपर अग्निकायकी अवगाहनाके भेद होते हैं। इस प्रकार ध्रुवहारका प्रमाण, वर्गणाके गुणकारका प्रमाण और वर्गणाका प्रमाण जानना ॥३९३॥

जो देशावधिज्ञानका विषय जघन्य द्रव्य पहले कहा था, उसको ध्रुवहारसे एक बार
२० भाग देनेपर देशावधिके दूसरे भेदका विषयभूत द्रव्य होता है। इसी प्रकार ध्रुवहारका

[illegible] मनोवर्गणेगें मुक्तारारिदं भागिसुत्त पोगलु केवलं [illegible] [illegible] कार्म्मणसमयप्रबद्धं मुक्तारक्के [illegible] मनोवर्गणेगें [illegible] ।

[illegible] विमज्जे [illegible] वग्गणयं ।

[illegible] भजिदं तु ॥२९८॥

[illegible] । परमे कार्म्मणस्य [illegible] तु ।
[illegible] भागाहार पुगुलं पोगलु [illegible] कार्म्मणवर्गणेयं तु मते एकवार भक्तां ओंदु यदि [illegible] प्रत्ययमापि [illegible] ।

[illegible] गेलम्मि ।

[illegible] ॥२९९॥

[illegible] । एकाकाशप्रदेशो वर्द्धते संपूर्णलोकपर्यंत । [illegible] ओंदरोळेकाकाशप्रदेश [illegible] संपूर्ण [illegible] ।

[illegible] क्रमेण समयेण ।

[illegible] ॥३००॥

[illegible] क्रमेण समयेण [illegible] । [illegible] समयोनं

डकदोळे जघन्यकालमिदु ८/a तत्कांडकोत्कृष्टकालमिदु ८/१ आदियनंतदोळ्कळे दोडे शेषं तत्कांडकदोळु जघन्यकालद मेले पेर्च्चिद समयंगळ प्रमाणमप्पुदु ८ a १ / १ a ई कालविशेषदिदं क्षेत्रविशेषमं भागिसुत्तुदेके दोडे जघन्यकालद मेले इनितु समयंगळु पेर्च्चिदागळा जघन्यक्षेत्रद मेलेनितु प्रदेशंगळु पेर्च्चिद योंदु समयं पेर्च्चिदागळेनितु प्रदेशंगळु पेर्च्चुगुमें दितु त्रैराशिकं माडि प्र काल ८ a १ / १ a फलप्रदेश ६ a ७ / ७ a इच्छाकालसमय १ लब्धक्षेत्रप्रदेशंगळु ६/८ इंतावलिभक्तघनांगुलप्रमितक्षेत्रविकल्पंगळु ध्रुववृद्धियिदं नडेदु नडेदोंदोंदु समयवृद्धियागुत्तं पोगि प्रथमकांडकचरमविकल्पदोळु जघन्यकालद मेले पेर्च्चिद समयंगळिनितप्पुवु ८ a ७ / ७ a इवं तज्जघन्यकालदोळु कूडुवागळु समच्छेदं माडि ८ ७ / a ७ आवलिगावलियं तोरि संख्यातरूपुगळं कूडिदोडिदु ८ a / ७ a अत्रत्यासंख्यातभाज्यभागहारंगळं सरिगळिद शेषं संख्यातभक्तावलिप्रमितमक्कु ८/a मत्तमोंदु समयवृद्धियादागळु क्षेत्रदोळु आवलिभक्तघनांगुलप्रमितप्रदेशंगळु क्षेत्रदोळु पेर्च्चुत्तं विरलागळिनितु समयंगळु पेर्च्चिदल्लिगेनितु प्रदेशंगळु क्षेत्रदोळु पेर्च्चुववें दितु त्रैराशिकमं माडि प्र = का स १ । फ । = प्रदेश ६/८ इ = का स ८ a-७ / ▪ a लब्धक्षेत्रप्रदेशंगळु ६ a-७ / a ७ इवं जघन्यक्षेत्रदोळु कूडुवागळु संख्यातरूपुगळिदं समच्छेदं माडि ६ ७ / a ७ घनांगुलक्के घनांगुलमं तोरि संख्यातरूपुगळं कूडिदोडिदु ६ a / ७ a अत्रत्यासंख्यातभाज्यभागहारंगळनपवर्तिसिद शेषं संख्यातभक्तघनांगुलप्रमितं चरमक्षेत्रविकल्पमक्कुं ६/७

इन्तु ध्रुववृद्धि विशेषिं सर्वकांडकदोळं परिपाटिक्रमदरियल्पडुगुमिन्नु ध्रुववृद्धिविशेषदिर तत्प्रथमकांडकदोळु असंख्यं संख्यं भागं असंख्यवारं तु घनांगुलासंख्यातैकभागमात्रक्षेत्रप्रदेशंगळु जघन्यक्षेत्रद मेले पेर्च्चिदागळोंदोंदु समयं जघन्यकालद मेले पेर्च्चुगुमंते घनांगुलासंख्यातैकभागमात्रक्षेत्रप्रदेशंगळु पेर्च्चिदागळोंदुं समयं केळगण कालदमेले पेर्च्चुगुमितु ध्रुवाध्रुववृद्धिगळु क्षेत्रदोळु तद्योग्यासंख्यातवारंगळागुत्तं विरलु कालदोळु मुंपेळ्दिनितु समयंगळु ८ a-७ / ७ a

[illegible] असंख्यातवारं भवति । तु-पुनः, तत्र काण्डके अध्रुववृद्धिविषयायां तद्वृद्धि- [illegible] च स्यात् भाति तच्चरमासंख्यातवारं भवति ॥४०३॥

[illegible] ध्रुववृद्धिस्थाने अध्रुववृद्धिस्थाने वा जघन्यदेशावधिविषयक्षेत्रस्योपरि क्षेत्रे वर्धिते

[illegible] घटते घटते घनांगुलके असंख्यातवें भाग प्रदेश बढ़नेपर जघन्य देशावधिके विषयभूत कालमें एक समयकी वृद्धि होती है। इस प्रकार क्षेत्रमें इतनी वृद्धि होनेपर कालमें एक समयकी वृद्धि [illegible] होती है इसे ध्रुववृद्धि कहते हैं। और पूर्वोक्त प्रकारसे ही कभी

प्रथमादिकांडकंगळं पेळ्दपेनें बुदाचार्यन प्रतिज्ञेयक्कुं ।

अंगुलमावलियाए भागमसंखेज्जदो वि संखेज्जा ।
अंगुलमावलियंतो आवलियं चांगुलपुधत्तं ॥४०४॥

अंगुलमावल्योर्भागोऽसंख्येयतोपि संख्येयः । अंगुलमावल्यंतः आवलिकं चांगुलपृथक्त्वं ॥

प्रथमकांडकदोळु जघन्यक्षेत्र कालंगळु घनांगुलावळिगळ असंख्यातैकभागमात्रंगळिवं मेले संख्येयो भागः क्षेत्रमुं कालमुं यथासंख्यमागि घनांगुलसंख्येयभागमुमावळि संख्येयभागमुमक्कु ६ । ८ / १ । १

द्वितीयकांडकदोळु क्षेत्रं घनांगुलमक्कुं कालमावल्यंतमेयक्कुं । किंचिदूनावलि यें बुदत्थं । ६ । ८–।
तृतीयकांडकदोळु आवलिरंगुलपृथक्त्वं घनांगुलपृथक्त्वमुमावलियमक्कुं । पृथक्त्व । ६८ ।

आवलियपुधत्तं पुण हत्थं तह गाउयं मुहूत्तं तु ।
जोयणभिण्णमुहुत्तं दिवसंतो पण्णुवीसं तु ॥४०५॥

आवलिपृथक्त्वं पुनर्हस्तस्तथा गव्यूतिर्म्मुहूर्त्तस्तु । योजनं भिन्नमुहूर्त्तः दिवसांतः पंचविंशतिस्तु ॥

चतुर्त्थकांडकदोळु पृथक्त्वावलियुमेकहस्तमुमक्कुं । हस्त १ । ८ । पृ । पंचमकांडकदोळु तथा गव्यूतिर्म्मुहूर्त्तांतः एकक्रोशमुमंतर्म्मुहूर्त्तमुमक्कुं । क्रो १ । का २ १– । षष्ठकांडकदोळु योजनंभिन्नमुहूर्त्तः एकयोजनमुं भिन्नमुहूर्त्तमुमक्कुं । यो १ । का = भिन्नमु १ ॥ सप्तमकांडकदोळु दिवसांतः पंचविंशतिस्तु किंचिदूनदिवसमुं पंचविंशतियोजनंगळुमक्कुं । यो २५ का = दि १ ।

विंशतिकाण्डकानि वक्ष्ये इत्याचार्यप्रतिज्ञा ॥४०३॥

प्रथमकाण्डके क्षेत्रकालौ जघन्यौ घनाङ्गुलावल्योरसंख्यातैकभागौ ६ । ८ / a a उत्कृष्टौ तयोः संख्येयभागौ ६ । ८ / १ । १ द्वितीयकाण्डके क्षेत्रं घनाङ्गुलम् । कालः आवल्यन्तः-किंचिदूनावलिरित्यर्थः ६ । ८– । तृतीयकाण्डके क्षेत्रं घनाङ्गुलपृथक्त्वं कालः आवलिपृथक्त्वं पृ ६ । ८ ॥४०४॥

चतुर्थकाण्डके कालः आवलिपृथक्त्वं । क्षेत्रं एकहस्तः । ह १ । ८ पृ । पञ्चमकाण्डके क्षेत्रं एकक्रोशः । कालः अन्तर्मुहूर्तः । क्रो १ । का २ १ । षष्ठकाण्डके क्षेत्रमेकयोजनं, कालः भिन्नमुहूर्तः । यो १ का भिन्न मु० १– । सप्तमकाण्डके कालः किंचिदूनदिवसः क्षेत्रं पञ्चविंशतियोजनानि यो २५ का दि १– ॥४०५॥

के अन्तिम भेदमें कालका प्रमाण होता है । आगे क्षेत्र और कालको लेकर उन्नीस काण्डक कहेंगे ऐसी प्रतिज्ञा आचार्यने की है ॥४०३॥

प्रथम काण्डकमें जघन्य क्षेत्र घनांगुलके असंख्यातवें भाग और जघन्य काल आवलीका असंख्यातवाँ भाग है । उत्कृष्ट क्षेत्र घनांगुलका संख्यातवाँ भाग और उत्कृष्ट काल आवलीका संख्यातवाँ भाग है । द्वितीयकाण्डकमें क्षेत्र घनांगुल प्रमाण और काल कुछ कम आवली है । तीसरे काण्डकमें क्षेत्र घनांगुल पृथक्त्व प्रमाण है और काल आवली पृथक्त्व प्रमाण है ॥४०४॥

चतुर्थ काण्डकमें काल आवली पृथक्त्व और क्षेत्र एकहाथ प्रमाण है । पाँचवें काण्डकमें क्षेत्र एक कोस प्रमाण काल अन्तर्मुहूर्त है । छठे काण्डकमें क्षेत्र एक योजन और काल भिन्न मुहूर्त है । सप्तम काण्डकमें काल कुछ कम एक दिन और क्षेत्र पचीस योजन है ॥४०५॥

देशावधि संबंध			
य ९ य ९ य य ९ ९ ०	≡ ० ० ०	प १ ० ० ०	≡० ० ० ०
कार्म्मंसम कार्म्मंसम	० ० ० द्वीप ० ६	० ० ० ० वर्ष ० ६	० ० ० ०
० ० म न य म न य	० ० ० द्वीप ० ५	० ० ० ० वर्ष ० ५	० ० ० ०
० ० भाषा प भाषो प	० ० ० द्वीप ० ४	० ० ० वर्ष ० ४	० ० ० ०
० ० तैज वर्ग तैज वर्ग	० ० ० द्वीप ० ३	० ० ० वर्ष ० ३	० ० ० ०
० ० कार्म्मंण श कार्म्मंण श	० ० ० द्वीप ० २	० ० ० वर्ष ० २	० ० ० ०
० ० तैज०:शरीर तैजे: शरीर	० ० ० द्वीप स ७	० ० ० - वर्ष ० १	० ० ० ०
० ० ०	० ०	० ० ० वर्ष स ७	० ० ०
० ० ० ०	० ० ० रुचक	० ० ० वर्ष पृ	० ० ०
० ० ० ०	० ० ० मानसक्षे.४५	० ० ० वर्ष १	० ० ०
० ० ० ०	० ० ० जंबु द्वीप	० ० ० माग १	० ० ० ०
० ० ० ०	० ० ० भरत	० ० ० दिन १५	० ० ० ०
० ० ० ०	० ० ० यो २ ५	० ० ० दिन १	० ० ० ०
० ० ० ०	० ० ० यो १	० ० ० भिन्न १-	० ० ० ० ०
० ० ० ०	० ० ० कोश १	२१ घ १-	० ० ० ० ० ०
० ० ० ० ०	० ० ० दण्ड १	० ० पृ ८	० ० ० ० ० ० ०
० ० ० ० ०	० ० ० पृ ६	० ० ० ० ० ८	० ० ० ० ० ० ० ०
० ० ० ०	० ० ६	० ० ० ८	० ० ० ० ० ० ० ०

		०	०							०
		०	०							०
	०	६	८							०
	०	७	७	८	८	८	८			०
	०	०	०							
	०	०	०	०	०	०	०	०	०	
	०	०	०	८	८	८				
	०	०	०	०	०	०	०			
	०	०	०	८	८					
	—	०	०	०	०	०				
म ० १२	१६ ख	०	०	८						
≡ ९	—	६	८	०						
स ० १२ ≡	१६ ख	० ०	०							
द्रव्य	क्षेत्र	काल	भाव							

साधिसुवुदु । अध्रुववृद्धिरपि पुनरविरुद्धमिन्नकांडकं अध्रुववृद्धियुं तन्न विवक्षितकांडकदोळ विरुद्धमागि ।

अंगुल असंखभागं संखं वा अंगुलं च तस्सेव ।
संखमसंखं एवं सेढीपदरस्स अद्धुवगे ॥४०९॥

अंगुलासंख्यातभागं संख्यं वा अंगुलं च तस्यैव । संख्यमसंख्यं एवं श्रेणीप्रतरस्या ध्रुवगे ॥

अध्रुववृद्धिविवक्षितमादोडे तत्कांडक क्षेत्रकालंगळ्गविरुद्धमागि घनांगुलासंख्यातैकभागमात्रमुं ६/a मेणु घनांगुल संख्यातैकभागमात्रमुं ६/१ मेणु घनांगुलमात्रमुं ६ संख्यातघनांगुलमात्रमुं ६१ । असंख्यातघनांगुलमात्रमुं । ६ a । एवं इंतु श्रेणिगं प्रतरक्कमरियल्पडुगुमदें तें दोडे श्रेण्यसंख्येयभागमात्रमुं श्रेणिय संख्येयभागममात्रमुं श्रेणिमात्रमुं, संख्यातश्रेणिमात्रमुं ॥—१॥ असंख्यात श्रेणिमात्रमुं ।—a । असंख्येयभागप्रतरमात्रमुं =/a प्रतरसंख्येयभागमात्रमुं =/१ प्रतरमात्रमु = संख्यातप्रतरमात्रमु = १ असंख्यातप्रतरमात्रमुं = a प्रदेशगळु पेच्चि पेच्चिकालदोळेकैक समयं पेर्च्चुगुमें दुध्रुववृद्धिक्रमं ।

कम्मइयवग्गणं धुवहारेणिगिवारभाजिदे दव्वं ।
उक्कस्सं खेत्तं पुण लोगो संपुण्णओ होदि ॥४१०॥

कार्म्मणवर्गणां ध्रुवहारेणैकवारभाजिते द्रव्यमुत्कृष्टं क्षेत्रं पुनर्लोकः संपूर्णो भवति ॥

अत्र च जघन्यकाले ८ समच्छेदेन ६ । १ । मिलिते प्रथमकाण्डकचरमे घनाङ्गुलसंख्येयभागो भवति ६/१ एवं सर्वकाण्डकेषु ध्रुववृद्धिं साधयेत् । अध्रुववृद्धिरपि विवक्षितकाण्डकेन तत्तत्क्षेत्रकालाविरोधेन वक्तव्या ॥४०८॥ तद्यथा—

घनाङ्गुलासंख्यातैकभागमात्राः ६/a वा घनाङ्गुलसंख्येयभागमात्राः ६/१ वा घनाङ्गुलमात्राः ६ वा संख्यातघनाङ्गुलमात्राः ६ १ वा असंख्यातघनाङ्गुलमात्रा ६ a एवं श्रेणीप्रतरयोरपि, तथाहि—श्रेण्यसंख्येयभागमात्राः [illegible] वा श्रेणिसंख्येयभागमात्राः १ वा श्रेणिमात्राः—वाः संख्यातश्रेणिमात्राः—१ वा असंख्यातश्रेणिमात्राः—a वा प्रतरासंख्येयमात्रा =/a वा प्रतरसंख्येयभागमात्राः =/१ वा संख्यातप्रतरमात्रा = १ [illegible] असंख्यातप्रतरमात्राः = a प्रदेशा वर्धित्वा वर्धित्वा काले एकैकसमयो वर्धते इत्यध्रुववृद्धिक्रमः ॥४०९॥

भागप्रमाण उत्कृष्टक्षेत्र प्रथमकाण्डकका होता है। इसी प्रकार सब काण्डकोंमें ध्रुववृद्धिका प्रमाण लाना चाहिए। अध्रुववृद्धि भी विवक्षित काण्डकमें उस-उस क्षेत्रकालका विरोध न करते हुए लानी चाहिए ॥४०८॥

वही कहते हैं—

घनांगुलके असंख्यातवें भागमात्र अथवा घनांगुलके संख्यातवें भागमात्र, अथवा घनांगुलमात्र, अथवा संख्यात घनांगुलमात्र, अथवा असंख्यात घनांगुलमात्र, अथवा श्रेणीके असंख्यातवें भागमात्र, अथवा श्रेणीके संख्यातवें भागमात्र, अथवा श्रेणिप्रमाण, अथवा संख्यात श्रेणिमात्र, अथवा असंख्यात श्रेणिमात्र, अथवा प्रतरके असंख्यातवें भाग, अथवा प्रतरके संख्यातवें भाग अथवा प्रतरमात्र अथवा संख्यात प्रतरमात्र अथवा असंख्यात प्रतरमात्र प्रदेश बढ़ा-बढ़ाकर कालमें एक-एक समय बढ़ता है। इस प्रकार अध्रुववृद्धिका क्रम है॥४०९॥

अनंतरं परमावधिज्ञान प्ररूपणमं पेळदपं :—

देसावहिवरदव्वं धुवहारेणवहिदे हवे णियमा ।
परमावहिस्स अवरं दव्वपमाणं तु जिणदिट्ठं ॥४१३॥

देशावधिवरद्रव्यं ध्रुवहारेणापहृते भवेन्नियमात् । परमावधेरवरद्रव्यप्रमाणं तु जिनदिष्टं ॥

सर्व्वोत्कृष्टदेशावधिज्ञानविषयोत्कृष्टद्रव्यमं पूर्व्वोक्त ध्रुवहारैकवार मक्तकार्म्मणवर्गणा-प्रमाणमं व ध्रुवहारदिदं भागिसुत्तिरलु व तु मत्ते परमावधिविषयजघन्यद्रव्यप्रमाणं नियमदिदं
९ ९९
मक्कुमेंदु जिनरिंदं पेळल्पट्टुदु । इन्ता परमावधियुत्कृष्टद्रव्यप्रमाणमं पेळदपं :—

परमावहिस्स भेदा सग ओगाहणवियप्पहदतेऊ ।
चरिमे हारपमाणं जेट्ठस्स य होदि दव्वं तु ॥४१४॥

परमावधेर्भेदाः स्वकायगाहनविकल्पहततेजसः । चरमे हारप्रमाणं ज्येष्ठस्य भवेत् द्रव्यं तु ॥

परमावधिज्ञानविकल्पंगळेनितप्पुवें दोडे स्वावगाहनविकल्पंगळिंदं गुणिसल्पट्ट तेजःस्कायिक-जीवंगळ संख्ये यावतावत्प्रमाणंगळप्पुवु ≡ ७ ६ ७ प ७ ई परमावधिज्ञानसर्व्वविकल्पंगळोळु सर्व्वोत्कृष्टचरमविकल्पदोळु तु मत्ते द्रव्यमुत्कृष्टपरमावधिगे ध्रुवहारप्रमाणमेयक्कुं ॥ ९ ॥

सव्वावहिस्स एक्को परमाणू होदि णिव्वियप्पो सो ।
गंगामहाणइस्स पवाहोव्व धुवो हवे हारो ॥४१५॥

सार्व्वावधेरेकः परमाणुः भवेन्निर्व्विकल्पः । सः गंगामहानद्याः प्रवाहवत् ध्रुवो भवेद्धारः ॥

देशावधेरुत्कृष्टद्रव्यमिदं व तु—पुनः ध्रुवहारेण भक्तं तदा व परमावधिविषयजघन्यद्रव्यं नियमेन भव-
९ ९९
तीति जिनैरुक्तं ॥४१३॥ इदानीं परमावधेरुत्कृष्टद्रव्यप्रमाणमाह—

परमावधिज्ञानविकल्पाः स्वावगाहनविकल्पगुणिततेजस्कायिकजीवसंख्या भवन्ति ≡ ७ ६ प ७ । ७ । तेषु सर्व्वोत्कृष्टचरमविकल्पेषु पुनः द्रव्यं ध्रुवहारप्रमाणमेव ९ भवेत् ॥४१४॥

अब परमावधिज्ञानका कथन करते हैं—

देशावधिके उत्कृष्ट द्रव्यको ध्रुवहारसे भाग देनेपर परमावधिके विषयभूत जघन्य द्रव्यका प्रमाण होता है ऐसा जिनदेवने कहा है ॥४१३॥

अब परमावधिके उत्कृष्ट द्रव्यका प्रमाण कहते हैं—

तेजस्कायिक जीवोंकी अवगाहनाके भेदोंसे तेजस्कायिक जीवोंकी संख्याको गुणा करनेपर जो प्रमाण आता है उतने परमावधिज्ञानके भेद हैं। उनमें-से सबसे उत्कृष्ट अन्तिम भेदके विषयभूत द्रव्य ध्रुवहार प्रमाण ही होता है। अर्थात् ध्रुवहारका जितना परिमाण है उतने परमाणुओंके समूहरूप सूक्ष्म स्कन्धको जानता है ॥४१४॥

आवलिअसंखभागा इच्छिदगच्छधणमाणमेत्ताओ ।
देसावहिस्स खेत्ते काले वि य होंति संवग्गे ।।४१७।

आवल्यसंख्यभागा ईप्सितगच्छधनमानमात्राः । देशावधेः क्षेत्रे कालेऽपि च भवंति संवर्गे ॥

परमावधिज्ञानविषयंगळप्प क्षेत्रकालंगळु तंतम्म जघन्यं मोदल्गोंडु असंख्यातगुणित-क्रमदिदं परमावधिज्ञानसर्व्वोत्कृष्टपर्य्यंतमविच्छिन्नरूपदिदं नडेयवंतु नडेव क्षेत्रकालविकल्पंगळा-वेडेयोळु विवक्षितंगळप्पुवल्लि देशावधिज्ञानविषयोत्कृष्टक्षेत्रकालमात्रगुण्यंगळ्गे आवल्यसंख्यात-भागगुणकारंगळु तद्विवक्षितगच्छधनमानमात्रंगळु संवर्गंगळागुत्तिरलु तावन्मात्रासंख्यातगुणित-क्रमंगळेंदरियल्पडुववेंतेंदोडे परमावधिज्ञानप्रथमविकल्पदोळु आवल्यसंख्यातभागगुणकारंगळु तद्गच्छमोंदक्कर संकलितधनमात्रंगळु १२/२१ अप्पुवेंबल्लियोंदोंदे गुणकारमक्कु ≡८ प-१८/a a मंते विवक्षितद्वितीयविकल्पदोळु तद्गच्छसंकलनधनमानमात्रंगळप्पुवु २३/२१। मूरु मूरु गुणकारं-गळप्पुवु ≡a८८८/aaa । प-१८८८/aaa अंते विवक्षिततृतीयविकल्पदोळु तद्गच्छसंकलनघनमानमात्रंगळ-प्पुवु ३।४/२।१ घेंवारारप्पुवु ≡८८८८८८/aaaaaa । प-१८८८८८८/aaaaaa मी प्रकारदिदं विवक्षितचतुर्थविकल्प-दोळु तद्गच्छसंकलनधनमानमात्रंगळप्पुवु ४।५/२।१ वेंदु पत्तु पत्तु गुणकारंगळप्पुवु ≡८।१०/a प-१।८।१०/a मिते पंचमविकल्पदोळु तद्गच्छसंकलनधनमात्रंगळप्पु २६/२१ वेंदु

परमावधेर्विवक्षितक्षेत्रविकल्पे विवक्षितकालविकल्पे च तद्विकल्पस्य यावत्संकलितधनं तावत्प्रमाणमात्रा आवल्यसंख्येयभागाः परस्परं संवर्गे देशावधेरुत्कृष्टक्षेत्रे उत्कृष्टकालेऽपि च गुणकारा भवन्ति। ततस्ते गुणकाराः प्रथमविकल्पे एकः। द्वितीयविकल्पे त्रयः। तृतीयविकल्पे षट्। चतुर्थविकल्पे दश। पञ्चमविकल्पे पञ्चदश एवं

परमावधिके विवक्षित क्षेत्र और विवक्षित कालके भेदमें उस भेदका जितना संकलित धन हो, उतने प्रमाण आवलीके असंख्यातवें भागोंको परस्परमें गुणा करनेपर जो प्रमाण आवे उतना देशावधिके उत्कृष्ट क्षेत्र और उत्कृष्ट कालमें गुणकार होते हैं। वे गुणकार प्रथम भेदमें एक, दूसरे भेदमें तीन, तीसरे भेदमें छह, चतुर्थ भेदमें दस, पंचम भेदमें पन्द्रह इस प्रकार अन्तिम भेद पर्यन्त जानना।

विशेषार्थ—जिस नम्बरके भेदकी विवक्षा हो, एकसे लगाकर उस भेद पर्यन्तके एक-एक अधिक अंकोंको जोड़नेसे जो प्रमाण आवे उतना ही उसका संकलित धन होता है। जैसे प्रथम भेदमें एक ही अंक है अतः उसका संकलित धन एक जानना। दूसरे भेदमें एक और दोको जोड़नेपर संकलित धन तीन होता है। तीसरे भेदमें एक, दो तीनको जोड़नेसे संकलित धन छह होता है। चौथे भेदमें उसमें चार जोड़नेसे संकलित धन दस होता है। पाँचवें भेदमें पाँचका अंक और जोड़नेसे संकलित धन पन्द्रह होता है। सो पन्द्रह जगह आवलीके असंख्यातवें भागोंको रखकर परस्परमें गुणा करनेसे जो परिमाण हो वही पाँचवें भेदका गुणकार होता है। इस गुणकारसे उत्कृष्ट देशावधिके क्षेत्र लोकको गुणा करनेपर जो

गुणकारंगळप्पुवु ≡८ । १५ । प–१ । ८ । १५ । इंतेल्लेडेयोळं व्याप्तियरियल्पडुगुं ।
a ‍ ‍ ‍ a

परमावहिवरखेत्तेणवहिदउक्कस्स ओहिखेत्तं तु ।
सव्वावहिगुणगारो काले वि असंखलोगो दु ॥४१९॥

परमावधिवरक्षेत्रेणापहृतोत्कृष्टावधिक्षेत्रं तु । सर्वावधिगुणकारः कालेऽप्यसंख्यातलोकस्तु ।

परमावधिज्ञानविषयोत्कृष्टक्षेत्रप्रमाणदिदं अवधिनिबद्धोत्कृष्टक्षेत्रमं भागिसुतिरलावुदों दु लब्धमदु तु मत्ते सर्व्वावधिज्ञानविषयक्षेत्रगुणकारमक्कुमावगुण्यमावुदेंदोडे परमावधिज्ञानविषयसर्व्वोत्कृष्टक्षेत्रमक्कुमा गुण्यगुणकारंगळं गुणिसितिरलब्धं सर्व्वावधिज्ञानविषयक्षेत्रमक्कुमेंबुदत्थं । अंतादोडा अवधिनिबद्धोत्कृष्ट क्षेत्रप्रमाणमनितें दोडे ।

घणलोगगुणसलागा वग्गट्ठाणा कमेण छेदणया ।
तेजस्कायस्स ठिदी ओहिणिबद्धं च खेत्तं ॥
अज्झवसाणणिगोदसरीरे तेसु वि य कायट्ठिदी जोगा ।
अविभागपडिच्छेदो लोगेवग्गे असंखेज्जो ।

एंबी यागमप्रमाणदिदं घनघनाधारियोळ्पेळल्पट्ट अवधिनिबद्धोत्कृष्टमसंख्यातलोकसंवर्गसंजनितलब्धराशियक्कुमी राशियं परमावधिज्ञानविषयसर्व्वोत्कृष्टक्षेत्रदिदं भागिसुतिरलु ≡ ≡ a ≡ a ≡ a ≡ a ≡ a ≡ a लब्धं यावत्तावत्प्रमाणं ≡ a ≡ a गुणकारप्रमाणमक्कुमी
≡ ≡ a ≡ a ≡ a
गुणकारदिदं परमावधिज्ञानविषयसर्व्वोत्कृष्टक्षेत्रमं ≡ ≡ a ≡ a ≡ a गुणिसितोडे सर्व्वावधिज्ञानविषयक्षेत्रमक्कुमें बुदत्थं ≡ ≡ a ≡ a ≡ a ≡ a ≡ a । तु मत्ते

घनमात्राः पद. ते उभये मिलित्वा गच्छघनमात्रा दशगुणकारा भवन्ति । एवं सर्वविकल्पेषु ज्ञातव्यम् ॥४१८॥

उत्कृष्टावधिक्षेत्रं तावत् द्विरूपघनाघनधारायां लोकगुणकारशलाकावर्गशलाकार्धच्छेदशलाकाग्निजस्कायिकस्थित्यवधिनिबद्धोत्कृष्टक्षेत्राणां प्रत्येकमसंख्यातवर्गस्थानानि गत्वा गत्वोत्पन्नत्वात् पञ्चासंख्यातलोकगुणितलोकमात्रं तदेव परमावधिज्ञानविषयोत्कृष्टक्षेत्रप्रमाणेन भक्तं सत्—≡ । ≡ a ≡ a ≡ a ≡ a ≡ a सर्वाव-
≡ । ≡ a ≡ a ≡ a

उसके प्रमाणको गच्छ कहते हैं। जैसे विवक्षित भेद चौथा सो गच्छका प्रमाण चार हुआ। और तत्काल अतीत तीसरा भेद तीन, उसका गच्छ धन छह हुआ। पहला गच्छ चार और यह छह मिलकर दस होते हैं। इतना ही विवक्षित गच्छ चारका संकलित धन होता है। यही चतुर्थ भेदका गुणकार होता है। इसी प्रकार सब भेदोंमें जानना ॥४१८॥

उत्कृष्ट अवधिज्ञानका क्षेत्र कहते हैं। द्विरूपघनाघनधारामें लोक, गुणकारशलाका, वर्गशलाका, अर्धच्छेदशलाका, अग्निकायकी स्थितिका परिमाण और अवधिज्ञानके उत्कृष्ट क्षेत्रका परिमाण, ये स्थान असंख्यात-असंख्यात वर्गस्थान जानेपर उत्पन्न होते हैं। इसलिए पाँच बार असंख्यात लोक प्रमाण परिमाणसे लोकको गुणा करनेपर सर्वावधिज्ञानके विषयभूत उत्कृष्ट क्षेत्रका परिमाण आता है। उसमें उत्कृष्ट परमावधिज्ञानके विषयभूत क्षेत्रका भाग देनेपर जो परिमाण आवे वह सर्वावधिज्ञानके विषयभूत क्षेत्रका परिमाण लानेके लिए गुणकार होता है। इससे परमावधिज्ञानके विषयभूत उत्कृष्ट क्षेत्रको गुणा करनेपर सर्वावधिज्ञानके विषयभूत उत्कृष्ट क्षेत्रका परिमाण आता है। तथा सर्वावधिके

मारु ६। एतावन्मात्र गुणकारंगळप्पुवु ६४ । ६४ । ६४ । ६४ । ६४ । ६४ मिल्लि ईप्सित-
४ ४ ४ ४ ४ ४
राशिच्छेदं विवक्षितराशियदु बेसदछप्पणगनद्दर च्छेदराशियें दु ८। इवनु देयच्छेदैः देयमात्रल्यसं-
ख्यातन्दसंदृष्टि ६४ इवरद्धंच्छेदंगळेनितप्पुवें बोडे भज्जस्सद्धच्छेदा भाज्यवर्द्धच्छेदंगळाद ६।
४
हारद्धच्छेदणाहि परिहीणा हारदर्द्धच्छेदंगळिदं परिहीनंगळाडोडे । ६ । २ । नाल्कु । लद्धस्सद्धछेदा तल्लब्धराशियद्धंच्छेदशलाकेगळप्पुवप्पुवरिंदमो देयराशियर्द्धच्छेदंगळिदं भागंगोऽुत्तिरलु १ ८
६-२
लब्धं यावन्मात्रं २ तावन्मात्रदेयरासीणब्भासे देयराशिगळगन्योन्याभ्यासमागुत्तिरलु ६४ । ६४
४ ४
तन्न विवक्षितराशियप्प बेसद छप्पण्णं पुट्टुगुमित । पल्य । सूच्यंगुल । जगच्छ्रेणिलोकंगळीप्सित-राशिगळादोडं तत्तर्द्धच्छेदंगळना देयमप्पावल्यसंख्यातदर्द्धच्छेदंगळिदं भागिसि

पल्यच्छेद सूच्यंगुलच्छेद जगच्छ्रेणीच्छेद लोकच्छेद ततल्लब्धमात्रमावल्यसंख्यातंगल
छे छे छे वि वि छे छे ९
१६—४ १६—४ १६—छे छे ३ १ । ६—४
४

गुणिसुत्तिरलु तत्तत्पल्यसूच्यंगुल जगच्छ्रेणिलोकंगळुं पुट्टुगुमें दरियुतु ।

दिण्णच्छेदेणवहिदलोगच्छेदेण पदधणे भजिदे ।
लद्धमिदलोगगुणणं परमावहिचरमगुणगारो ॥४२१॥

देयच्छेदनापहृत लोकच्छेदेन पदधने भक्ते । लब्धमितलोकगुणनं परमावधिचरमगुणकारः।
देयच्छेदंगळिदं भागिसल्पट्ट लोकच्छेदंगळिदं ८ पदधने मुन्नं विवक्षित तृतीयपद
६—२
धनमं ३ । ४ भजिसे भागिसुत्तिरलु ३ । ४ पल्लब्धं तल्लब्धमपवर्तितं मूरु ३ । तावन्मात्र
२ । १ २ १ । ८
६—२

दैर्भक्तेषु—	पल्यच्छेद छे १६-४	सूच्यङ्गुलच्छेद छे छे १६-४	जगच्छ्रेणिच्छेद वि छे छे ३ १६-४	लोकच्छेद वि छे छे ९ १६-४	तत्र यल्लब्धं तत्सन्मात्रा-

ल्यसंख्येयभागानामभ्यासे कृते ते पल्यादीप्सितराशयः उत्पद्यन्ते ॥४२०॥

देयच्छेदभक्तलोकच्छेदैः ८ पदधने विवक्षिततृतीयपदस्य धने ३ । ४ भक्ते ३ । ४
६-२ २ । १ २ । १ । ८
६-२

२५६ उत्पन्न होती है। इसी प्रकार पल्य प्रमाण या सूच्यंगुल प्रमाण या जगतश्रेणी प्रमाण अथवा लोकप्रमाण जो भी इच्छित राशि हो उसके अर्धच्छेदोंमें देयराशि आवलीके असंख्यातवें भागके अर्धच्छेदोंसे भाग देनेपर जो प्रमाण आवे उसका एक-एकके रूपमें विरलन करके प्रत्येकके ऊपर आवलीका असंख्यातवाँ भाग रखकर परस्परमें गुणा करनेपर इच्छित राशि पल्य आदि उत्पन्न होती है ॥४२०॥

देयराशिके अर्धच्छेदोंका भाग लोकराशिके अर्धच्छेदोंमें देनेपर जो प्रमाण आवे

अनंतरं तिर्य्यग्मनुष्यगतिगळोळवधिविषयक्षेत्रमं पेळ्दपं ।

तिरिए अवरं ओघो तेजालंबे (तेजोयंते) होदि उक्कस्सं ।
मणुए ओघं देवे जहाकमं सुणुह वोच्छामि ॥४२५॥

तिर्य्यक्ष्ववरमोघः तेजोऽवलंबे च भवत्युत्कृष्टं । मनुजे ओघः देवे यथाक्रमं शृणुत वक्ष्यामि ॥

तिर्य्यग्गतिय तिर्य्यंचरोळु देशावधिज्ञान जघन्यमक्कुं । मेले तेजः शरीरपर्य्यंतं सामान्योक्त द्रव्यक्षेत्रकालभावंगळुत्कृष्टदिंदमल्लिपर्य्यंतं विषयमप्पुवु ।

मनुजरोळु देशावधिजघन्यं मोदल्गोंडु सर्व्वावधिज्ञानपर्य्यंतं सामान्योक्तसर्व्वमुमप्पुदु । देवगतियोळु देवक्कळगे यथाक्रमदिदं पेळ्वेवेकेळि :—

पणुवीसजोयणाइं दिवसंतं च य कुमारभोम्माणं ।
संखेज्जगुणं खेत्तं बहुगं कालं तु जोइसिगे ॥४२६॥

पंचविंशतिर्य्योजनानि दिवसस्यांतश्च कुमारभौमानां । संख्येयगुणं क्षेत्रं बहुकःकालस्तु ज्योतिष्के ॥

भावनरोळं व्यंतरोळं जघन्यदिदमिप्पत्तैदु योजनंगळुमोंदु दिनदोळगे विषयमक्कुं । ज्योतिष्करोळु भवनवासिव्यंतररुगळ जघन्यविषयक्षेत्रमं नोडलु संख्यातगुणितं क्षेत्रमक्कुं बहुकालमक्कुं ।

नरके योजनं संपूर्णं भवति ॥४२४॥ अथ तिर्यग्मनुष्यगत्योराह—

तिर्यग्जीवे देशावधिज्ञानं जघन्यादारभ्य उत्कृष्टतः तेजःशरीरविषयविकल्पपर्यन्तमेव सामान्योक्तद्रव्यादिविषयं भवति । मनुजे देशावधिजघन्यादारभ्य सर्वावधिज्ञानपर्यन्तं सामान्योक्तं सर्वं भवति ॥४२५॥ देवगतौ यथाक्रमं वक्ष्यामि शृणुत—

भावनव्यन्तरयोर्जघन्येन पञ्चविंशतियोजनानि किंचिदूनदिवसश्च विषयो भवति । ज्योतिष्के क्षेत्रं ततः संख्यातगुणं, कालस्तु बहुकः ॥४२६॥

पृथिवीमें आधा-आधा कोस बढ़ता जाता है। इस तरह प्रथम नरकमें सम्पूर्ण योजन क्षेत्र होता है ॥४२४॥

अब तिर्यंचगति और मनुष्यगतिमें कहते हैं—

तिर्यंचजीवमें देशावधिज्ञान जघन्यसे लेकर उत्कृष्टसे तैजसशरीर जिस भेदका विषय है उस भेद पर्यन्त होता है। सामान्य अवधिज्ञानके वर्णनमें जहाँ तक द्रव्यादि विषय जो कहे हैं वे सब होते हैं। मनुष्यमें देशावधिके जघन्यसे लेकर सर्वावधिज्ञान पर्यन्त जो सामान्य कथन किया है वह सब होता है। आगे यथाक्रम देवगति में कहूँगा। उसे सुनो ॥४२५॥

अब देवगतिमें कहते हैं—

भवनवासी और व्यन्तरोंमें अवधिज्ञानका विषयभूत क्षेत्र जघन्यसे पचीस योजन है और काल कुछ कम एक दिन है। तथा ज्योतिषी देवोंमें क्षेत्र तो इससे संख्यातगुणा है और काल बहुत है ॥४२६॥

षधिदर्शनविदं काण्वरं।

जघन्य	जघन्य	उ	उ
भवनव्यंतर	जोयिसि	असुर	अ ९।८गं।जो
यो २५	२५१	को ०	१०००।०
वि १	बहुकाल	य ०	य ० ९

सक्कीसाणा पढमं बिदियं तु सणक्कुमारमाहिंदा।
तदियं तु बम्ह लांतव सुक्कसहस्सारया तुरियं ॥४३०॥

शक्रेशानौ प्रथमां द्वितीयां तु सनत्कुमारमाहेंद्रौ। तृतीयां तु ब्रह्मलांतवौ शुक्रसहस्रारजौ तुर्य्यां॥

सौधर्म्मैशानकल्पजरुगळु प्रथमपृथ्वीपर्य्यंतं काण्वरु। सनत्कुमारमाहेंद्रकल्पसंभूतरु मत्ते द्वितीयपृथ्वीपर्य्यंतं काण्वरु। ब्रह्मलांतयकल्पजरु तृतीयपृथ्वीपर्य्यंतं काण्वरु। शुक्रशतारकल्पजरु चतुर्त्थपृथ्वीपर्य्यंतं काण्वरु।

आणदपाणदवासी आरण तह अच्चुदा य पस्संति।
पंचमखिदिपेरंतं छट्ठिं गेवेज्जगा देवा ॥४३१॥

आनतप्राणतवासिनः आरणास्तथाऽच्युताश्च पश्यंति पंचमक्षितिपर्य्यंतं षष्ठि ग्रैवेयका देवाः॥

आनतप्राणतवासिगळु आरणाच्युतकल्पजरुमंते पंचमक्षितिपर्य्यंतं काण्वरु। नवग्रैवेयकजहमिंद्ररु षष्ठपृथ्वीपर्य्यंतं काण्वरु।

सव्वं च लोयनालिं पस्संति अणुत्तरेसु जे देवा।
सक्खेत्ते य सकम्मे रूवगदमणंतभागं च ॥४३२॥

सर्वां च लोकनाडीं पश्यंत्यनुत्तरेषु ये देवाः। स्वक्षेत्रे स्वकर्म्मणि रूपगतमनंतभागं च॥

स्वकीयावस्थितस्थानादुपरि सुरगिरिशिखरपर्यन्तं अवधिदर्शनेन पश्यन्ति ॥४२९॥

सौधर्मैशानजाः प्रथमपृथ्वीपर्यन्तं पश्यन्ति। सनत्कुमारमाहेन्द्रजाः पुनर्द्वितीयपृथ्वीपर्यन्तं पश्यन्ति। ब्रह्मलान्तवजास्तृतीयपृथ्वीपर्यन्तं पश्यन्ति। शुक्रशतारजाः चतुर्थपृथ्वीपर्यन्तं पश्यन्ति ॥४३०॥

आनतप्राणतवासिनः तथा आरणाच्युतवासिनश्च पञ्चमपृथ्वीपर्यन्तं पश्यन्ति, नवग्रैवेयकजा देवाः षष्ठपृथ्वीपर्यन्तं पश्यन्ति ॥४३१॥

शिखरपर्यन्त अवधिदर्शनके द्वारा देखते हैं ॥४२९॥

सौधर्म और ऐशान स्वर्गोंके देव अवधिज्ञानके द्वारा प्रथम नरक पृथ्वीपर्यन्त देखते हैं। सनत्कुमार और माहेन्द्र स्वर्गोंके देव दूसरी पृथ्वीपर्यन्त देखते हैं। ब्रह्म ब्रह्मोत्तर और लान्तव-कापिष्ठ स्वर्गोंके देव तीसरी पृथ्वी पर्यन्त देखते हैं। शुक्र-महाशुक्र और शतार-सहस्रार स्वर्गोंके देव चतुर्थ पृथ्वीपर्यन्त देखते हैं ॥४३०॥

आनत-प्राणत तथा आरण-अच्युत स्वर्गोंके वासी देव पाँचवी पृथ्वीपर्यन्त देखते हैं तथा नौ ग्रैवेयकोंके देव छठी पृथ्वीपर्यन्त देखते हैं ॥४३१॥

स्वविषयक्षेत्रदोळु ओंदु प्रदेशमं तेगवोम्में ध्रुवहारदिंद भागिसुवुदु। स्वस्वावधिविषयक्षेत्रप्रदेशप्रमाणं परिसमाप्तियक्कुमन्नेवरमन्नेवरं ध्रुवहारदिंदं द्रव्यमं भागिसुत्तं भागिसुत्तिरलु तत्रतन चरमखंडं तत्रतनावधिज्ञानविषयद्रव्यप्रमाणमक्कुं। स्वस्वावधिविषयक्षेत्रप्रदेशप्रचयप्रमित ध्रुवहारंगळिंदं स्वस्वावधिज्ञानावरणद्रव्यमं विस्रसोपचयमं भागिसुत्तिरलु स्वस्वावधिज्ञानविषयद्रव्यमक्कुमेंबुदु तात्पर्यार्थं।

सोहम्मीसाणाणमसंखेज्जाओ हु वस्सकोडीओ।
उवरिमकप्पचउक्के पल्लासंखेज्जभागो दु ॥४३५॥

सौधर्मैशानानामसंख्येयाः खलु वर्षकोट्यः। उपरितनकल्पचतुष्के पल्यासंख्यातभागस्तु।

तत्तो लांतवकप्पप्पहुडी सव्वट्ठसिद्धिपेरंतं।
किंचूणपल्लमेत्तं कालपमाणं जहाजोग्गं ॥४३६॥

ततो लांतवकल्पप्रभृति सर्व्वार्थसिद्धिपर्य्यंतं। किंचिदूनपल्यमात्रं कालप्रमाणं यथायोग्यं।

सौधर्म्मैशानकल्पजर्ग्गवधिज्ञानविषयकालमसंख्यात वर्षकोटिगळप्पुवु। वर्ष को a। खलु स्फुटमागि। तु मते उपरितनकल्पचतुष्के सनत्कुमार-माहेंद्र-ब्रह्म-ब्रह्मोत्तर-कल्पचतुष्टयवासिदेवकर्कळगे कालं यथायोग्यमप्पपल्यासंख्यातभागमात्रमक्कु प/a मेले लांतवकल्पं मोदल्गोंडु सर्व्वार्थसिद्धिपर्य्यंतं कल्पजर्ग्गं कल्पातीतजर्ग्गं कालं यथायोग्यमप्प किंचिदूनपल्यप्रमाणमक्कुं।

तेषु एकप्रदेशमपनीय द्रव्यमेकवारं ध्रुवहारेण भजेत् यावत्स्वस्वावधिक्षेत्रप्रदेशप्रमाणं परिसमाप्यते तावत्। तत्रतनचरमखण्डं तत्रतनावधिज्ञानविषयद्रव्यप्रमाणं भवति। स्वस्वावधिविषयक्षेत्रप्रदेशप्रचयमितध्रुवहारभक्तं विविस्रसोपचयस्वस्वावधिज्ञानावरणद्रव्य स्वस्वावधिविषयद्रव्यं स्यादित्यर्थः ॥४३३-४३४॥

सौधर्मैशानजानामवधिविषयकालः असंख्यातवर्षकोटयः खलु वर्षको a। तु-पुनः, उपरितनकल्पचतुष्क-

---

और प्रदेशोंमें एक कम कर दें। इस तरह तबतक भाग दें जबतक सब प्रदेश समाप्त हों। अन्तिम भाग देनेपर जो सूक्ष्म पुद्गलस्कन्ध शेष रहे उतने प्रमाण पुद्गलस्कन्धको सौधर्म ऐशान स्वर्गका देव जानता है। इसी प्रकार सानत्कुमार माहेन्द्र स्वर्गके देवोंके घनरूप चार राजू प्रमाण क्षेत्रके प्रदेशोंका जितना प्रमाण है उतनी बार उनके अवधिज्ञानावरण द्रव्यमें ध्रुवहारका भाग देते-देते जो प्रमाण रहे उतने परमाणुओंके स्कन्धको उनका अवधिज्ञान जानता है। ब्रह्म-ब्रह्मोत्तर स्वर्गके देवोंके साढ़े पाँच राजू, लान्तव-कापिष्ठवालोंके छह राजू, शुक्र-महाशुक्रवालोंके साढ़े सात राजू, शतार-सहस्रारवालोंके आठ राजू, आनत-प्राणतवालोंके साढ़े नौ राजू, आरण-अच्युतवालोंके दस राजू, ग्रैवेयकवालोंके ग्यारह राजू, अनुदिशवालोंके कुछ अधिक तेरह राजू, अनुत्तर विमानवालोंके कुछ कम चौदह राजू क्षेत्र-

पेळल्पट्टुदु। नरलोके तदुत्पत्तिप्रवृत्तिगळेरडुं मनुष्यक्षेत्रदोळेयक्कुं। मनुष्यक्षेत्रदिदं पोरगे मनःपर्य्यंयज्ञानक्कुत्पत्तियुं प्रवृत्तियुमिल्लें बुदत्थं।

परकीयमनसि व्यवस्थितोऽर्थः मन इत्युच्यते। मनः पर्येति गच्छति जानातीति मनःपर्य्यंयः एंदितु परमनोगतार्त्थंग्राहकं मनःपर्य्यंयज्ञानमक्कुमा परमनोगतार्त्थंमुं चिंतितमचिंतितमर्द्धंचिंतितमें दितनेकभेदमप्पुददं मनुष्यक्षेत्रदोळु मनःपर्य्यंयज्ञानमरिगुमें बुदं तात्पर्य्यं।

मणपज्जवं च दुविहं उजुविउलमदित्ति उजुमदी तिविहा।
उजु मणवयणे काये गदत्थविसयत्ति णियमेण ॥४३९॥

मनः पर्य्यंयश्च द्विविधः ऋजुविपुलमती इति। ऋजुमतिस्त्रिविधः ऋजु मनोवचने काये गतार्त्थंविषय इति नियमेन।

सामान्यदिदं मनःपर्य्यंयज्ञानमोंदु अदं भेदिसिदोडे ऋजुमतिमनःपर्य्यंयमें दु विपुलमतिमनःपर्य्यंयमें दितु मनःपर्य्यंयज्ञानं द्विविधमक्कु—। मल्लि ऋज्वी ऋजुकायवाग्मनस्कृतार्त्थंस्य परकीयमनोगतस्य विज्ञानान्निर्व्वर्त्तिता निष्पन्ना मतिर्य्यस्य सः ऋजुमतिः स चासौ मनःपर्य्यंयश्च ऋजुमतिमनःपर्य्यंयः। विपुला कायवाग्मनस्कृतार्त्थंस्य परकीयमनोगतस्य विज्ञाना निर्व्वर्त्तिताऽनिर्व्वर्तिता कुटिला च मतिर्य्यस्य सः विपुलमतिः। स चासौ मनःपर्य्यंयश्च विपुलमतिमनःपर्य्यंयः। एंदितु निरुक्तिसिद्धंगळप्पुवल्लि ऋजुश्च विपुला च ऋजु विपुले। ते मती ययोस्तौ ऋजुविपुलमती। ऋजुमनोगतार्त्थंविषयमनःपर्य्यंयमें दु ऋजुवचनगतार्त्थंविषयमनःपर्य्यंयमें दुं ऋजुकायगतार्त्थंविषयमनःपर्य्यंयमुमें दितु ऋजुमतिमनःपर्य्यंयं नियम-

---

मनुष्यक्षेत्र एव न तद्बहिः। परकीयमनसि व्यवस्थितोऽर्थः मनः तत् पर्येति गच्छति जानातीति मनःपर्ययः ॥४३८॥

स मनःपर्ययः सामान्येनैकोऽपि भेदविवक्षया ऋजुमतिमनःपर्ययः विपुलमतिमनःपर्ययश्चेति द्विविधः। तत्र ऋज्वी-ऋजुकायवाङ्मनःकृतार्थस्य—परकीयमनोगतस्य विज्ञानान्निर्वर्तिता-निष्पन्ना मतिर्यस्य स ऋजुमतिः स चासौ मनःपर्ययश्च ऋजुमतिमनःपर्ययः। विपुला कायवाग्मनःकृतार्थस्य—परकीयमनोगतस्य विज्ञानान्निर्वर्तिता अनिर्वर्तिता कुटिला च मतिर्यस्य स विपुलमतिः स चासौ मनःपर्ययश्च विपुलमतिमनःपर्ययः। अथवा ऋजुश्च विपुला च ऋजुविपुले ते मती ययोस्तौ ऋजुविपुलमती तौ च तौ मनःपर्ययौ च ऋजुविपुलमतिमनःपर्ययौ। तत्र ऋजुमतिमनःपर्ययः ऋजुमनोगतार्थविषयः, ऋजुवचनगतार्थविषयः, ऋजुकायगतार्थविषयश्चेति नियमेन

का जो अर्थ दूसरेके मनमें स्थित है, उसको जो ज्ञान जानता है वह मनःपर्यय कहा जाता है। दूसरेके मनमें स्थित अर्थ मन हुआ, उसे जो जानता है वह मनःपर्यय है। इस ज्ञानकी उत्पत्ति और प्रवृत्ति मनुष्यक्षेत्रमें ही होती है, उसके बाहर नहीं ॥४३८॥

वह मनःपर्यय सामान्यसे एक होनेपर भी भेदविवक्षासे ऋजुमतिमनःपर्यय विपुलमतिमनःपर्यय इस तरह दो प्रकार है। सरल काय, वचन और मनके द्वारा किया गया जो अर्थ दूसरेके मनमें स्थित है उसको जाननेसे निष्पन्न हुई मति जिसकी है वह ऋजुमति है और ऋजुमति और मनःपर्यय ऋजुमतिमनःपर्यय है। तथा सरल अथवा कुटिल काय-वचन-मनके द्वारा किया गया जो अर्थ दूसरेके मनमें स्थित है उसको जाननेसे निष्पन्न या अनिष्पन्न मति जिसकी है वह विपुलमति है। विपुलमति और मनःपर्यय विपुलमति मनःपर्यय है। अथवा ऋजु और विपुला मति जिनकी है वे ऋजुमति, विपुलमति मनःपर्यय हैं। ऋजुमतिमनःपर्यय नियमसे तीन प्रकारका है—सरल मनके द्वारा चिन्तित मनोगत

पेळल्पट्टुदु। नरलोके तदुत्पत्तिप्रवृत्तिगळेरडुं मनुष्यक्षेत्रदोळेयक्कुं। मनुष्यक्षेत्रदिदं पोरगे मनःपर्य्ययज्ञानक्कुत्पत्तियुं प्रवृत्तियुमिल्लेंबुदत्थं।

परकीयमनसि व्यवस्थितोऽर्थः मन इत्युच्यते। मनः पर्येति गच्छति जानातीति मनःपर्य्ययः एंदितु परमनोगतात्थंग्राहकं मनःपर्य्ययज्ञानमक्कुमा परमनोगतात्थंमुं चिंतितमचिंतितमर्द्धचिंतितमें दितनेकभेदमप्पुददं मनुष्यक्षेत्रदोळु मनःपर्य्ययज्ञानमरिगुमेंबुदु तात्पर्य्यं।

मणपज्जवं च दुविहं उजुविउलमदित्ति उजुमदी तिविहा।
उजु मणवयणे काये गदत्थविसयत्ति णियमेण ॥४३९॥

मनः पर्य्ययश्च द्विविधः ऋजुविपुलमती इति। ऋजुमतिस्त्रिविधः ऋजु मनोवचने काये गतार्त्थविषय इति नियमेन।

सामान्यदिदं मनःपर्य्ययज्ञानमोंदु अदं भेदिसिदोडे ऋजुमतिमनःपर्य्ययमें दुं विपुलमतिमनःपर्य्ययमें दितु मनःपर्य्ययज्ञानं द्विविधमक्कु-। मल्लि ऋज्वी ऋजुकायवाग्मनस्कृतार्त्थस्य परकीयमनोगतस्य विज्ञानान्निर्व्वत्तिता निष्पन्ना मतिर्य्यस्य सः ऋजुमतिः स चासौ मनःपर्य्ययश्च ऋजुमतिमनःपर्य्ययः। विपुला कायवाग्मनस्कृतार्त्थस्य परकीयमनोगतस्य विज्ञाना निर्व्वर्त्तिताऽनिर्व्वर्त्तिता कुटिला च मतिर्य्यस्य सः विपुलमतिः। स चासौ मनःपर्य्ययश्च विपुलमतिमनःपर्य्ययः। एंदितु निरुक्तिसिद्धंगळप्पुवल्लि ऋजुश्च विपुला च ऋजु विपुले। ते मती ययोस्तौ ऋजुविपुलमती। ऋजुमनोगतात्थंविषयमनःपर्य्ययमें दुं ऋजुवचनगतात्थंविषयमनःपर्य्ययमें दुं ऋजुकायगतात्थंविषयमनःपर्य्ययमुमें दितु ऋजुमतिमनःपर्य्ययं नियम-

मनुष्यक्षेत्र एव न तद्बहिः। परकीयमनसि व्यवस्थितोऽर्थः मनः तत् पर्येति गच्छति जानातीति मनःपर्ययः ॥४३८॥

स मनःपर्ययः सामान्येनैकोऽपि भेदविवक्षया ऋजुमतिमनःपर्ययः विपुलमतिमनःपर्ययश्चेति द्विविधः। तत्र ऋज्वी-ऋजुकायवाङ्मनःकृतार्थस्य—परकीयमनोगतस्य विज्ञानान्निर्वर्तिता-निष्पन्ना मतिर्यस्य स ऋजुमतिः स चासौ मनःपर्ययश्च ऋजुमतिमनःपर्ययः। विपुला कायवाग्मनःकृतार्थस्य—परकीयमनोगतस्य विज्ञानान्निर्वर्तिता अनिर्वर्तिता कुटिला च मतिर्यस्य स विपुलमतिः स चासौ मनःपर्ययश्च विपुलमतिमनःपर्ययः। अथवा ऋजुश्च विपुला च ऋजुविपुले ते मती ययोस्तौ ऋजुविपुलमती तौ च तौ मनःपर्ययौ च ऋजुविपुलमतिमनःपर्ययौ। तत्र ऋजुमतिमनःपर्ययः ऋजुमनोगतार्थविषयः, ऋजुवचनगतार्थविषयः, ऋजुकायगतार्थविषयश्चेति नियमेन

का जो अर्थ दूसरेके मनमें स्थित है, उसको जो ज्ञान जानता है वह मनःपर्यय कहा जाता है। दूसरेके मनमें स्थित अर्थ मन हुआ, उसे जो जानता है वह मनःपर्यय है। इस ज्ञानकी उत्पत्ति और प्रवृत्ति मनुष्यक्षेत्रमें ही होती है, उसके बाहर नहीं ॥४३८॥

वह मनःपर्यय सामान्यसे एक होनेपर भी भेदविवक्षासे ऋजुमतिमनःपर्यय विपुलमतिमनःपर्यय इस तरह दो प्रकार है। सरल काय, वचन और मनके द्वारा किया गया जो अर्थ दूसरेके मनमें स्थित है उसको जाननेसे निष्पन्न हुई मति जिसकी है वह ऋजुमति है और ऋजुमति और मनःपर्यय ऋजुमतिमनःपर्यय है। तथा सरल अथवा कुटिल काय-वचन-मनके द्वारा किया गया जो अर्थ दूसरेके मनमें स्थित है उसको जाननेसे निष्पन्न या अनिष्पन्न मति जिसकी है वह विपुलमति है। विपुलमति और मनःपर्यय विपुलमति मनःपर्यय है। अथवा ऋजु और विपुला मति जिनकी है वे ऋजुमति, विपुलमति मनःपर्यय हैं। ऋजुमतिमनःपर्यय नियमसे तीन प्रकारका है—सरल मनके द्वारा चिन्तित मनोगत

डोडं वेसगोळदिद्दोडे विपुलमतिमनःपर्य्ययज्ञानमरिगुमें विंतिल्लियुं शब्दगतार्थंगळुमर्त्थगतार्थंगळु-मेंदितु द्विप्रकारांगळप्पुवु ।

तियकालविसयरूविं चिंतंतं वट्टमाणजीवेण ।
उजुमदिणाणं जाणदि भूदभविस्सं च विउलमदी ॥४४१॥

त्रिकालविषयरूपिणं चिंत्यमानं वर्त्तमानजीवेन । ऋजुमतिज्ञानं जानाति भूतभविष्यंतौ च विपुलमतिः ।

त्रिकालविषयपुद्गलद्रव्यमं वर्त्तमानजीवनिदं चिंतिसल्पडुत्तिद्दुदं ऋजुमतिमनःपर्य्ययज्ञान-मरिगुं । भूतभविष्यद्वर्त्तमानकालविषयंगळप्प चिंतितमं चिन्तयिष्यमाणमं चिंत्यमानमं विपुलमतिः मनःपर्य्ययज्ञानमरिगुं ॥

सव्वंगअंगसंभवचिण्हादुप्पज्जदे जहा ओही ।
मणपज्जवं च दव्वमणादो उप्पज्जदे णियमा ॥४४२॥

सर्व्वांगांगसंभवचिह्नादुत्पद्यते यथावधिः । मनःपर्य्ययश्च द्रव्यमनसः उत्पद्यते नियमात् ॥

सर्व्वांगदोळमंगसंभवशंखादिशुभचिह्नं गळोळं यथा येंतोगळवधिज्ञानं पुट्टुगुमंते मनःपर्य्यय-ज्ञानमुं द्रव्यमनदिदं पुट्टुगुं नियमदिदं । नियमशब्दं द्रव्यमनदोळल्लदे मत्तेल्लियुमंगप्रदेशदोळु मनःपर्य्ययं पुट्टुदेंबवधारणार्थमक्कुं ॥

हिदि होदि हु दव्वमणं वियसिय अट्ठच्छदारविंदं वा ।
अंगोवंगुदयादो मणवग्गणखंददो णियमा ॥४४३॥

हृदि भवति खलु द्रव्यमनो विकसिताष्टच्छदारविन्दवत् । अंगोपांगोदयात् मनोवर्गणा-स्कन्धतो नियमात् ॥

त्रिकालविषयपदार्थान् चिन्तितवान् वा उक्तवान् वा कृतवान् विस्मृत्य कालान्तरेण स्मर्तुमशक्तः आगत्य पृच्छति वा तूष्णीं तिष्ठति तदा विपुलमतिमनःपर्ययज्ञानं जानाति ॥४४०॥

त्रिकालविषयपुद्गलद्रव्यं वर्तमानजीवेन चिन्त्यमानं ऋजुमतिमनःपर्ययज्ञानं जानाति । भूतभविष्यद्वर्त-मानकालविषयं चिन्तितं चिन्तयिष्यमाणं चिन्त्यमानं च विपुलमतिमनःपर्ययज्ञानं जानाति ॥४११॥

सर्वाङ्गे अङ्गसंभवशङ्खादिशुभचिह्ने च यथा अवधिज्ञानमुत्पद्यते तथा मनःपर्ययज्ञानं द्रव्यमनसि एवोत्पद्यते नियमेन नान्यत्राङ्गप्रदेशेषु ॥४४२॥

कायसे किये गये त्रिकालवर्ती पदार्थोंको विचार किया कहा या शरीरसे किया। पीछे भूल गया और समय बीतनेपर स्मरण नहीं कर सका। आकर पूछता है या चुप बैठता है तब विपुलमति मनः पर्ययज्ञानी जानता है ॥४४०॥

त्रिकालवर्ती पुद्गल द्रव्य वर्तमान जीवके द्वारा चिन्तवन किया गया हो तो उसे ऋजुमति मनःपर्ययज्ञान जानता है। और त्रिकालवर्ती पुद्गलद्रव्य भूतकालमें चिन्तवन किया गया हो, भविष्यत् कालमें चिन्तन किया जानेवाला हो या वर्तमानमें चिन्तवन किया जाता हो तो उसे विपुलमतिमनःपर्ययज्ञान जानता है ॥४४१॥

जैसे भवप्रत्यय अवधिज्ञान सर्वांगसे उत्पन्न होता है और गुणप्रत्यय अवधिज्ञान शरीरमें प्रकट हुए शंख आदि शुभ चिह्नोंसे उत्पन्न होता है वैसे ही मनःपर्ययज्ञान द्रव्यमनसे ही उत्पन्न होता है ऐसा नियम है, शरीरके अन्य प्रदेशोंमें उत्पन्न नहीं होता ॥४४२॥

स्पर्शनादींद्रियंगळुमं नोइंद्रियमुमं मनोवचनकाययोगमुमें विवं तन्न पेरर संबंधिगळुमनपेक्षिसियेयृजुमतिमनःपर्य्ययज्ञानं संजनिसुगुं। वु मत्तें इंद्रियनोइंद्रिययोगादिगळं स्वपरसंबंधिगळनपेक्षिसदे विपुलमतिमनःपर्य्ययज्ञानं चक्षुरिंद्रियमोगळं तु रसादिगळं परिहरिसि रूपमों वने परिच्छेदिसुगुमंते मनःपर्य्ययज्ञानमुं भवविषयाशेषानंतपर्य्यायंगळं परिहरिसि आवुवों वु कारणदिदं भवसंजिततद्विरिव्यंजनपर्य्यायंगळं परिच्छेदिसुगुमदु कारणदिदंमिदवधिज्ञानवंते नियमदिदं संजनिसुगुं।

पडिवादी पुण पढमा अप्पडिवादी हु होदि विदिया हु ।
सुद्धो पढमो बोहो सुद्धतरो विदियबोहो दु ॥४४७॥

प्रतिपाती पुनः प्रथमोऽप्रतिपाती खलु भवति द्वितीयः। शुद्धः प्रथमो बोधः शुद्धतरो द्वितीयबोधस्तु ॥

प्रथमः मोदल ऋजुमतिमनःपर्य्ययं प्रतिपाती प्रतिपातियक्कुं । प्रतिपतनं प्रतिपातः उपशांतकषायंगे चारित्रमोहोद्रेकदिदं प्रच्युतसंयमशिखरंगे प्रतिपातमक्कुं। क्षीणकषायंगे प्रतिपातकारणाभावदिदं अप्रतिपातमक्कुं। तदपेक्षेयिदं प्रतिपातोऽस्यास्तीति प्रतिपाती। पुनः मत्ते द्वितीयः विपुलमतिमनःपर्य्ययं अप्रतिपाती खलु प्रतिपातरहितमक्कुं। न प्रतिपाती अप्रतिपाती। शुद्धः प्रथमो बोधः मोदल ऋजुमतिमनःपर्य्ययं विशुद्धबोधमक्कुं। प्रतिपक्षकर्म्मक्षयोपशममंटागुत्तिरलु आत्मन प्रसादमं विशुद्धियें बुदु। तदस्यास्तीति विशुद्धः शुद्धतरो द्वितीयबोधस्तु। तु मत्तें अतिशयदिदं विशुद्धमक्कुं विपुलमतिमनःपर्य्ययं।

परमणसिट्ठियमट्ठं ईहामदिणा उजुट्ठियं लहिय ।
पच्छा पच्चक्खेण य उजुमदिणा जाणदे णियमा ॥४४८॥

परमनसि स्थितमर्थं ईहामत्या ऋजुस्थितं लब्ध्वा। पश्चात्प्रत्यक्षेण च ऋजुमतिना जानीते नियमात् ॥

ऋजुमतिमनःपर्ययः स्पर्शनादीन्द्रियाणि नोइन्द्रियं मनोवचनकाययोगांश्च स्वपरसंबन्धिनोऽपेक्ष्यैवोत्पद्यते। विपुलमतिमनःपर्ययस्तु अवधिज्ञानमिव तानऽनपेक्ष्यैवोत्पद्यते नियमेन ॥४४६॥

प्रथमः ऋजुमतिमनःपर्ययः प्रतिपाती भवति। क्षीणकषायस्याप्रतिपातेऽपि, उपशान्तकषायस्य चारित्रमोहोद्रेकात्पतनसंभवात्। पुनः द्वितीयो विपुलमतिमनःपर्ययः अप्रतिपाती खलु। ऋजुमतिमनःपर्ययो विशुद्धः, प्रतिपक्षकर्मक्षयोपशमे सति आत्मप्रसादरूपविशुद्धेः संभवात्। तु पुनः विपुलमतिमनःपर्ययः अतिशयेन विशुद्धो भवति ॥४४७॥

ऋजुमतिमनःपर्यय अपने और अन्य जीवोंके स्पर्शन आदि इन्द्रियों, मन, और मनवचन-काय योगोंकी अपेक्षासे ही उत्पन्न होता है। और विपुलमतिमनःपर्यय अवधिज्ञानकी तरह इनकी अपेक्षाके बिना ही उत्पन्न होता है ॥४४६॥

प्रथम ऋजुमति मनःपर्यय प्रतिपाती होता है। जो ऋजुमति मनःपर्ययज्ञानी क्षपकश्रेणीपर आरोहण करके क्षीणकषाय हो जाता है यद्यपि वह वहाँसे गिरता नहीं है किन्तु जो उपशम श्रेणीपर आरोहण करके उपशान्त कषाय नामक ग्यारहवें गुणस्थानवर्ती होता है, चारित्रमोहका उद्रेक होनेसे उसका प्रतिपात होता है। किन्तु दूसरा विपुलमतिमनःपर्यय अप्रतिपाती है। ऋजुमति मनःपर्यय विशुद्ध है क्योंकि प्रतिपक्षी कर्मका क्षयोपशम होनेपर

अवरं दव्वमुरालियसरीरणिज्जिण्णसमयपबद्धं तु ।
चक्खिंदियणिज्जिण्णं उक्कस्सं उजुमदिस्स हवे ॥४५१॥

अवरं द्रव्यमौदारिकशरीरनिर्ज्जीर्ण्णसमयप्रबद्धस्तु । चक्षुरिंद्रियनिर्ज्जीर्णमुत्कृष्टं ऋजुमते भवेत् ।

ऋजुमतिमनःपर्य्ययज्ञानक्के विषयमप्प जघन्यद्रव्यमौदारिकशरीरनिर्ज्जीर्ण्णसमयप्रबद्धमक्कुं । स ० १६ ख । तु मत्ते । उत्कृष्टं द्रव्यं चक्षुरिंद्रियनिर्ज्जीर्णद्रव्यमक्कुं । अदर प्रमाणमेनितेंदोडे त्रैराशिकदिदं साधिसल्पडुगुं ।

आ त्रैराशिकविधानमेनितेंदोडे संख्यातघनांगुलप्रमितमौदारिकशरीरावगाहनप्रदेशंगळोळेल्लमेत्तलानुं सविस्रसोपचयौदारिकशरीरसमयप्रबद्धंगळोळेल्लमेत्तलानुं सविस्रसोपचयौदारिकशरीरसमयप्रबद्धंगळेयिसुवागळु चक्षुरिंद्रियाभ्यंतरनिर्वृत्तिप्रदेशप्रचयमिनितरोळिनितु द्रव्यंगळेयिसुगुमेंदितु त्रैराशिकमं माडि प्र ६ । १ । फ स ० १६ ख ६ ६ प आद्यंतसदृशं त्रैराशिके

प १ १ ० प
० ०

मध्यम नाम फलं भवेत् एंदु बंद लब्धं चक्षुरिंद्रियनिर्ज्जीर्णद्रव्यमिदु ऋजुमतिमनःपर्य्ययक्कुत्कृष्टद्रव्यमक्कुं स ० १६ ख ६ प
०
६ । १ प १ १ प

तत्र ऋजुमतिमनःपर्ययः जघन्यद्रव्यं औदारिकशरीरनिर्जीर्णसमयप्रबद्धं जानाति स ० १६ ख । तु—पुनः, उत्कृष्टद्रव्यं चक्षुरिन्द्रियनिर्जीर्णमात्रं जानाति। तत्कथम् ? औदारिकशरीरावगाहने संख्यातघनाङ्गुले सविस्रसोपचयौदारिकशरीरसमयप्रबद्धो गलति तदा चक्षुरिन्द्रियाभ्यन्तरनिर्वृत्तिप्रदेशप्रचये कियदिति त्रैराशिकेन प्र ६ १ । फ स ० १६ ख । इ ६ प लब्धमात्रं भवति—स ० १६ ख । ६ । प ॥४५१॥
० ०

प १ १ प
० ०

६ १ प १ १ प
० ०

ऋजुमति मनःपर्यय औदारिक शरीरके निर्जीर्ण समय प्रबद्धरूप जघन्य द्रव्यको जानता है और उत्कृष्टद्रव्यके रूपमें चक्षु इन्द्रियके निर्जीर्णद्रव्यको जानता है। वह कितना है सो कहते हैं—औदारिक शरीरकी अवगाहना संख्यात घनांगुल है। उसके विस्रसोपचय सहित औदारिक शरीरके समय प्रबद्ध परमाणुओंकी निर्जरा होती है। तब चक्षु इन्द्रियकी अभ्यन्तर निर्वृत्तिके प्रदेश प्रचयमें कितनी निर्जरा हुई, ऐसा त्रैराशिक करनेपर जितना परिमाण आवे उतने परमाणुओंके स्कन्धको ऋजुमति उत्कृष्ट रूपसे जानता है॥४५१॥

अवरं दव्वमुरालियसरीरणिज्जिण्णसमयबद्धं तु।
चक्खिंदियणिज्जिण्णं उक्कस्सं उजुमदिस्स हवे ॥४५१॥

अवरं द्रव्यमौदारिकशरीरनिर्जीर्णसमयप्रबद्धस्तु। चक्षुरिंद्रियनिर्जीर्णमुत्कृष्टं ऋजुमते भवेत्।

ऋजुमतिमनःपर्य्ययज्ञानक्के विषयमप्प जघन्यद्रव्यमौदारिकशरीरनिर्जीर्णसमयप्रबद्ध मक्कुं। स ० १६ ख। तु मत्ते। उत्कृष्टं द्रव्यं चक्षुरिंद्रियनिर्जीर्णद्रव्यमक्कुं। अदर प्रमाणमेनितेंदोडे त्रैराशिकविदं साधिसल्पडुगुं।

आ त्रैराशिकविधानमेनितेंदोडे संख्यातघनांगुलप्रमितमौदारिकशरीरावगाहनप्रदेशंगळोळेल्लमेत्तलानुं सविस्रसोपचयौदारिकशरीरसमयप्रबद्धंगळोळेल्लमेत्तलानुं सविस्रसोपचयौदारिकशरीरसमयप्रबद्धंगळेनितुवागळु चक्षुरिंद्रियाभ्यंतरनिर्वृत्तिप्रदेशप्रचयमिनितरोळिनितु द्रव्यंगळेनितुगुमेंदितु त्रैराशिकमं माडि प्र ६।१। फ स ० १६ ख ६ ६ प आद्यंतगतदं त्रैराशिकं

प १ १ ० प
० ०

मध्यम नाम फलं भवेत् एंदु बंद लब्धं चक्षुरिंद्रियनिर्जीर्णद्रव्यमिदु ऋजुमतिमनःपर्य्ययक्कुत्कृष्टद्रव्यमक्कुं स ० १६ ख ६ प
०
६।१ प १ १ प

तत्र ऋजुमतिमनःपर्ययः जघन्यद्रव्यं औदारिकशरीरनिर्जीर्णसमयप्रबद्धं जानाति स ० १६ ख। तु—पुनः, उत्कृष्टद्रव्यं चक्षुरिन्द्रियनिर्जीर्णमात्रं जानाति। तत्कियत् ? औदारिकशरीरावगाहने संख्यातघनाङ्गुले सविस्रसोपचयौदारिकशरीरसमयप्रबद्धो गलति तदा चक्षुरिन्द्रियाभ्यन्तरनिर्वृत्तिप्रदेशप्रचये कियदिति त्रैराशिकेन प्र ६ १। फ स ० १६ ख। इ ६ प लब्धमात्रं भवति—स ० १६ ख। ६। प ॥४५१॥
० ०

प १ १ प
० ० ६ १ प १ १ प
० ०

ऋजुमति मनःपर्यय औदारिक शरीरके निर्जीर्ण समय प्रबद्धरूप जघन्य द्रव्यको जानता है और उत्कृष्टद्रव्यके रूपमें चक्षु इन्द्रियके निर्जीर्णद्रव्यको जानता है। वह कितना है सो कहते हैं—औदारिक शरीरकी अवगाहना संख्यात घनांगुल है। उसके विस्रसोपचय सहित औदारिक शरीरके समय प्रबद्ध परमाणुओंकी निर्जरा होती है। तब चक्षु इन्द्रियकी अभ्यन्तर निर्वृत्तिके प्रदेश प्रचयमें कितनी निर्जरा हुई, ऐसा त्रैराशिक करनेपर जितना परिमाण आवे उतने परमाणुओंके स्कन्धको ऋजुमति उत्कृष्ट रूपसे जानता है ॥४५१॥

अवरं दव्वमुरालियसरीरणिज्जिण्णसमयबद्धं तु ।
चक्खिंदियणिज्जिण्णं उक्कस्सं उजुमदिस्स हवे ।।४५१।।

अवरं द्रव्यमौदारिकशरीरनिर्जीर्णसमयप्रबद्धस्तु । चक्षुरिंद्रियनिर्जीर्णमुत्कृष्टं ऋजुमते भवेत् ।

ऋजुमतिमनःपर्ययज्ञानक्के विषयमप्प जघन्यद्रव्यमौदारिकशरीरनिर्जीर्णसमयप्रबद्धमक्कुं । स ० १६ ख । तु मत्ते । उत्कृष्टं द्रव्यं चक्षुरिंद्रियनिर्जीर्णद्रव्यमक्कुं । अवर प्रमाणमेनितेंदोडे त्रैराशिकविदं साधिसल्पडुगुं ।

आ त्रैराशिकविधानमेनितेंदोडे संख्यातघनांगुलप्रमितमौदारिकशरीरावगाहनप्रदेशंगळोळेल्लमेत्तलानुं सविस्रसोपचयौदारिकशरीरसमयप्रबद्धंगळोळेल्लमेत्तलानुं सविस्रसोपचयौदारिकशरीरसमयप्रबद्धंगळेयिसुवागळु चक्षुरिंद्रियाभ्यंतरनिर्वृत्तिप्रदेशप्रचयमिनितरोळिनितु द्रव्यंगळेयिसुगुमेंदितु त्रैराशिकमं माडि प्र ६ । १ । फ स ० १६ ख ६ ६ प आद्यंतगहर्श त्रैराशिक

प १ १ ० प
a a

मध्यम नाम फलं भवेत् एंदु बंद लब्धं चक्षुरिंद्रियनिर्जीर्णद्रव्यमिदु ऋजुमतिमनःपर्ययक्कुत्कृष्टद्रव्यमक्कुं स ० १६ ख ६ प
a
६ । १ प १ १ प

तत्र ऋजुमतिमनःपर्ययः जघन्यद्रव्यं औदारिकशरीरनिर्जीर्णसमयप्रबद्धं जानाति स ० १६ ख । तु-पुनः, उत्कृष्टद्रव्यं चक्षुरिन्द्रियनिर्जीर्णमात्रं जानाति। तत्कियत् ? औदारिकशरीरावगाहने संख्यातघनाङ्गुले सविस्रसोपचयौदारिकशरीरसमयप्रबद्धो गलति तदा चक्षुरिन्द्रियाभ्यन्तरनिर्वृत्तिप्रदेशप्रचये कियदिति त्रैराशिकेन प्र ६ १ । फ स ० १६ ख । इ ६ प लब्धमात्रं भवति—स ० १६ ख । ६ । प ।।४५१।।

a a

प १ १ प
a a

६ १ प १ १ प
a a

ऋजुमति मनःपर्यय औदारिक शरीरके निर्जीर्ण समय प्रबद्धरूप जघन्य द्रव्यको जानता है और उत्कृष्टद्रव्यके रूपमें चक्षु इन्द्रियके निर्जीर्णद्रव्यको जानता है। वह कितना है सो कहते हैं—औदारिक शरीरकी अवगाहना संख्यात घनांगुल है। उसके विस्रसोपचय सहित औदारिक शरीरके समय प्रबद्ध परमाणुओंकी निर्जरा होती है। तब चक्षु इन्द्रियकी अभ्यन्तर निर्वृत्तिके प्रदेश प्रचयमें कितनी निर्जरा हुई, ऐसा त्रैराशिक करनेपर जितना परिमाण आवे उतने परमाणुओंके स्कन्धको ऋजुमति उत्कृष्ट रूपसे जानता है ।।४५१।।

अवरं दव्वमुरालियसरीरणिज्जिण्णसमयबद्धं तु ।
चक्खिंदियणिज्जिण्णं उक्कस्सं उजुमदिस्स हवे ॥४५१॥

अवरं द्रव्यमौदारिकशरीरनिर्जीर्णसमयप्रबद्धस्तु । चक्षुरिंद्रियनिर्जीर्णमुत्कृष्टं ऋजुमते भवेत् ।

ऋजुमतिमनःपर्य्ययज्ञानक्के विषयमप्प जघन्यद्रव्यमौदारिकशरीरनिर्जीर्णसमयप्रबद्धमक्कुं । स ० १६ ख । तु मत्ते । उत्कृष्टं द्रव्यं चक्षुरिंद्रियनिर्जीर्णद्रव्यमक्कुं । अदर प्रमाणमेनितेंदोडे त्रैराशिकदिदं साधिसल्पडुगुं ।

आ त्रैराशिकविधानमेनितेंदोडे संख्यातघनांगुलप्रमितमौदारिकशरीरावगाहनप्रदेशंगळोळेल्लमेत्तलानुं सविस्रसोपचयौदारिकशरीरसमयप्रबद्धंगळोळेल्लमेत्तलानुं सविस्रसोपचयौदारिकशरीरसमयप्रबद्धंगळेयिसुवागळु चक्षुरिंद्रियाभ्यंतरनिर्वृत्तिप्रदेशप्रचयमिनितरोळिनितु द्रव्यंगळेयिसुगुमेंदितु त्रैराशिकमं माडि प्र ६ । १ । फ स ० १६ ख इ ६ प आद्यंतगहशं त्रैराशिकं

प १ १ ० प
० ०

मध्यम नाम फलं भवेत् एंदु बंद लब्धं चक्षुरिंद्रियनिर्जीर्णद्रव्यमिदु ऋजुमतिमनःपर्य्ययक्कुत्कृष्टद्रव्यमक्कुं स ० १६ ख ६ प
०
६ । १ प १ १ प

तत्र ऋजुमतिमनःपर्ययः जघन्यद्रव्यं औदारिकशरीरनिर्जीर्णसमयप्रबद्धं जानाति स ० १६ ख । तु-पुनः, उत्कृष्टद्रव्यं चक्षुरिन्द्रियनिर्जीर्णमात्रं जानाति। तत्कियत् ? औदारिकशरीरावगाहने संख्यातघनाङ्गुले सविस्रसोपचयौदारिकशरीरसमयप्रबद्धो गलति तदा चक्षुरिन्द्रियाभ्यन्तरनिर्वृत्तिप्रदेशप्रचये कियदिति त्रैराशिकेन प्र ६ १ । फ स ० १६ ख । इ ६ प लब्धमात्रं भवति—स ० १६ ख । ६ । १ प ॥४५१॥
०
प १ १ प
० ०
६ १ प १ १ प
० ०

ऋजुमति मनःपर्यय औदारिक शरीरके निर्जीर्ण समय प्रबद्धरूप जघन्य द्रव्यको जानता है और उत्कृष्टद्रव्यके रूपमें चक्षु इन्द्रियके निर्जीर्णद्रव्यको जानता है। वह कितना है सो कहते हैं—औदारिक शरीरकी अवगाहना संख्यात घनांगुल है। उसके विस्रसोपचय सहित औदारिक शरीरके समय प्रबद्ध परमाणुओंकी निर्जरा होती है। तब चक्षु इन्द्रियकी अभ्यन्तर निर्वृत्तिके प्रदेश प्रचयमें कितनी निर्जरा हुई, ऐसा त्रैराशिक करनेपर जितना परिमाण आवे उतने परमाणुओंके स्कन्धको ऋजुमति उत्कृष्ट रूपसे जानता है ॥४५१॥

तव्विदियं कप्पाणमसंखेज्जाणं च समयसंखसमं ।
धुवहारेणवहरिदे होदि हु उक्कस्सयं दव्वं ॥४५४॥

तद्द्वितीयं कल्पानामसंख्यातानां च समयसंख्यासमं ध्रुवहारेणापहृते भवति खलूत्कृष्टं द्रव्यं।

तं द्वितीयं विपुलमनःपर्य्ययज्ञानविषयद्वितीयद्रव्यविकल्पमं असंख्यातकल्पंगळ समयंगळ संख्यासमानध्रुवहारंगळिंदं भागिसुत्तं विरलु यावत्प्रमाणं लब्धं तावत्प्रमाणं विपुलमतिमनःपर्य्ययज्ञानविषयसर्व्वोत्कृष्टद्रव्यविकल्पमक्कुं खलु स्फुटमागि स ० ख ख
९ क ० ९९९

गाउयपुधत्तमवरं उक्कस्सं होदि जोयणपुधत्तं ।
विउलमदिस्स य अवरं तस्स पुधत्तं वरं खु णरलोयं ॥४५५॥

गव्यूतिपृथक्त्वमवरमुत्कृष्टं भवति योजनपृथक्त्वं । विपुलमतेरवरं तस्य पृथक्त्वं खलु नरलोकः ॥

ऋजुमतिमनःपर्य्ययज्ञानविषयजघन्यक्षेत्रं गव्यूतिपृथक्त्वमेरडुमूरु क्रोशंगळप्पुवु । क्रो २ । ३ । मवरुत्कृष्टक्षेत्रं योजनपृथक्त्वसमाष्टयोजनप्रमाणमक्कुं । यो ७ । ८ । विपुलमतिमनःपर्य्ययज्ञान विषयजघन्यक्षेत्रं तस्य पृथक्त्वमा योजनंगळ पृथक्त्वमष्टयोजननवयोजनप्रमाणमक्कुं । ८ । ९ । तदुत्कृष्टज्ञानविषयोत्कृष्टक्षेत्रं खलु स्फुटमागि । नरलोकः मनुष्यलोकमेनितनितु प्रमाणमक्कुं ।

णरलोएत्ति य वयणं विक्खंभणियामयं ण वट्टस्स ।
जम्हा तग्घणपदरं मणपज्जवखेत्तमुद्दिट्ठं ॥४५६॥

नरलोक इति वचनं विष्कंभनियामकं न वृत्तस्य । यस्मात्तद्घनप्रतरं मनःपर्य्ययक्षेत्रमुद्दिष्टं ॥

विपुलमतिमनःपर्य्ययज्ञानविषयसर्व्वोत्कृष्टक्षेत्रप्रमाणवोळु नरलोक इति वचनं नरलोकमें बी शब्दं तन्मनुष्यक्षेत्रवृत्तविष्कंभनियामकमल्तेकें दोडे यस्मात् आवुदों दु कारणदिदं तद्घनप्रतरमा

तस्मिन् विपुलमतिविषयद्वितीयद्रव्ये असंख्यातकल्पसमयसंख्यैर्ध्रुवहारैर्भक्ते विपुलमतिविषयं सर्वोत्कृष्ट-द्रव्यं भवति— स ० ० ० ख ख ॥४५४॥
९। क ० ९९९

ऋजुमतिविषयजघन्यक्षेत्रं गव्यूतिपृथक्त्वं द्वित्रिक्रोशाः २ । ३ । उत्कृष्टं योजनपृथक्त्वं सप्ताष्टयोजनानि ७ । ८ । विपुलमतिविषयजघन्यक्षेत्रं योजनपृथक्त्वं अष्टनवयोजनानि । ८ । ९ । उत्कृष्टं स्फुटं नरलोकः ॥४५५॥

यद्विपुलमतिविषयोत्कृष्टक्षेत्रप्ररूपणे नरलोक इति वचनमुक्तं तत् तद्गतविष्कम्भस्य नियामकं निश्चायकं

विपुलमतिके विषयभूत उस दूसरे द्रव्यमें असंख्यात कल्पकालके समयोंकी संख्या जितनी है उतनी बार ध्रुवहारसे भाग देनेपर विपुलमतिके विषयभूत सर्व उत्कृष्टद्रव्य आता है ॥४५४॥

ऋजुमतिका विषयभूत जघन्य क्षेत्र गव्यूति पृथक्त्व अर्थात् दो-तीन कोस है। और उत्कृष्ट क्षेत्र योजन पृथक्त्व अर्थात् सात-आठ योजन है। विपुलमतिका विषयभूत जघन्य क्षेत्र योजन पृथक्त्व अर्थात् आठ-नौ योजन है और उत्कृष्टक्षेत्र मनुष्यलोक है ॥४५५॥

विपुलमतिका विषय उत्कृष्टक्षेत्रका कथन करते हुए जो मनुष्यलोक कहा है वह

तव्विदियं कप्पाणमसंखेज्जाणं च समयसंखसमं ।
धुवहारेणवहरिदे होदि हु उक्कस्सयं दव्वं ॥४५४॥

तद्द्वितीयं कल्पानामसंख्यातानां च समयसंख्यासमं ध्रुवहारेणापहृते भवति खलूत्कृष्टं द्रव्यं ।

तं द्वितीयं विपुलमनःपर्य्ययज्ञानविषयद्वितीयद्रव्यविकल्पमं असंख्यातकल्पंगळ समयंगळ संख्यासमानध्रुवहारंगळिंदं भागिसुत्तं विरलु यावत्प्रमाणं लब्धं तावत्प्रमाणं विपुलमतिमनःपर्य्ययज्ञानविषयसर्व्वोत्कृष्टद्रव्यविकल्पमक्कुं खलु स्फुटमागि स ० ख ख / ९ क ० ९९९

गाउयपुधत्तमवरं उक्कस्सं होदि जोयणपुधत्तं ।
विउलमदिस्स य अवरं तस्स पुधत्तं वरं खु णरलोयं ॥४५५॥

गव्यूतिपृथक्त्वमवरमुत्कृष्टं भवति योजनपृथक्त्वं । विपुलमतेरवरं तस्य पृथक्त्वं खलु नरलोकः ॥

ऋजुमतिमनःपर्य्ययज्ञानविषयजघन्यक्षेत्रं गव्यूतिपृथक्त्वमेरडुमूरु क्रोशंगळप्पुवु । क्रो २ । ३ । मवरुत्कृष्टक्षेत्रं योजनपृथक्त्वसप्ताष्टयोजनप्रमाणमक्कुं । यो ७ । ८ । विपुलमतिमनःपर्य्ययज्ञान विषयजघन्यक्षेत्रं तस्य पृथक्त्वमा योजनंगळ पृथक्त्वमष्टयोजननवयोजनप्रमाणमक्कुं । ८ । ९ । तदुत्कृष्टज्ञानविषयोत्कृष्टक्षेत्रं खलु स्फुटमागि । नरलोकः मनुष्यलोकमेनितनितु प्रमाणमक्कुं ।

णरलोएत्ति य वयणं विक्खंभणियामयं ण वट्टस्स ।
जम्हा तग्घणपदरं मणपज्जवखेत्तमुद्दिट्ठं ॥४५६॥

नरलोक इति वचनं विष्कंभनियामकं न वृत्तस्य । यस्मात्तद्घनप्रतरं मनःपर्य्ययक्षेत्रमुद्दिष्टं ॥

विपुलमतिमनःपर्य्ययज्ञानविषयसर्व्वोत्कृष्टक्षेत्रप्रमाणदोळु नरलोक इति वचनं नरलोकमें बी शब्दं तन्मनुष्यक्षेत्रवृत्तविष्कंभनियामकमल्तेकेंदोडे यस्मात् आवुदों दु कारणदिंदं तद्घनप्रतरमा

तस्मिन् विपुलमतिविषयद्वितीयद्रव्ये असंख्यातकल्पसमयसंख्यध्रुवहारैर्भक्ते विपुलमतिविषयं सर्वोत्कृष्ट-द्रव्यं भवति— स ० ० ० ख ख / ९ क ० ९९९ ॥४५४॥

ऋजुमतिविषयजघन्यक्षेत्रं गव्यूतिपृथक्त्वं द्वित्रिक्रोशाः २ । ३ । उत्कृष्टं योजनपृथक्त्वं सप्ताष्टयोजनानि ७ । ८ । विपुलमतिविषयजघन्यक्षेत्रं योजनपृथक्त्वं अष्टनवयोजनानि । ८ । ९ । उत्कृष्टं स्फुटं नरलोकः ॥४५५॥

यद्विपुलमतिविषयोत्कृष्टक्षेत्रप्ररूपणे नरलोक इति वचनमुक्तं तत् तद्गतविष्कम्भस्य नियामकं निश्चायकं

विपुलमतिके विषयभूत उस दूसरे द्रव्यमें असंख्यात कल्पकालके समयोंकी संख्या जितनी है उतनी बार ध्रुवहारसे भाग देनेपर विपुलमतिके विषयभूत सर्व उत्कृष्टद्रव्य आता है ॥४५४॥

ऋजुमतिका विषयभूत जघन्य क्षेत्र गव्यूति पृथक्त्व अर्थात् दो-तीन कोस है। और उत्कृष्ट क्षेत्र योजन पृथक्त्व अर्थात् सात-आठ योजन है। विपुलमतिका विषयभूत जघन्य क्षेत्र योजन पृथक्त्व अर्थात् आठ-नौ योजन है और उत्कृष्टक्षेत्र मनुष्यलोक है ॥४५५॥

विपुलमतिका विषय उत्कृष्टक्षेत्रका कथन करते हुए जो मनुष्यलोक कहा है वह

तब्बिदियं कप्पाणमसंखेज्जाणं च समयसंखसमं ।
धुवहारेणवहरिदे होदि हु उक्कस्सयं दव्वं ॥४५४॥

तद्द्वितीयं कल्पानामसंख्यातानां च समयसंख्यासमं ध्रुवहारेणापहृते भवति खलूत्कृष्टं द्रव्यं ।

तं द्वितीयं विपुलमनःपर्य्ययज्ञानविषयद्वितीयद्रव्यविकल्पमं असंख्यातकल्पंगळ समयंगळ संख्यासमानध्रुवहारंगळिदं भागिसुत्तं विरलु यावत्प्रमाणं लब्धं तावत्प्रमाणं विपुलमतिमनःपर्य्ययज्ञानविषयसर्व्वोत्कृष्टद्रव्यविकल्पमक्कुं खलु स्फुटमागि स ० ख ख
९ क ० ९९९

गाउयपुधत्तमवरं उक्कस्सं होदि जोयणपुधत्तं ।
विउलमदिस्स य अवरं तस्स पुधत्तं वरं खु णरलोयं ॥४५५॥

गव्यूतिपृथक्त्वमवरमुत्कृष्टं भवति योजनपृथक्त्वं । विपुलमतेरवरं तस्य पृथक्त्वं खलु नरलोकः ॥

ऋजुमतिमनःपर्य्ययज्ञानविषयजघन्यक्षेत्रं गव्यूतिपृथक्त्वमेरडुमूरु क्रोशंगळप्पुवु । क्रो २ । ३ । मदरुत्कृष्टक्षेत्रं योजनपृथक्त्वसप्ताष्टयोजनप्रमाणमक्कुं । यो ७ । ८ । विपुलमतिमनःपर्य्ययज्ञान विषयजघन्यक्षेत्रं तस्य पृथक्त्वमा योजनंगळ पृथक्त्वमष्टयोजननवयोजनप्रमाणमक्कुं । ८ । ९ । तदुत्कृष्टज्ञानविषयोत्कृष्टक्षेत्रं खलु स्फुटमागि । नरलोकः मनुष्यलोकमेनितनितु प्रमाणमक्कुं ।

णरलोएत्ति य वयणं विक्खंभणियामयं ण वट्टस्स ।
जम्हा तग्घणपदरं मणपज्जवखेत्तमुद्दिट्ठं ॥४५६॥

नरलोक इति वचनं विष्कंभनियामकं न वृत्तस्य । यस्मात्तद्घनप्रतरं मनःपर्य्यायक्षेत्रमुद्दिष्टं ॥

विपुलमतिमनःपर्य्ययज्ञानविषयसर्व्वोत्कृष्टक्षेत्रप्रमाणदोळु नरलोक इति वचनं नरलोकमें बी शब्दं सन्मनुष्यक्षेत्रवृत्तविष्कंभनियामकमल्तेके दोडे यस्मात् आवुदोंदु कारणदिदं तद्घनप्रतरमा

तस्मिन् विपुलमतिविषयद्वितीयद्रव्ये असंख्यातकल्पसमयसंख्यैर्ध्रुवहारैर्भक्ते विपुलमतिविषयं सर्वोत्कृष्ट-

द्रव्यं भवति— स ० ० ० ख ख ॥४५४॥
९। क ० ९९९

ऋजुमतिविषयजघन्यक्षेत्रं गव्यूतिपृथक्त्वं द्वित्रिक्रोशाः २ । ३ । उत्कृष्टं योजनपृथक्त्वं सप्ताष्टयोजनानि ७ । ८ । विपुलमतिविषयजघन्यक्षेत्रं योजनपृथक्त्वं अष्टनवयोजनानि । ८ । ९ । उत्कृष्टं स्फुटं नरलोकः ॥४५५॥

यद्विपुलमतिविषयोत्कृष्टक्षेत्रप्ररूपणे नरलोक इति वचनमुक्तं तत् तद्गतविष्कम्भस्य नियामकं निश्चायकं

विपुलमतिके विषयभूत उस दूसरे द्रव्यमें असंख्यात कल्पकालके समयोंकी संख्या जितनी है उतनी बार ध्रुवहारसे भाग देनेपर विपुलमतिके विषयभूत सर्व उत्कृष्टद्रव्य आता है ॥४५४॥

ऋजुमतिका विषयभूत जघन्य क्षेत्र गव्यूति पृथक्त्व अर्थात् दो-तीन कोस है। और उत्कृष्ट क्षेत्र योजन पृथक्त्व अर्थात् सात-आठ योजन है। विपुलमतिका विषयभूत जघन्य क्षेत्र योजन पृथक्त्व अर्थात् आठ-नौ योजन है और उत्कृष्टक्षेत्र मनुष्यलोक है ॥४५५॥

विपुलमतिका विषय उत्कृष्टक्षेत्रका कथन करते हुए जो मनुष्यलोक कहा है वह

तब्विदियं कप्पाणमसंखेज्जाणं च समयसंखसमं ।
धुवहारेणवहरिदे होदि हु उक्कस्सयं दव्वं ॥४५४॥

तद्द्वितीयं कल्पानामसंख्यातानां च समयसंख्यासमं ध्रुवहारेणापहृते भवति खलूत्कृष्टं द्रव्यं ।

तं द्वितीयं विपुलमनःपर्य्ययज्ञानविषयद्वितीयद्रव्यविकल्पमं असंख्यातकल्पंगळ समयंगळ संख्यासमानध्रुवहारंगळिदं भागिसुत्तं विरलु यावत्प्रमाणं लब्धं तावत्प्रमाणं विपुलमतिमनःपर्य्ययज्ञानविषयसर्व्वोत्कृष्टद्रव्यविकल्पमक्कुं खलु स्फुटमागि स ० स स
९ क ० ९९९

गाउयपुधत्तमवरं उक्कस्सं होदि जोयणपुधत्तं ।
विउलमदिस्स य अवरं तस्स पुधत्तं वरं खु णरलोयं ॥४५५॥

गव्यूतिपृथक्त्वमवरमुत्कृष्टं भवति योजनपृथक्त्वं । विपुलमतेरवरं तस्य पृथक्त्वं खलु नरलोकः ॥

ऋजुमतिमनःपर्य्ययज्ञानविषयजघन्यक्षेत्रं गव्यूतिपृथक्त्वमेरडुमूरु क्रोशंगळप्पुवु । क्रो २ । ३ । मवरुत्कृष्टक्षेत्रं योजनपृथक्त्वसप्ताष्टयोजनप्रमाणमक्कुं । यो ७ । ८ । विपुलमतिमनःपर्य्ययज्ञान विषयजघन्यक्षेत्रं तस्य पृथक्त्वमा योजनंगळ पृथक्त्वमष्टयोजननवयोजनप्रमाणमक्कुं । ८ । ९ । तदुत्कृष्टज्ञानविषयोत्कृष्टक्षेत्रं खलु स्फुटमागि । नरलोकः मनुष्यलोकमेनितनितु प्रमाणमक्कुं ।

णरलोएत्ति य वयणं विक्खंभणियामयं ण वट्टस्स ।
जम्हा तग्घणपदरं मणपज्जवखेत्तमुद्दिट्ठं ॥४५६॥

नरलोक इति वचनं विष्कंभनियामकं न वृत्तस्य । यस्मात्तद्घनप्रतरं मनःपर्य्यायक्षेत्रमुद्दिष्टं ॥

विपुलमतिमनःपर्य्ययज्ञानविषयसर्व्वोत्कृष्टक्षेत्रप्रमाणदोळु नरलोक इति वचनं नरलोकमेंबी शब्दं तन्मनुष्यक्षेत्रवृत्तविष्कंभनियामकमल्तेकेंदोडे यस्मात् आवुदोंदु कारणदिदं तद्घनप्रतरमा

तस्मिन् विपुलमतिविषयद्वितीयद्रव्ये असंख्यातकल्पसमयसंख्यैर्ध्रुवहारैर्भक्ते विपुलमतिविषयं सर्वोत्कृष्ट-

द्रव्यं भवति— स ० ० ० स स ॥४५४॥
९ क ० ९ ९ ९

ऋजुमतिविषयजघन्यक्षेत्रं गव्यूतिपृथक्त्वं द्वित्रिक्रोशाः २ । ३ । उत्कृष्टं योजनपृथक्त्वं सप्ताष्टयोजनानि ७ । ८ । विपुलमतिविषयजघन्यक्षेत्रं योजनपृथक्त्वं अष्टनवयोजनानि । ८ । ९ । उत्कृष्टं स्फुटं नरलोकः ॥४५५॥

यद्विपुलमतिविषयोत्कृष्टक्षेत्रप्ररूपणे नरलोक इति वचनमुक्तं तत् तद्गतविष्कम्भस्य नियामकं निश्चायकं

विपुलमतिके विषयभूत उस दूसरे द्रव्यमें असंख्यात कल्पकालके समयोंकी संख्या जितनी है उतनी बार ध्रुवहारसे भाग देनेपर विपुलमतिके विषयभूत सर्व उत्कृष्टद्रव्य आता है ॥४५४॥

ऋजुमतिका विषयभूत जघन्य क्षेत्र गव्यूति पृथक्त्व अर्थात् दो-तीन कोस है। और उत्कृष्ट क्षेत्र योजन पृथक्त्व अर्थात् सात-आठ योजन है। विपुलमतिका विषयभूत जघन्य क्षेत्र योजन पृथक्त्व अर्थात् आठ-नौ योजन है और उत्कृष्टक्षेत्र मनुष्यलोक है ॥४५५॥

विपुलमतिका विषय उत्कृष्टक्षेत्रका कथन करते हुए जो मनुष्यलोक कहा है वह

तव्विदियं कप्पाणमसंखेज्जाणं च समयसंखसमं ।
धुवहारेणवहरिदे होदि हु उक्कस्सयं दव्वं ॥४५४॥

तद्द्वितीयं कल्पानामसंख्यातानां च समयसंख्यासमं ध्रुवहारेणापहृते भवति खलूत्कृष्टं द्रव्यं ।

तं द्वितीयं विपुलमनःपर्ययज्ञानविषयद्वितीयद्रव्यविकल्पमं असंख्यातकल्पंगळ समयंगळ संख्यासमानमप्प ध्रुवहारंगळिदं भागिसुत्तं विरलु आवत्प्रमाणं लब्धं तावत्प्रमाणं विपुलमतिमनःपर्ययज्ञानविषयसर्वोत्कृष्टद्रव्यविकल्पमक्कुं खलु स्फुटमागि स ० स स
९ क ० ९९९

गाउयपुधत्तमवरं उक्कस्सं होदि जोयणपुधत्तं ।
विउलमदिस्स य अवरं तस्स पुधत्तं वरं खु णरलोयं ॥४५५॥

गव्यूतिपृथक्त्वमवरमुत्कृष्टं भवति योजनपृथक्त्वं । विपुलमतेरवरं तस्य पृथक्त्वं खलु नरलोकः ॥

ऋजुमतिमनःपर्ययज्ञानविषयजघन्यक्षेत्रं गव्यूतिपृथक्त्वमक्कुमदु क्रोशंगळप्पुवु । क्रो २ । ३ । मदुत्कृष्टक्षेत्रं योजनपृथक्त्वसप्ताष्टयोजनप्रमाणमक्कुं । यो ७ । ८ । विपुलमतिमनःपर्ययज्ञान विषयजघन्यक्षेत्रं तस्य पृथक्त्वमा योजनंगळ पृथक्त्वमष्टयोजननवयोजनप्रमाणमक्कुं । ८ । ९ । तदुत्कृष्टज्ञानविषयोत्कृष्टक्षेत्रं खलु स्फुटमागि । नरलोकः मनुष्यलोकमेनितनितु प्रमाणमक्कुं ।

णरलोएत्ति य वयणं विक्खंभणियामयं ण वट्टस्स ।
जम्हा तग्घणपदरं मणपज्जवखेत्तमुद्दिट्ठं ॥४५६॥

नरलोक इति वचनं विष्कंभनियामकं न वृत्तस्य । यस्मात्तद्घनप्रतरं मनःपर्ययक्षेत्रमुद्दिष्टं ॥

विपुलमतिमनःपर्ययज्ञानविषयसर्वोत्कृष्टक्षेत्रप्रमाणदोळु नरलोक इति वचनं नरलोकमें बो शब्दं तन्मनुष्यक्षेत्रवृत्तविष्कंभनियामकमल्लेकें दोडे यस्मात् आवुदों दु कारणदिदं तद्घनप्रतरमा

तस्मिन् विपुलमतिविषयद्वितीयद्रव्ये असंख्यातकल्पसमयसंख्यैर्ध्रुवहारैर्भक्ते विपुलमतिविषयं सर्वोत्कृष्ट-
द्रव्यं भवति— स ० ० ० स स ॥४५४॥
९ । क ० ९ ९ ९

ऋजुमतिविषयजघन्यक्षेत्रं गव्यूतिपृथक्त्वं द्वित्रिक्रोशाः २ । ३ । उत्कृष्टं योजनपृथक्त्वं सप्ताष्टयोजनानि ७ । ८ । विपुलमतिविषयजघन्यक्षेत्रं योजनपृथक्त्वं अष्टनवयोजनानि । ८ । ९ । उत्कृष्टं स्फुटं नरलोकः ॥४५५॥

यद्विपुलमतिविषयोत्कृष्टक्षेत्रकथने नरलोक इति वचनमुक्तं तत् तद्वृत्तविष्कम्भस्य नियामकं निश्चायकं

विपुलमतिके विषयभूत उस दूसरे द्रव्यमें असंख्यात कल्पकालके समयोंकी संख्या जितनी है उतनी बार ध्रुवहारसे भाग देनेपर विपुलमतिके विषयभूत सर्व उत्कृष्टद्रव्य आता है ॥४५४॥

ऋजुमतिका विषयभूत जघन्य क्षेत्र गव्यूति पृथक्त्व अर्थात् दो-
उत्कृष्ट क्षेत्र योजन पृथक्त्व अर्थात् सात-आठ योजन है। विपुलम
क्षेत्र योजन पृथक्त्व अर्थात् आठ-नौ योजन है और उत्कृष्टक्षेत्र

विपुलमतिका विषय उत्कृष्टक्षेत्रका कथन करते हुए

आवलिअसंखभागं अवरं च वरं च वरमसंखगुणं ।
तत्तो असंखगुणिदं असंखलोगं तु विउलमदी ॥४५८॥

आवल्यसंख्यभागो अवरश्च वरश्च वरोऽसंख्यगुणः ततोऽसंख्यगुणितः असंख्यलोकस्तु विपुलमतेः ॥

भावं प्रति वर्त्ति । ऋजुमतिमनःपर्ययज्ञानविषयजघन्यमावल्यसंख्यातैकभागमक्कुमुत्कृष्टमुमंते आवल्यसंख्यभागमक्कुमादोडे जघन्यम नोडलसंख्यातगुणमक्कुं । ततः आ ऋजुमतिमनःपर्ययज्ञानविषयोत्कृष्टभावप्रमाणमं नोडलु विपुलमतिमनःपर्ययज्ञानविषयजघन्यभावमसंख्यातगुणितमक्कुमा विपुलमतिमनःपर्ययज्ञानविषयोत्कृष्टभावं मु मत्ते असंख्यातलोकः असंख्यातलोकमात्रमक्कुं । ≡a ।

मज्झिमदव्वं खेत्तं कालं भावं च मज्झिमं णाणं ।
जाणदि इदि मणपज्जवणाणं कहिदं समासेण ॥४५९॥

मध्यमद्रव्यं क्षेत्रं कालं भावं च मध्यमज्ञानं जानाति । इतिमनःपर्ययज्ञानं कथितं समासेन ॥

ऋजुमतिमनःपर्ययज्ञानजघन्योत्कृष्टज्ञानंगळुं विपुलमतिमनःपर्ययजघन्योत्कृष्टज्ञानंगळुं ई पेळल्पट्ट तंतम्म जघन्योत्कृष्टद्रव्यक्षेत्रकालभावंगळनरियुवुवु मध्यमज्ञानविकल्पंगळु तंतम्म मध्यमद्रव्यक्षेत्रकालभावंगळनरियवितु मनःपर्ययज्ञानं संक्षेपदिदं पेळल्पट्टुदु । तद्द्रव्यक्षेत्रकालभावंगळ्गे संदृष्टि :—

भावं प्रति ऋजुमतेर्विषयजघन्यं आवल्यसंख्यातैकभागः ८ । उत्कृष्टं तदालापमपि जघन्यादसंख्यात-
a a a
गुणं ८ a । ९५. विपुलमतेर्विषयजघन्यमसंख्यातगुणं ८ a a उत्कृष्टं तु पुनः असंख्यातलोकः ।≡a॥४५८॥
a a a a a a

ऋजुविपुलमत्योः जघन्योत्कृष्टविकल्पौ उक्तस्वस्वजघन्योत्कृष्टद्रव्यक्षेत्रकालभावान् जानीतः । मध्यमविकल्पास्तु स्वस्वमध्यमद्रव्यक्षेत्रकालभावान् जानन्ति इत्येवं मनःपर्ययज्ञानं संक्षेपेणोक्तम् ॥४५९॥

भावकी अपेक्षा ऋजुमतिका जघन्य विषय आवलीका असंख्यातवाँ भाग है। उत्कृष्ट भी उतना ही है किन्तु जघन्यसे असंख्यातगुणा है। उससे विपुलमतिका जघन्य विषय असंख्यातगुणा है और उत्कृष्ट असंख्यात लोक है ॥४५८॥

ऋजुमति और विपुलमतिके जघन्य और उत्कृष्ट भेद अपने-अपने जघन्य और उत्कृष्ट द्रव्य-क्षेत्र-काल और भावोंको जानते हैं। तथा मध्यमभेद अपने-अपने मध्यम क्षेत्र-काल-भाव-को जानते हैं। इस प्रकार मनःपर्ययज्ञानका संक्षेपसे कथन किया ॥४५९॥

अनंतरं ज्ञानमार्गणेयोळ् जीवसंख्येयं पेळ्वपं ।

चदुगदिमदिसुदबोहा पल्लासंखेज्जया हु मणपज्जा ।
संखेज्जा केवलिणो सिद्धादो होंति अदिरित्ता ॥४६१॥

चतुर्गतिमतिश्रुतबोधाः पल्यासंख्येयमात्राः खलु मनःपर्य्ययज्ञानिनः संख्येयाः केवलिनः सिद्धेभ्यो भवंत्यतिरिक्ताः ॥

चतुर्गतिय मतिज्ञानिगळुं श्रुतज्ञानिगळुं प्रत्येकं पल्यासंख्यातभागप्रमितरु स्फुटमागि । म । प । श्रु । प । मनःपर्य्ययज्ञानिगळु संख्यातप्रमितरेयप्पुवु । १ । केवलज्ञानिगळु सिद्धरं नोडे ꣵ जिनर संख्येयिदं साधिकरप्परु १ । ३

ओहिरहिदा तिरिक्खा मदिणाणिअसंखभागगा मणुवा ।
संखेज्जा हु तदूणा मदिणाणी ओहिपरिमाणं ॥४६२॥

अवधिरहितास्तिर्य्यंचो मतिज्ञान्यसंख्यभागप्रमिता मानवाः । संख्येयाः खलु तदूना मतिज्ञानिनो अवधिज्ञानिनः परिमाणं ॥

अवधिज्ञानरहिततिर्य्यंचरु मतिज्ञानिगळ संख्येयं नोडलसंख्यातभागप्रमितरप्परु प १ ꣵ ꣵ अवधिरहितमनुष्यरु संख्यातप्रमितरप्परु- । १ । मी येरडु राशिगळिदं प १ ꣵ १ ꣵ हीनमप्प मतिज्ञानिगळ संख्ये अवधिज्ञानिगळ परिमाणमक्कु प ꣵ ꣵ ꣵ

मन्तव्यम् ॥४६०॥ अथ ज्ञानमार्गणायां जीवसंख्यामाह—

चतुर्गतेर्मतिज्ञानिनः श्रुतज्ञानिनश्च प्रत्येकं पल्यासंख्यातैकभागमात्राः स्युः स्फुटं म प ꣵ श्रु प ꣵ । मनःपर्ययज्ञानिनः संख्याताः १ । केवलज्ञानिनः जिनसंख्यया समधिकसिद्धराशिः ३ ॥४६१॥

अवधिज्ञानरहिततिर्यञ्च मतिज्ञानिसंख्याया असंख्येयभागः प १ ꣵ ꣵ । अवधिरहितमनुष्याः संख्याताः १ एतद्राशिद्वयोना मतिज्ञानसंख्यैव चतुर्गत्यवधिज्ञानपरिमाणं भवति प ꣵ-१ ꣵ ꣵ ॥४६२॥

अथ ज्ञानमार्गणामें जीवोंकी संख्या कहते हैं—

चारों गतियोंमें मतिज्ञानी पल्यके असंख्यातवें भाग हैं और श्रुतज्ञानी भी पल्यके असंख्यातवें भाग हैं। मनःपर्ययज्ञानी संख्यात हैं। और केवलज्ञानी सिद्धराशिमें तेरहवें और चौदहवें गुणस्थानके जिनोंकी संख्या मिलानेपर जो प्रमाण हो उतने हैं ॥४६१॥

अवधिज्ञानसे रहित तिर्यंच मतिज्ञानियोंकी संख्यासे असंख्यातवें भाग हैं। अवधिज्ञानसे रहित मनुष्य संख्यात हैं। मतिज्ञानियोंकी संख्यामें ये दोनों राशि घटा देनेपर चारों गतिके अवधिज्ञानियोंका प्रमाण होता है ॥४६२॥

मतिश्रुतावधिमनःपर्य्ययकेवलज्ञानिगळ संख्येगळनप्दु राशिगळं कूडिदोडे केवलज्ञानिगळ संख्येय मेले साधिकमक्कु ७ (1/३) मी राशियं सर्व्वजीवराशियोळु १६ कळेयुत्तिरलुळिद शेषं १३– प्रत्येकं मत्यज्ञानिगळ संख्येयुं श्रुताज्ञानिगळ संख्येयुमक्कु १३।१३ । मितु पेळल्पट्ट संख्येगळ संदृष्टि चतुर्गतियक्कु । मतिज्ञानिगळु १३–। चतुर्गतियक्कु श्रुतज्ञानिगळु १३–। चतुर्गतिय विभंगज्ञानिगळु ≡ ४।६५ = १ चतुर्गतियमतिज्ञानिगळु प चतुर्गतिय श्रुतज्ञानिगळु प चतुर्गतिय अवधिज्ञानिगळु प ० मनुष्यगतियमनःपर्य्ययज्ञानिगळु १ केवलज्ञानिगळु सिद्धरुं जिनरुं १/३ तिर्य्यग्गतिय विभंगज्ञानिगळु ६ प मनुष्यगतिय विभंगज्ञानिगळु १ नारकविभंगज्ञानिगळु—२—। देवविभंगज्ञानिगळु = १ / ४।६५=१ संदृष्टिः—

कुमति	कुश्रुत	विभंग	मति	श्रुत	अवधि	मनः	केवल	तिरि-विभंग ॥
१३–	१३–	≡ / ४।६५ – १	प	प	प	१	१/३	– ६ प

मनु-विभंग	नारक-विभंग	देव-विभंग
१	—२—	= १ / ४।६५ – १

इंतु भगवदर्हत्परमेश्वरचारुचरणारविंदद्वंद्ववंदनानंदित पुण्यपुंजायमान श्रीमद्रायराजगुरुमंडलाचार्य्यमहावादवादीश्वररायवादिपितामह सकलविद्वज्जनचक्रवर्त्तिश्रीमदभयसूरिसिद्धांतचक्रवर्त्ति श्रीपादपंकजरजोरंजितललाटपट्टं श्रीमत्केशवण्णविरचितमप्प गोम्मटसारकर्णाटकवृत्ति जीवतत्त्वप्रदीपिकेयोळु जीवकांडविंशतिप्ररूपणंगळोळु द्वादशज्ञानमार्ग्गणामहाधिकारं समाप्तमाप्तु ॥

मत्यादिसम्यग्ज्ञानराशिपञ्चकेन साधिककेवलिराशिमात्रेण १/३ सर्वजीवराशि- १६ हीनस्तदा १३–प्रत्येकं मतिश्रुताज्ञानिपरिमाणं स्यात् ॥४६४॥

मति आदि पाँच सम्यग्ज्ञानियोंकी संख्या केवलज्ञानियोंके संख्यासे कुछ अधिक है। इसको सर्वजीवराशिमें-से घटानेपर मतिअज्ञानी और श्रुतअज्ञानी जीवका परिमाण होता है ॥४६४॥

संयममार्गणा ॥१३॥

ज्ञानमार्गणा स्वरूपमं पेळ्दनंतरं संयममार्गणास्वरूपमं पेळल्वेडि मुंदण सूत्रमं पेळ्दपं—

वदसमिदिकसायाणं दंडाण तहिंदियाण पंचण्हं ।
धारण-पालणणिग्गहचागजओ संजमो भणियो ॥४६५॥

व्रतसमितिकषायाणां दंडानां तथेंद्रियाणां पंचानां । धारणपालननिग्रहत्यागजयः संयमो भणितः ॥

व्रतसमितिकषायदंडेंद्रियंगळें बो इवु यथासंख्यमागि धारणपालननिग्रहत्यागजयं संयममें बुदु परमागमदोळ्पेळल्पट्टुदु । व्रतधारणं समितिपालनं कषायनिग्रहं दंडत्यागमिंद्रियजयमें बो पंचप्रकारमनुळ्ळुदु संयममें बुदत्थं । सम् सम्यग्यमनं संयमः एंदिती निरुक्तिगनुरूपलक्षणं संयमक्के पेळल्पट्टुदें बुदु तात्पर्य्यं ।

बादरसंजलणुदए सुहुमुदए समखए-य मोहस्स ।
संजमभावो णियमा होदित्ति जिणेहि णिद्दिट्ठं ॥४६६॥

बादरसंज्वलनोदये सूक्ष्मोदये उपशमे क्षये च मोहस्य । संयमभावो नियमात् भवतीति जिनैर्न्निर्द्दिष्टः ॥

बादरसंज्वलनोदयदोळ् सूक्ष्मलोभोदयदोळं मोहनीयकर्म्मोपशमदोळं क्षयदोळं नियमदिदं संयमभावमक्कुमें बु अर्हदादिगळिदं पेळल्पट्टुदु ।

विदर्भ विमलयन्स्वीयैर्गुणैर्विश्वातिशायिभिः ।
विमलस्तीर्थकर्ता यो वन्दे तं तत्पदाप्तये ॥१३॥

अथ ज्ञानमार्गणां प्ररूप्येदानीं संयममार्गणामाह—

व्रतसमितिकषायदण्डेन्द्रियाणां पञ्चानां यथासंख्यं धारणपालननिग्रहत्यागजयाः संयमो भणितः । व्रतधारणं समितिपालनं कषायनिग्रहः दण्डत्यागः इन्द्रियजयः इति पञ्च च संयम इत्यर्थः । सं—सम्यक् यमनं संयमः ॥४६५॥

बादरसंज्वलनोदये सूक्ष्मलोभोदये मोहनीयोपशमे क्षये च नियमेन संयमभावः स्यात् । तथा हि—प्रमत्ता-

---

ज्ञानमार्गणाकी प्ररूपणा करके अब संयममार्गणाकी प्ररूपणा करते हैं—व्रत, समिति, कषाय, मन-वचन कायरूप दण्ड और इन्द्रियोंका यथाक्रम धारण, पालन, निग्रह, त्याग और जयको संयम कहा है । अर्थात् व्रतोंका धारण, समितियोंका पालन, कषायोंका निग्रह, दण्डोंका त्याग और इन्द्रियोंका जय इस प्रकार पाँच प्रकारका संयम है । 'सं' अर्थात् सम्यक्रूपसे यमको संयम कहते हैं ॥४६५॥

बादर संज्वलन कषायका उदय होते, सूक्ष्म लोभकषायका उदय रहते तथा मोहनीयका उपशम और क्षय होनेपर नियमसे संयमभाव होता है ऐसा जिनदेवने कहा है। इसका

गुणमक्कुं ।

जहखादसंजमो पुण उवसमदो होदि मोहणीयस्स ।
खयदो वि य सो णियमा होदि त्ति जिणेहि णिद्दिट्ठं ॥४६८॥

यथाख्यातसंयमः पुनरुपशमाद्भवति मोहनीयस्य । क्षयतोपि च ॥ नियमाद् भवति इति जिनैर्निर्दिष्टं ॥

यथाख्यातसंयमं मत्ते मोहनीयदुपशमदिंदमक्कुं । मोहनीयनिरवशेषक्षयदिंदमुं आ यथाख्यातसंयमं नियमदिंदमक्कुमेंदितु जिनरुगळिंदं पेळल्पट्टुदु ।

तदियकसायुदयेण य विरदाविरदो गुणो हवे जुगवं ।
बिदियकसायुदयेण य असंजमो होदि णियमेण ॥४६९॥

तृतीयकषायोदयेन च विरताविरतगुणो भवेद्युगपत् । द्वितीयकषायोदयेन च असंयमो भवति नियमेन ॥

प्रत्याख्यानावरणतृतीयकषायोदयदिंदं विरताविरतगुणमोम्मों दलोळेयक्कुं । संयममुमसंयममुमोम्मों दलोळेयक्कुमकारणमागि सम्यग्मिथ्यादृष्टियें तंते देशसंयतनुं मिश्रसंयमियक्कुमेंबुदत्थं । द्वितीयकषायोदयदोळप्रत्याख्यानकषायोदयदोळसंयमं नियमदिंदमक्कुं ।

संगहिय सयलसंजममेयजममणुत्तरं दुरवगम्मं ।
जीवो समुव्वहंतो सामाइयसंजदो होदि ॥४७०॥

संगृह्य सकलसंयममेकयममनुत्तरं दुरवगम्यं । जीवःसमुद्वहन् सामायिकसंयमो भवति ॥

संगृह्य सकलसंयमं व्रतधारणादिपंचविधमप्पसंयममं युगपत्सर्वसावद्याद्विरतोस्मि येंदितु संग्रहिसि संक्षेपिसि एकयमं भेदरहितसकलसावद्यनिवृत्तिस्वरूपमप्प एकयमुमं अनुत्तरं असदृशं

सूक्ष्मसांपरायसंयमगुणो भवति ॥४६७॥

स यथाख्यातसंयमः पुनः मोहनीयस्योपशमतः निरवशेषक्षयतश्च नियमेन भवतीति जिनैरुक्तम् ॥४६८॥

प्रत्याख्यानकषायोदयेन विरताविरतगुणो युगपद् भवति, संयमासंयमयोर्युगपत्संभवात् । सम्यग्मिथ्यादृष्टिवद्देशसंयतोऽपि मिश्रसंयमीत्यर्थः । अप्रत्याख्यानकषायोदये असंयमो नियमेन भवति ॥४६९॥

सकलसंयमं—व्रतधारणादिपञ्चविधं युगपत्सर्वसावद्याद्विरतोऽस्मीति संगृह्य—संक्षिप्य, एकयम—भेदरहित-

पर्यन्त होते हैं। सूक्ष्मकृष्टिको प्राप्त संज्वलन लोभका उदय होते हुए सूक्ष्म साम्पराय नामक संयमगुण होता है ॥४६७॥

यथाख्यात संयम नियमसे मोहनीयके उपशमसे अथवा सम्पूर्ण क्षयसे होता है ऐसा जिनदेवने कहा है ॥४६८॥

तीसरी प्रत्याख्यान कषायके उदयसे एक साथ विरतअविरतरूप गुण होता है क्योंकि संयम और असंयम एक साथ होते हैं। अर्थात् जैसे तीसरे गुणस्थानमें सम्यक्त्व और मिथ्यात्व मिले-जुले होते हैं वैसे ही देशसंयत नामक पंचम गुणस्थानमें संयम और असंयम मिला हुआ होता है। दूसरी अप्रत्याख्यान कषायके उदयमें नियमसे असंयम होता है ॥४६९॥

व्रतधारण आदि रूप पाँच प्रकारके सकल संयमको एक साथ 'मैं सबसे सावद्यसे विरत हूँ' इस प्रकार संगृहीत करके एक यम रूपसे धारण करना सामायिक संयम है।

पंचसमितयोऽस्यसंतीति पंचसमितः। पंचसमितियुतनुं तिस्रो गुप्तयोऽस्मिन्निति त्रिगुप्तः त्रिगुप्तिगळोळ्कूडिदनु सदापि सर्व्वदापि एल्ला कालमुं सावद्यं प्राणिवधमं परिहरति परिहरिसुगुं। यः आवनोर्व्वं पंचैकयमः पंचैकयमनुळ्ळ पुरुषः पुरुषनु सः आतं परिहारकसंयतः खलु परिहारविशुद्धिसंयतनक्कुं स्फुटमागि।

वीसं वासो जम्मे वासपुधत्तं खु तित्थयरमूले।
पच्चक्खाणं पढिदो संझूणदुगाउयविहारो ॥४७३॥

त्रिंशद्वर्षो जन्मनि वर्षपृथक्त्वं खलु तीर्त्थंकरमूले। प्रत्याख्यानं पठितः संध्योनद्विगव्यूतिविहारः॥

जन्मदोळु त्रिंशद्वर्षमनुळ्ळं सर्व्वदा सुखियप्पं मत्तु दीक्षेगोंडु वर्षपृथक्त्वं बरं तीर्त्थंकरश्रीपादमूलदोळु प्रत्याख्यानमें बो भत्तनय पूर्व्वमं पठियिसिदातं परिहारविशुद्धिसंयममं कैकोंडु संध्यात्रयन्यूनसर्व्वकालदोळरडु क्रोशप्रमाणविहारमनुळ्ळं रात्रियोळ्विहाररहितनुं प्रावृट्कालनियममिल्लदनुं परिहारविशुद्धिसंयमनक्कुं। परिहरणं परिहारः प्राणिवधान्निवृत्तिस्तेन परिहारेण विशिष्टा शुद्धिर्य्यस्मिन् स परिहारविशुद्धिसंयमो यस्य स परिहारविशुद्धिसंयमः ई परिहारविशुद्धिसंयमक्के जघन्यकालमंतर्म्मुहूर्त्तमक्कुमेके दोडे परिहारविशुद्धिसंयमं पोर्द्दि जघन्यकालपर्य्यंतमिर्द्दन्यगुणस्थानमं पोर्द्दिदपं तदंतर्म्मुहूर्त्तकालसंभवमक्कुमप्पुदरिदं। उत्कृष्टदिंदमष्टत्रिंशद्वर्षन्यूनपूर्व्वकोटिवर्षमक्कुमेके दोडे पुट्टिदिदिनं मोदल्गोंडु मूवत्तु वर्षंबरं सर्व्वदा सुखियागि कालमं कळेदु संयममं पोर्द्दि मेले वर्षपृथक्त्वं बरं तीर्त्थंकरश्रीपादमूलदोळु प्रत्याख्यानमें ब

पञ्चसमितिसमेतः त्रिगुप्तियुतः सदापि प्राणिवधं परिहरति, यः पञ्चानां सामायिकादीनां मध्ये परिहारविशुद्धिनामैकसंयमः पुरुषः सः परिहारविशुद्धिसंयतः स्फुटं भवति ॥४७२॥

जन्मनि त्रिंशद्वर्षकः सर्वदा सुखी भूत्वा दीक्षां गृहीत्वा वर्षपृथक्त्वपर्यन्तं तीर्थंकरश्रीपादमूले प्रत्याख्यानं नवमपूर्वं पठित्वा स परिहारविशुद्धिसंयमं स्वीकृत्य संध्यात्रयोनसर्वकाले द्विक्रोशप्रमाणविहारी रात्रौ विहाररहितः प्रावृट्कालनियमरहितः परिहारविशुद्धिसंयतो भवति। परिहरणं परिहारः, प्राणिवधान्निवृत्तिः, तेन विशिष्टा शुद्धिर्यस्मिन् स परिहारविशुद्धिः, स संयमो यस्य स परिहारविशुद्धिसंयमः, तस्य जघन्यकालोऽन्तर्मुहूर्तः, जघन्येन तावत्कालमेव तत्र स्थित्वा गुणस्थानान्तरगमनात्। उत्कृष्टः अष्टत्रिंशद्वर्षोनपूर्वकोटिः, उत्पत्ति-

जो पाँच समिति और तीन गुप्तियोंसे युक्त होकर सदा ही प्राणिवधसे दूर रहता है वह सामायिक आदि पाँच संयमोंमें-से परिहारविशुद्धि नामक एक संयमको धारण करनेसे परिहारविशुद्धि संयमी होता है ॥४७२॥

जन्म से तीस वर्ष तक सर्वदा सुखपूर्वक रहते हुए उसे त्याग दीक्षा ग्रहण करके वर्षपृथक्त्वपर्यन्त तीर्थंकरके पादमूलमें जिसने प्रत्याख्यान नामक नौवें पूर्वको पढ़ा है वह परिहारविशुद्धि संयमको स्वीकार करके सदा काल तीनों सन्ध्याओंको छोड़कर दो कोस प्रमाण विहार करता है, रात्रिमें विहार नहीं करता, वर्षाकालमें उसके विहार न करनेका नियम नहीं रहता, वह परिहारविशुद्धि संयमी होता है। परिहरण अर्थात् प्राणिहिंसासे निवृत्तिको परिहार कहते हैं। उससे विशिष्ट शुद्धि जिसमें है वह परिहारविशुद्धि है। वह संयम जिसके होता है वह परिहारविशुद्धि संयमी है। उसका जघन्य काल अन्तर्मुहूर्त है क्योंकि कमसे कम इतने काल पर्यन्त ही उस संयममें रहकर अन्य गुणस्थानोंमें चला जाता है। उत्कृष्ट काल अड़तीस वर्ष कम एक पूर्व कोटि है क्योंकि उत्पत्ति दिनसे लेकर तीस वर्ष

त्मस्वभावावस्थापेक्षालक्षणं यथाख्यातं चारित्रमित्याख्यायते।

पंचतिहिचउविहेहि य अणुगुणसिक्खावएहि संजुत्ता।
उच्चंति देसविरया सम्माइट्ठी झलियकम्मा ॥४७६॥

पंचत्रिचतुर्व्विधैश्च अणुगुणशिक्षाव्रतैः संयुक्ताः। उच्यंते देशविरताः सम्यग्दृष्टयो झटित-कर्म्माणः ॥

पंचविधाणुव्रतंगळिदं त्रिविधगुणव्रतंगळिदं चतुर्व्विधशिक्षाव्रतंगळिदं संयुक्तरप्प सम्यग्दृष्टि-गळु कर्म्मनिर्जरेयोळ्कूडिदवर्गळु देशविरतरेंदु परमागमदोळ्पेळल्पट्टर।

दंसणवदसामायियपोसहसचित्तराइभत्ते य।
बम्हारंभपरिग्गह अणुमणमुद्दिट्ठ देसविरदेदे ॥४७७॥

दर्शनिकव्रतिकसामायिकप्रोषधोपवाससचित्तविरत-रात्रिभक्तविरतब्रह्मचार्यारंभविरतपरि-ग्रहविरतानुमतिविरतोद्दिष्टविरताः देशविरता एते ॥

इल्लि नामैकदेशो नाम्नि वर्त्तते एंबी न्यायदिदं गाथे माडल्पट्टुदु। आ देशविरतभेदंगळ्गेनो-दपुवदेंतेंदोडे दर्शनिकनुं व्रतिकनुं सामायिकनुं प्रोषधोपवासनुं सचित्तविरतनुं रात्रिभक्तविर-तनुं ब्रह्मचारियुं . आरंभविरतनुं परिग्रहविरतनुमनुमतिविरतनुमुद्दिष्टविरतनुमेंदितिल्लि दर्शनिकनेंबं।

"पंचुंबरसहियाइं सत्तइ वसणाइ जो विवज्जेइ।
सम्मत्तविसुद्धमई सो दंसणसावओ भणियो ॥" [वसु. श्रा ५७]

यथाख्यातचारित्रमित्याख्यायते ॥४७५॥

पञ्चत्रिचतुरणुगुणशिक्षाव्रतैः संयुक्तसम्यग्दृष्टयः कर्मनिर्जरावन्तः ते देशविरताः इति परमागमे उच्यन्ते ॥४७६॥

अत्र नामैकदेशो नाम्नि वर्तते इति नियमात् गाथार्थो व्याख्यायते। दर्शनिकः, व्रतिकः, सामायिकः, प्रोषधोपवासः, सचित्तविरतः, रात्रिभक्तविरतः, ब्रह्मचारी, आरम्भविरतः, परिग्रहविरतः, अनुमतिविरतः, उद्दिष्टविरतश्चेत्येकादशैते विरतभेदाः। तत्र—"पञ्चुंबरसहियाइं सत्तइ वसणाणि जो विवज्जेई। सम्मत्तविसुद्धमई सो दंसणसावओ भणिओ।" (वसु श्रा ५७) इत्यादिलक्षणानि ग्रन्थान्तरेऽवगन्तव्यानि ॥४७७॥

समस्त मोहनीय कर्मके उपशम अथवा क्षयसे आत्मस्वभावकी अवस्थारूप लक्षणवाला यथाख्यात चारित्र कहलाता है ॥४७५॥

पाँच अणुव्रत, तीन गुणव्रत और चार शिक्षाव्रतोंसे संयुक्त सम्यग्दृष्टी जो कर्मोंकी निर्जरा करते हैं उन्हें परमागममें देशविरत कहते हैं ॥४७६॥

यहाँ नामका एकदेश नामका वाचक होता है इस नियमके अनुसार गाथाका अर्थ कहते हैं—दर्शनिक, व्रतिक, सामायिक, प्रोषधोपवास, सचित्तविरत, रात्रिभक्तविरत, ब्रह्मचारी, आरम्भविरत, परिग्रहविरत, अनुमतिविरत और उद्दिष्टविरत ये ग्यारह देश-विरतके भेद हैं। पाँच उदुम्बरादिकके साथ सात व्यसनोंको जो छोड़ता है उस विशुद्ध सम्यक्त्वधारीको दर्शनिक श्रावक कहते हैं। इत्यादि इन भेदोंके लक्षण अन्य ग्रन्थोंसे जानना ॥४७७॥

प्रमत्तादिचतुर्णांयुतिः सामायिकद्विकं प्रमत्तर संख्यें ५९३९८२०६। अप्रमत्तरसंख्यें २९६९९१०३। उपशमकापूर्व्वंकरणरु। २९९। उपशमकानिवृत्तिकरणरु २९९। क्षपकापूर्व्वंकरणरु ५९८। क्षपकानिवृत्तिकरणरु ५९८। इंतु प्रमत्तादिचतुर्ग्गुणस्थानवर्त्तिगळ युति प्रत्येकसामायिक-संयमिगळसंख्येयु छेदोपस्थापनसंयमिगळ संख्येयक्कुमेके बोडे सामायिकसंयमिगळेनिबरनिबरे छेदोपस्थापनसंयमिगळप्पुदरिदं। ८२०९९१०३। ८९०९९१०३। क्रमदिव शेषत्रयं परिहार-विशुद्धिसंयमिगळ संख्येयु सूक्ष्मसांपरायसंयमिगळ संख्येयुं यथाख्यातसंयमिगळ संख्येयुं त्रिरूपोन-सप्तसहस्रमुं ६९९७। त्रिरूपोननवशतमुं ८९७। त्रिरूपोननवलक्षमुमक्कुं। ८९९९९७।

पल्लासंखेज्जदिमं विरदाविरदाण दव्वपरिमाणं।
पुव्वुत्तरासिहीणो संसारी अविरदाण पमा ॥४८१॥

पल्यासंख्येयभागो विरताविरतानां द्रव्यप्रमाणं। पूर्व्वोक्तराशिहीनः संसारी अविरतानां प्रमा ॥

पल्यासंख्यातैकभागं देशसंयतजीवद्रव्यप्रमाणमक्कु प / a a ४ a मी पूर्व्वोक्तयद्राशिविहीन-

---

प्रमत्ताः ५, ९३, ९८, २०६ अप्रमत्ताः २, ९६, ९९, १०३, उपशमकापूर्वकरणाः २९९, उपशम-कानिवृत्तिकरणाः २९९, क्षपकापूर्वकरणाः ५९८, क्षपकानिवृत्तिकरणाः ५९८, एषां चतुर्णां युतिः प्रत्येकं सामायिकछेदोपस्थापनसंयमिसंख्या भवति उभयत्र समसंख्यात्वात् ८, ९०, ९९, १०३। ८, ९०, ९९, १०३। परिहारविशुद्धिसूक्ष्मसांपराययथाख्यातसंयमिसंख्या क्रमेण त्रिरूपोनसप्तसहस्रं ६९९७ त्रिरूपोननवशतं ८९७, त्रिरूपोननवलक्षं ८९९९९७ भवति ॥४८०॥

पल्यासंख्यातैकभागो देशसंयतजीवद्रव्यप्रमाणं भवति प / a a ४ a एतत्पूर्वोक्तयद्राशिविहीनसंसारिराशिरेव

प्रमत्तादि चार गुणस्थानवर्ती जीवोंका जितना जोड़ है उतने ही सामायिक और छेदोपस्थापना संयमी होते हैं। सो प्रमत्तसंयत पाँच करोड़ तिरानबे लाख, अठानबे हजार दो सौ छह ५९३९८२०६, अप्रमत्तसंयत दो करोड़ छियानबे लाख, निन्यानबे हजार एक सौ तीन २९६९९१०३, उपशम श्रेणीवाले अपूर्वकरण गुणस्थानवर्ती दो सौ निन्यानबे २९९, उपशम श्रेणिवाले अपूर्वकरण गुणस्थानवर्ती दो सौ निन्यानबे २९९, उपशम श्रेणिवाले अनिवृत्तिकरण गुणस्थानवर्ती दो सौ निन्यानबे २९९, क्षपक श्रेणिवाले अपूर्वकरण पाँचसौ अठानबे, क्षपक-श्रेणिवाले अनिवृत्तिकरण पाँचसौ अठानवे ५९८ इन सबका जोड़ आठ करोड़, नब्बे लाख, निन्यानबे हजार एक सौ तीन ८९०९९१०३ इतने जीव सामायिक संयमी और इतने ही छेदोपस्थापना संयमी होते हैं। दोनोंकी संख्या समान होती है। परिहार विशुद्धि संयतोंकी संख्या तीन कम सात हजार ६९९७ है। सूक्ष्मसाम्पराय संयमियोंकी संख्या तीन कम नौ सौ ८९७ है। यथाख्यात संयतोंकी संख्या तीन कम नौ लाख ८९९९९७ है ॥४८०॥

पल्यके असंख्यातवें भाग देश संयमी जीवोंका प्रमाण है। इन छहों राशियोंको

दर्शन-मार्गणा ॥१४॥

संयममार्गणानंतरं दर्शनमार्गणेयं पेळ्दपं :—

जं सामण्णं गहणं भावाणं णेव कट्टुमायारं ।
अविसेसिदूण अट्ठे दंसणमिदि भण्णये समये ॥४८२॥

यत्सामान्यग्रहणं भावानां नैव कृत्वाऽऽकारमविशेष्यार्थान्दर्शनमिति भण्यते समये ॥

भावानां सामान्यविशेषात्मकबाह्यपदार्थंगळ आकारं नैव कृत्वा भेदग्रहणमं माडदे यत्सामान्यग्रहणं आवुदों दु स्वरूपमात्रमं कैकोळ्वुदु दर्शनमें दितु परमागमदोळु पेळल्पट्टुदु ।

वस्तुस्वरूपमात्रग्रहणमें तें दोडे अर्थाविशेष्य बाह्यार्थंगळं जातिक्रियागुणप्रकारंगळिदं विकल्पिसदे स्वपरसत्तावभासनं दर्शनमें दितु पेळल्पट्टुदें बुदर्थं । मत्तमोयर्थमनें विशदं माडिदपं—

भावाणं सामण्णविसेसयाणं सरूवमेत्तं जं ।
वण्णणहीणग्गहणं जीवेण य दंसणं होदि ॥४८३॥

भावानां सामान्यविशेषात्मकानां स्वरूपमात्रं यद्वर्णनहीनग्रहणं जीवेन च दर्शनं भवति ॥

सामान्यविशेषात्मकंगळप्प पदार्थंगळ आवुदों दु स्वरूपमात्रं विकल्परहितमागि जीवनिदं स्वपरसत्तावभासनमदु दर्शनमें बुदक्कुं । पश्यति दृश्यतेऽनेन दर्शनमात्रं वा दर्शनमें दितु कर्तृकरण-

---

अनन्तानन्दसंसारसागरोत्तारसेतुकम् ।
अनन्तं तीर्थकर्तारं वन्देऽनन्तमुदे सदा ॥१४॥

अथ संयममार्गणां व्याख्याय दर्शनमार्गणां व्याख्याति—

भावानां सामान्यविशेषात्मकबाह्यपदार्थानां आकारं–भेदग्रहणं, अकृत्वा यत्सामान्यग्रहणं–स्वरूपमात्रावभासनं तद् दर्शनमिति परमागमे भण्यते । वस्तुस्वरूपमात्रग्रहणं कथम् ? अर्थात्–बाह्यपदार्थान् अविशेष्य–जातिक्रियाग्रहणविकारैरविकल्प्य स्वपरसत्तावभासनं दर्शनमित्यर्थः ॥४८२॥ अमुमेवार्थं विशदयति—

भावानां सामान्यविशेषात्मकपदार्थानां यत्स्वरूपमात्रं विकल्परहितं यथा भवति तथा जीवेन स्वपर-

---

संयममार्गणाको कहकर दर्शन मार्गणाको कहते हैं—

भाव अर्थात् सामान्य विशेषात्मक पदार्थोंके आकार अर्थात् भेदग्रहण न करके जो सामान्य ग्रहण अर्थात् स्वरूपमात्रका अवभासन है, उसे परमागममें दर्शन कहते हैं। वस्तु-स्वरूपमात्रका ग्रहण कैसे करता है ? अर्थात् पदार्थके जाति, क्रिया, गुण आदि विकारोंका विकल्प न करते हुए अपना और अन्यका केवल सत्तामात्रका अवभासन दर्शन है ॥४८२॥

इसी अर्थको स्पष्ट करते हैं—

सामान्य विशेषात्मक पदार्थोंका विकल्परहित स्वरूपमात्र जैसा है वैसा जीवके साथ स्वपर सत्ताका अवभासन दर्शन है। जो देखता है, जिसके द्वारा देखा जाता है या देखना

बहुविधंगळु बहुप्रकारंगळुमप्पवेळगुगळु चंद्रसूर्य्यरत्नादिप्रकाशंगळु लोकदोळ्परिमितक्षेत्रदोळेयप्पुवाद वेळगुगळिंदं पवणिसल्पडद लोकालोकंगळोळापुवोंदु विगततिमिरमप्पुदद्दु केवलदर्शनोद्योतमक्कुं।

अनंतरं दर्शनमार्गणेयोळु जीवसंख्येयं गाथाद्वयदिदं पेळ्वपं :—

जोगे चउरक्खाणं पञ्चक्खाणं च खीणचरिमाणं।
चक्खूणमोहिकेवलपरिमाणं ताण णाणं व ॥४८७॥

योगे चतुरक्षाणां पंचाक्षाणां च क्षीणकषायचरमाणां। चक्षुषामवधिकेवलपरिमाणं तयोर्ज्ञानवत्।

मिथ्यादृष्टिगुणस्थानमादियागि क्षीणकषायावसानमाद गुणस्थानवर्त्तिगळु शक्तिचक्षुर्द्दर्शनिगळेंदुं व्यक्तिचक्षुर्द्दर्शनिगळेंदुं। चक्षुर्द्दर्शनिगळसंख्येयोळु द्विप्रकारमप्परल्लि लब्ध्यपर्य्याप्तकचतुरिंद्रियजीवंगळ संख्येयोळु पंचेंद्रियलब्ध्यपर्य्याप्तजीवंगळ संख्येयं संयोगमागुत्तिरलु शक्तिगतचक्षुर्द्दर्शनिगळ संख्येयक्कुं। पर्य्याप्तकचतुरिंद्रियजीवंगळुमं पर्याप्तकपंचेंद्रियजीवंगळ संख्येयुमं संयोगमं माडुत्तिरलु व्यक्तिगतचक्षुर्द्दर्शनिगळ संख्येयक्कुं। तच्छक्तिव्यक्तिगतचक्षुर्द्दर्शनिगळ संख्येयंतप्पल्लि त्रैराशिकं माडल्पडुवुदवेंतें दोडे द्विचतुःपंचेंद्रियजीवंगळेल्लमोमावल्यसंख्यातभक्तप्रतरांगुलभाजितजगत्प्रतरमात्रं फलराशियागुत्तिरलु चतुःपंचेन्द्रियद्वयक्केनितु जीवंगळप्पुवेंदु

बहुविधाः—तीव्रमन्दमध्यमादिभावेन अनेकविधाः बहुप्रकाराश्चोद्योताः चन्द्रसूर्यरत्नादिप्रकाराः लोके—परिमितक्षेत्रे एव भवन्ति तैः प्रकाशैरनुपमेयः लोकालोकयोर्विगततिमिरो यः स केवलदर्शनोद्योतो भवति ॥४८६॥
अथ दर्शनमार्गणायां जीवसंख्या गाथाद्वयेनाह—

मिथ्यादृष्ट्यादयः क्षीणकषायान्ताः शक्तिगतचक्षुर्दर्शनिनः व्यक्तिगतचक्षुर्दर्शनिनश्च। तत्र लब्ध्यपर्याप्तचतुरिन्द्रियपञ्चेन्द्रियाः शक्तिगतचक्षुर्दर्शनिनः, पर्याप्तकचतुरिन्द्रियपञ्चेन्द्रियाः व्यक्तिगतचक्षुर्दर्शनिनः। तद्यथा—द्वित्रिचतुःपञ्चेन्द्रियप्रमाणं यदि आवल्यसंख्यातभक्तप्रतराङ्गुलभाजितजगत्प्रतरं तदा चतुःपञ्चेन्द्रियप्रमाणं

तीव्र, मन्द, मध्यम आदिके भेदसे अनेक प्रकारके चन्द्र, सूर्य, रत्न आदि सम्बन्धी उद्योत परिमित क्षेत्रको ही प्रकाशित करनेवाले हैं। उन प्रकाशोंकी उपमा जिसे नहीं दी जा सकती ऐसा जो लोक-अलोक दोनोंको प्रकाशित करता है वह केवल दर्शनरूप उद्योत है ॥४८६॥

अथ दर्शन मार्गणामें जीवोंकी संख्या दो गाथाओंसे कहते हैं—

मिथ्यादृष्टिसे लेकर क्षीणकषाय गुणस्थान पर्यन्त जीव दो प्रकारके हैं, शक्तिरूप चक्षुदर्शनवाले और व्यक्तिरूप चक्षुदर्शनवाले। उनमें-से लब्ध्यपर्याप्तक चतुरिन्द्रिय और पंचेन्द्रिय तो शक्तिरूप चक्षुदर्शनवाले हैं और पर्याप्तक चतुरिन्द्रिय व्यक्तिरूप चक्षुदर्शन वाले हैं। यदि दोइन्द्रिय, तेइन्द्रिय, चतुरिन्द्रिय और पंचेन्द्रिय जीवोंका प्रमाण आवलीके असंख्यातवें भागसे भाजित प्रतरांगुल और उससे भाजित जगत्प्रतर प्रमाण है तो चतुरिन्द्रिय

१. भेदेनानेकप्रकारा उद्योताः प्रकाशविशेषा लोके परिमितक्षेत्र एव प्रकाशते। यो लोकालोकयोः सर्वसामान्याकारे वितिमिरः क्रमकरणव्यवधानराहित्येन सदावभासमानः स केवलदर्शनाख्य उद्योतो भवति इत्योऽप्यन्यमपि पाठो दृश्यते बपुस्तके।

एइंदियपहुदीणं खीणकसायंतणंतरासीणं ।
जोगो अचक्खुदंसणजीवाणं होदि परिमाणं ॥४८८॥

एकेंद्रियप्रभृतीनां क्षीणकषायांतानंतराशीनां योगो चक्षुर्द्दर्शनजीवानां भवति परिमाणं ।
एकेंद्रियप्रभृति क्षीणकषायांतानंतानंतजीवंगळयोगं अचक्षुर्द्दर्शनजीवंगळ प्रमाणमक्कुं ।१३।

शक्तिचक्षु	व्यक्तिचक्षु	अचक्षु	अवधिदर्शन	केवलदर्शन
≡	२	१ ३	प ----	७
४ २—	४	०	० ०	३
२ ४	५		०	
०				

इंतु भगवदर्हत्परमेश्वरचारुचरणारविंदद्वंद्ववंदनानंदितपुण्यपुंजायमानश्रीमद्रायराजगुरु मंडलाचार्य्यमहावादवादीश्वररायवादिपितामह सकलविद्वज्जनचक्रवर्त्तिश्रीमदभयसूरि सिद्धांतचक्रवर्त्ति श्रीपादपंकजरजोरंजित ललाटपट्टं श्रीमत्केशवण्णविरचित गोम्मटसारकर्णाटवृत्ति जीवतत्त्वप्रदीपिकेयोळ् जीवकांडविंशतिप्ररूपणंगळोळ् चतुर्द्दशं दर्शनमार्ग्गणाधिकारं निगदितमास्तु ।

एकेन्द्रियप्रभृतिक्षीणकषायान्तानन्तानन्तजीवानां योगः अचक्षुर्दर्शनजीवप्रमाणं भवति १३–॥४८८॥

एकेन्द्रियसे लेकर क्षीणकषाय गुणस्थान पर्यन्त अनन्त जीवोंका जो योग है उतना अचक्षुदर्शनी जीवोंका प्रमाण है ॥४८८॥

इस प्रकार सिद्धान्त चक्रवर्ती आचार्य नेमिचन्द्र रचित गोम्मटसार अपर नाम
पंचसंग्रहकी केशववर्णी रचित कर्नाटक वृत्ति अनुसारिणी हिन्दी टीकामें
जीवकाण्डके अन्तर्गत दर्शन मार्गणा प्ररूपणा नामक चौदहवाँ
अधिकार समाप्त हुआ ॥१४॥

जोगपउत्ती लेस्सा कसायउदयाणुरंजिया होइ।
तत्तो दोण्णं कज्जं बंधचउक्कं समुद्दिट्ठं ॥४९०॥

योगप्रवृत्तिर्लेश्या कषायोदयानुरंजिता भवति। ततो द्वयोः कार्यं बंधचतुष्कं समुद्दिष्टं ॥

कायवाङ्मनःप्रवृत्तियं लेश्ये ये बुदक्कु कषायोदयानुरंजितमक्कुं। अदु कारणमागि द्वयोः कार्यं योगकषायंगळ कार्यमप्प बंधचतुष्कं प्रकृतिस्थित्यनुभागप्रदेशबंधचतुष्टयं [illegible] समुद्दिष्टं परमागमदोळु पेळल्पट्टुदु। योगदिंदं प्रकृतिप्रदेशबंधमक्कुं। कषायदिंदं स्थित्यनुभागबंधमक्कुमप्पुदरिंदं कषायोदयानुरंजितयोगप्रवृत्तिये लेश्येयप्पुदरिंदं नाल्कुं बंधमुं पुट्टुगुमेंदु तात्पर्यं।

लेश्यामार्गणेयोळधिकारनिर्देशमं माडिदपं गाथाद्वयदिंदं :—

णिद्देसवण्णपरिणामसंकमो कम्मलक्खणगदी य।
सामी साहणसंखा खेत्तं फासं तदो कालो ॥४९१॥
अंतरभावप्पबहु अहियारा सोलसा हवंतित्ति।
लेस्साण साहणट्ठं जहाकमं तेहिं वोच्छामि ॥४९२॥

निर्देशवर्णपरिणामसंक्रमकर्मलक्षणगतयश्च। स्वामी साधनसंख्या क्षेत्रं स्पर्शं ततः कालः ॥
अन्तरभावाल्पबहुत्वमधिकाराः षोडश भवन्ति। लेश्यानां साधनार्थं यथाक्रमं तैर्वक्ष्यामि ॥

निर्देशमुं वर्णमुं परिणाममुं संक्रममुं कर्ममुं लक्षणमुं गतियुं स्वामियुं साधनमुं संख्येयुं क्षेत्रमुं स्पर्शमुं कालमुं अंतरमुं भावमुं अल्पबहुत्वमुं [illegible]

[illegible]

काय, वचन और मनकी प्रवृत्ति लेश्या है। वह मन, वचन, कायकी प्रवृत्ति कषायके उदयसे अनुरंजित है। इस कारणसे दोनों योग और कषायोंका कार्य प्रकृति, प्रदेश, अनुभाग और स्थितिरूप चार प्रकारका बंध [illegible] है। [illegible] प्रकृतिबंध, प्रदेशबंध और कषायके उदयसे [illegible] कषायके उदयसे अनुरंजित योगप्रवृत्ति [illegible] है [illegible] होता है ॥४९०॥

छप्पयणीलकवोदसुहेमंबुजसंखसंणिहा वण्णे ।
संखेज्जाऽसंखेज्जाऽणंतवियप्पा य पत्तेयं ॥४९५॥

षट्पदनीलकपोतसुहेमांबुजशंखसन्निभा वर्णे । संख्येयासंख्येया अनंतविकल्पाश्च प्रत्येकं ॥

तुंबिय, नीलरत्नद, कपोतपक्षिय, सुहेमद, अंबुजद, शंखद सन्निभंगळु यथाक्रमदिदमप्पुवु । कृष्णलेश्यादिगळु वर्णंदोळु चिंद्रियग्राह्यत्तिगळिंदं प्रत्येकं संख्यातंगळप्पुवु । कृ १ नी १ क १ ते १ प १ शु १ ॥ स्कंधभेददिदं प्रत्येकमसंख्यातंगळप्पुवु । कृ ᴝ नील ᴝ क ᴝ ते ᴝ प ᴝ शु ᴝ ॥ परमाणुभेददिदं प्रत्येकमनंतानंतगळप्पुवु । कृ ख नी ख क ख ते ख प ख शु ख ॥

णिरया किण्हा कप्पा भावाणुगया हु तिसुरणरतिरिये ।
उत्तरदेहे छक्कं भोगे रविचंदहरिदंगा ॥४९६॥

नारकाः कृष्णाः कल्पजा भावानुगता खलु त्रिसुरनरतिर्यक्षु । उत्तरदेहे षट्कं भोगे रविचंद्रहरितांगाः ॥

नारकरेल्लरुं कृष्णवर्णरेयप्परु कल्पजरेल्लरु भावलेश्यानुगतरप्परु । भवनत्रयदेवर्कळुं मनुष्यरुं तिर्य्यंचरुगळुं उत्तरदेहंगळु देवक्कळ वैकुर्व्वण शरीरंगळु अवुं षड्वर्णंगळप्पुवु यथाक्रममुत्तममध्यमजघन्यभोगभूमिजरप्प नरतिर्य्यंचरुगळ शरीरंगळु रविचंद्रहरिद्वर्णंगळप्पुवु ॥

कृष्णादिलेश्याः वर्णे षट्पद–नीलरत्न–कपोत–सुहेम–अम्बुज–शङ्खसंनिभा भवन्ति । पुनस्ता इन्द्रियग्राह्यत्वाभिः प्रत्येकं संख्याताः कृ १ । नी १ । क १ । ते १ । प १ । शु १ । स्कन्धभेदेनासंख्याताः कृ ᴝ । नी ᴝ क ᴝ । ते ᴝ । प ᴝ । शु ᴝ । परमाणुभेदेन अनन्तानन्ताश्च भवन्ति । कृ ख । नी ख । क ख । ते ख । प ख । शु ख ॥४९५॥

नारकाः सर्वे कृष्णा एव, कल्पजाः सर्वे स्वस्वभावलेश्यानुगा एव । भवनत्रयदेवाः मनुष्यास्तिर्यञ्चो देवविकुर्वणदेहाश्च सर्वे षड्वर्णाः । उत्तममध्यमजघन्यभोगभूमिजनरतिर्यञ्चः क्रमशः रविचन्द्रहरिद्वर्णा एव ॥४९६॥

वर्णके रूपमें कृष्ण आदि लेश्या भौंरे, नीलम, कबूतर, स्वर्ण, कमल और शंखके समान होती हैं। अर्थात् भौंरेके समान जिनके शरीरका रंग काला है, उनके द्रव्यलेश्या कृष्ण है। नीलमके समान नील रंग वालोंकी द्रव्यलेश्या नील होती है। कबूतरके समान शरीरके वर्णवालोंकी द्रव्यलेश्या कापोत होती है। स्वर्णके समान पीत वर्ण वालोंकी द्रव्यलेश्या पीत होती है। कमलके समान शरीरके वर्णवालोंकी द्रव्यलेश्या पद्म होती है। और जिनका शरीरका रंग शंखके समान सफेद होता है उनकी द्रव्यलेश्या शुक्ल होती है। इन्द्रियोंके द्वारा प्रतीत होनेकी अपेक्षा प्रत्येक लेश्याके संख्यात भेद होते हैं। स्कन्धोंके भेदसे असंख्यात भेद हैं और परमाणुओंके भेदसे अनन्त भेद हैं॥४९५॥

सब नारकी कृष्णवर्ण ही होते हैं। सब कल्पवासी देव अपनी-अपनी भावलेश्याके अनुसार ही द्रव्यलेश्यावाले होते हैं। अर्थात् जैसी उनकी भावलेश्या होती है उसीके अनुसार उनके शरीरका वर्ण होता है। भवनवासी, व्यन्तर, ज्योतिषीदेव, मनुष्य, तिर्यंच और देवोंके विक्रियासे बना शरीर ये सब छहों वर्णवाले होते हैं। उत्तम, मध्यम और जघन्य

१. ब अनन्तास्च ।

[illegible] संक्लेशस्थानगतम् अशुभलेश्या- [illegible] । [illegible] । [illegible] विशुद्धिस्थान [illegible] । [illegible] ।

तिव्वतमा तिव्वतरा तिव्वा असुहा सुहा तहा मंदा ।
मंदतरा मंदतमा छट्ठाणगया हु पत्तेयं ॥५००॥

तीव्रतमानि तीव्रतराणि तीव्राण्यशुभानि शुभानि तथा मन्दानि । मन्दतराणि मन्दतमानि षट्स्थानगतानि खलु प्रत्येकं ।

[illegible] अशुभलेश्या संक्लेशस्थानंगळु [illegible] सामान्याशुभलेश्या [illegible] बहुभागमात्रंगळ- [illegible] नीललेश्या [illegible] तद्बहुभागमात्रंगळ- [illegible] कपोतलेश्या [illegible] तदेकभागमात्रंगळप्पुवु [illegible] शुभलेश्याविशुद्धिस्थानंगळु [illegible] असंख्यातलोकभक्तैकभागमात्रंगळोळु [illegible] तेजोलेश्या-

असंख्यातलोकमात्राणि [illegible] । तेषु [illegible] अशुभलेश्यास्थानानि [illegible] । [illegible] शुभलेश्याविशुद्धिस्था- [illegible] ॥४९९॥

[illegible] अशुभलेश्यासंक्लेशस्थानानि कृष्णनीलकपोतलेश्यानिर्विशेषाणि । तत्र [illegible] सामान्याशुभलेश्या [illegible] असंख्यातलोकभक्तैकं बहुभाग- [illegible] कपोत- [illegible] पुनः शुक्लेश्याविशुद्धिस्थानेषु [illegible]

कषायोंके अनुभागरूप उदय स्थान असंख्यात लोक मात्र होते हैं। उनमें यथायोग्य असंख्यात लोकका भाग देनेपर बहुभाग प्रमाण संक्लेश स्थान हैं, वे भी असंख्यात लोक प्रमाण ही हैं। और शेष एक भाग प्रमाण विशुद्धिस्थान हैं, वे भी असंख्यात लोक मात्र हैं। संक्लेशस्थान तो अशुभ लेश्याओंके स्थान हैं और विशुद्धि स्थान शुभ लेश्याओंके स्थान हैं ॥४९९॥

पहले कहे असंख्यात लोकके बहुभाग मात्र अशुभ लेश्या सम्बन्धी स्थान कृष्ण, नील, कापोतके भेदसे तीन प्रकारके हैं। उन सामान्य अशुभ लेश्या सम्बन्धी स्थानोंमें यथायोग्य असंख्यात लोकका भाग देनेपर बहुभाग प्रमाण कृष्णलेश्या सम्बन्धी तीव्रतम कषायरूप संक्लेश स्थान हैं। शेष रहे एक भागमें पुनः असंख्यात लोकसे भाग देनेपर बहुभाग मात्र

काऊ णीलं किण्हं परिणमदि किलेसवड्ढिदो अप्पा ।
एवं किलेसहाणीवड्ढीदो होदि असुहतियं ॥५०२॥

कपोतं नीलं कृष्णं परिणमति क्लेशवृद्धित आत्मा । एवं क्लेशहानिवृद्धितोऽशुभत्रयं भवति ।

संक्लेशवृद्धियिदमात्मं कपोतनीलकृष्णलेश्यारूपमं तप्पुदंते परिणमवि परिणमिसुगुमितु संक्लेशहानिवृद्धिगळिंदमशुभत्रयरूपनक्कुं ।

तेऊ पम्मे सुक्के सुहाणमवरादि अंसगे अप्पा ।
सुद्धिस्स य वड्ढीदो हाणीदो अण्णहा होदि ॥५०३॥

तेजसि पद्मे शुक्ले शुभानामवराद्यंशके आत्मा विशुद्धेश्च वृद्धितो हानितोऽन्यथा भवति ।

शुभंगळप्प तेजःपद्मशुक्ललेश्येगळ जघन्याद्यंशंगळोळात्मं विशुद्धिवृद्धियिदं भवति परिणमिसुगुं । हानितोऽन्यथा भवति विशुद्धिय हानियिदं शुक्ललेश्योत्कृष्टं मोदल्गोंडु तेजोलेश्याजघन्यांशपर्यंतं भवति परिणमिसुगुं । संदृष्टि :—

अशुभलेश्या	≡ स्थानानि ९ a ८	सर्व्वधनं ≡ a	शुभलेश्या	स्थानानि	≡ ९ a । १
तीव्रतमकृष्ण	तिव्वतरनील	तिव्वकपोत	मंदतेज	मंदतरपद्म	मंदतमशुक्ल
उ oooooo ज	उ oooooo ज	उ oooooo ज	ज oooooo उ	ज oooooo उ	ज oooooo उ
≡ a ८ ८ / ९ ९	≡ a । ८ । ८ / ९ ९ ९	≡ a । ८ । १ / ९ ९ ९	≡ a ८ । / ९ ९	≡ a ८ / ९ ९ ९	≡ a । १ / ९ ९ ९

परिणामाधिकारं तृतीयं समाप्तमाय्तु ।

अनंतरं संक्रमणाधिकारमं गाथात्रयदिदं स्वस्थानपरस्थानसंक्रमणमनि परिणामपरावृत्तिरचनेयं कटाक्षिसिकोंडु पेळ्दपं ।

संक्लेशवृद्धयात्मा कपोतनीलकृष्णलेश्यारूपेण परिणमति इति संक्लेशहानिवृद्धिभ्यामशुभत्रयरूपो भवति ॥५०२॥

शुभानां तेजःपद्मशुक्ललेश्यानां जघन्याद्यंशेषु आत्मा विशुद्धिवृद्धितो भवति परिणमति, हानितोऽन्यथा शुक्लोत्कृष्टात्तेजोजघन्यांशपर्यन्तं परिणमति ॥५०३॥ इति परिणामाधिकारः । उक्तपरिणामपरावृत्तिरचनामनधिकृत्य संक्रमणाधिकारं गाथात्रयेणाह—

तथा संक्लेश परिणामोंमें वृद्धि होनेसे कपोत, नील और कृष्ण लेश्यारूपसे परिणमन करता है। इस प्रकार संक्लेश परिणामोंमें हानि, वृद्धि होनेसे तीन अशुभ लेश्या रूपसे परिणमन करता है ॥५०२॥

शुभ तेज, पद्म और शुक्ल लेश्याओंके जघन्य, मध्यम, उत्कृष्ट अंशोंमें आत्मा विशुद्धिकी वृद्धिसे परिणमन करता है। और विशुद्धिकी हानिसे अन्यथा अर्थात् शुक्ल लेश्याके उत्कृष्ट अंशसे तेजोलेश्याके जघन्य अंश तक परिणमन करता है ॥५०३॥

इस प्रकार परिणामाधिकार समाप्त हुआ।

उक्त परिणामोंके परिवर्तनकी रचनाको मनमें रखकर तीन गाथाओंसे संक्रमण अधिकारको कहते हैं—

लेश्यानां कृष्णादिसर्व्वलेश्येगळ उत्कृष्टात् उत्कृष्टदत्तणिवं अनंतरस्वलेश्यास्थानविकल्पदोळु अवरहानिः अनंतैकभागहानियक्कुं । एकें दोडुत्कृष्टलेश्योदयस्थानकमप्पुदरिंदमनंतरोर्व्वंकस्थानदोळनंतैकभागहानियक्कुमप्पुदरिदं । अवरस्मात् सर्व्वलेश्येगळ जघन्यस्थानदत्तणिवं स्वस्थाने स्वस्थानदोळु अवरवृद्धिः अनंतभागवृद्धिये अक्कुमेकें दोडे लेश्याजघन्यस्थानंगळनितुमष्टांकंगळप्पुदरिदमनंतरस्थानंगळोळु अनंतभागवृद्धिये नियमदिंदमक्कुमेकें दोडा जघन्यमा षट्स्थानादियप्पुदरिदं । उत्तरस्थानमनंतैकभागवृद्धिस्थानमक्कुमप्पुदरिदं । अवरस्मात् सर्व्वलेश्येगळ जघन्यस्थानदत्तणिवं परस्थाने परस्थानसंक्रमणदोळु अनंतरस्थानदोळु हानिः अनंतगुणहानिये नियमाद् भवति नियमदिंमक्कुमेकेंदोडे शुक्ललेश्याजघन्यदिंदमनंतरपद्मलेश्यास्थानदोळनंतगुणहानि नियमदिमें तक्कुमंते कृष्णलेश्याजघन्यदिदमनंतरनीललेश्यास्थानदोळमनंतगुणहानियक्कुमितेल्ला लेश्येगळगमक्कुं ॥

संकमणे छट्ठाणा हाणिसु वड्ढीसु होंति तण्णामा ।
परिमाणं च य पुव्वं उत्तकमं होदि सुदणाणे ॥५०६॥

संक्रमणे षट्स्थानानि हानिषु वृद्धिषु भवंति तन्नामानि । परिमाणं च पूर्व्वमुक्तक्रमो भवति श्रुतज्ञाने ॥

ई संक्रमणदोळु हानिगळोळं वृद्धिगळोळं षड्वृद्धिगळुं षड्हानिगळुं मप्पुवु । तद्वृद्धिहानिगळ पेसर्गळुमवर प्रमाणंगळुमं मुन्नं श्रुतज्ञानमार्ग्गणेयोळ्पेळ्द क्रममेयक्कुमें दरिवुदें तें दोडे अनंत-

कृष्णादिसर्वलेश्योत्कृष्टादनन्तरस्वलेश्यास्थानविकल्पे अवरहानिः अनन्तैकभागहानिर्भवति, कुतः? तदनन्तरस्योर्वङ्कात्मकत्वात् । सर्वलेश्यानां जघन्यात्पुनः स्वस्थाने अवरवृद्धिः अनन्तैकभागवृद्धिरेव भवति । कुतः? तज्जघन्यानामष्टांकरूपत्वात् । सर्वलेश्याजघन्यस्थानात् परस्थानसंक्रमणेऽनन्तरस्थाने अनन्तगुणहानिरेव नियमाद्भवति । कुतः? शुक्ललेश्याजघन्यादनन्तरपद्मलेश्यास्थानवत्कृष्णलेश्याजघन्यादनन्तरनीललेश्यास्थानेऽपि तद्धानेरेव संभवात् । एवं सर्वलेश्यानां भवति ॥५०५॥

अस्मिन् संक्रमणे हानिषु वृद्धिषु च षड्वृद्धयः षड्ढानयश्च भवन्ति । तासां नामानि प्रमाणानि च पूर्वं

कृष्ण आदि सब लेश्याओंके उत्कृष्ट स्थानमें जितने परिणाम होते हैं उनसे उत्कृष्ट स्थानके समीपवर्ती उसी लेश्याके स्थानमें 'अवरहानि' अर्थात् उत्कृष्ट स्थानसे अनन्त भाग हानिको लिये हुए परिणाम होते हैं क्योंकि उत्कृष्टके अनन्तरवर्ती परिणाम उवंकरूप होता है और अनन्त भागकी संदृष्टि उवंक है। तथा सब लेश्याओंके जघन्य स्थानसे उसी लेश्यामें उसके समीपवर्ती स्थानमें अनन्तवें भागवृद्धि ही होती है क्योंकि उनके जघन्य अष्टांकरूप होते हैं। सब लेश्याओंके जघन्य स्थानसे परस्थानसंक्रमण होनेपर उसके अनन्तरवर्ती स्थानमें अनन्त गुणहानि ही नियमसे होती है। क्योंकि शुक्ललेश्याके जघन्य स्थानके अनन्तर जो पद्मलेश्याका उत्कृष्ट स्थान है उसीकी तरह कृष्णलेश्याके जघन्य स्थानके अनन्तर जो नीललेश्याका उत्कृष्ट स्थान है उनमें भी अनन्त गुणहानि ही सम्भव है। इसी प्रकार सब लेश्याओंमें जानना ॥५०५॥

इस संक्रमणमें हानि और वृद्धिमें छह हानियाँ और छह वृद्धियाँ होती हैं। उनके

१. म अकस्मात् अवरवृद्धि स. । २. म हानिः हानिये ।

पहिया जे छप्पुरिसा परिभट्टारण्णमज्झदेसम्मि ।
फलभरियरुक्खमेगं पेक्खित्ता ते विचिंतंति ॥५०७॥

पथिका ये षट्पुरुषाः परिभ्रष्टाः अरण्यमध्यदेशे, फलभरितमेकं वृक्षं प्रेक्ष्य ते विचिंतयंति ॥

णिम्मूलखंधसाहुवसाहं छित्तुं चिणित्तु पडिदाइं ।
खाउं फलाइ इदि जं मणेण वयणं हवे कम्मं ॥५०८॥

निर्म्मूलस्कंधशाखोपशाखाश्छित्त्वा उच्चित्य पतितानि । खादितुं फलानीति यन्मनसा वचनं भवेत्कर्म्म ॥

मुंपेळ्द पथिकरुगळं तोळल्दुत्तमरण्यमध्यदोळों दु फलभरितमाकंदवृक्षमं कंडु तत्फलभक्षणोपायमं कृष्णलेश्याविपरिणामजीवंगळितें दु चिंतिसिदपरु । मरनं निर्म्मूलमप्पंतु कडिवुं, स्कंधमने कडिवुं, शाखेयने कडिवुं, उपशाखेयने कडिवुं, मरनं नोयिसदे पण्गळने तिरिदु, इल्लि बिद्दिर्दुव्वने मेलुवेमें वितापुदों दु मनदिनालापमदा कृष्णलेश्यादि षट्प्रकारद जीवंगळ्गो यथाक्रमदिदं कर्म्मम बुदक्कुं । अथिदनेयक कर्म्माधिकारं तीदर्दुदु ॥

अनंतरं लक्षणाधिकारमं गाथानवकदिदं पेळ्दपं ॥

चंडो ण मुचइ वेरं भंडणसीलो य धम्मदयरहिओ ।
दुट्ठो ण य एदि वसं लक्खणमेयं तु किण्हस्स ॥५०९॥

चंडो न मुंचति वैरं भंडनशीलश्च धर्म्मदयारहितः । दुष्टः न चैति वशं लक्षणमेतत्तु कृष्णस्य ॥

चंडः तीव्रकोपनं न मुंचति वैरं वैरमं बिडुवनल्लं । भंडनशीलश्च युद्धशीळनुं धर्म्मदयारहितः धर्म्ममुं दयेयुमिल्लदनुं दुष्टः दुष्टनुं न चैति वशं वशवर्त्तियप्पनुमल्लं । एतल्लक्षणं इंतप्प लक्षणमनुळ्ळं तु

कृष्णाद्येकैकलेश्यायुक्तषट्पथिकाः पुरुषाः पथः परिभ्रष्टाः अरण्यमध्यदेशे फलभरितमेकं वृक्षं दृष्ट्वा ते विचिन्तयन्ति । तत्र आद्यः—वृक्षं निर्मूलं छित्वा, अन्यः स्कन्धं छित्वा, परः शाखा छित्वा, अन्यः उपशाखा छित्वा, परो वृक्षाबाधं फलान्येव छित्वा, अन्यः पतितान्येव गृहीत्वा च फलान्यश्नोति यन्मनःपूर्वकं वचः तत्क्रमशस्तासां कर्म भवति ॥५०७-५०८॥ इति कर्माधिकारः ॥ अथ लक्षणाधिकारं गाथानवकेनाह—

चण्डस्तीव्रकोपनः वैरं न मुञ्चति, भण्डनशीलश्च युद्धशीलश्च धर्मदयारहितः दुष्टः निर्दयो वश नैति

कृष्ण आदि एक-एक लेश्यावाले छह पथिक मार्ग भूल गये। वनके मध्यमें फलोंसे लदे हुए एक वृक्षको देखकर वे विचार करते हैं—कृष्णलेश्यावाला विचारता है कि वृक्षको जड़से उखाड़कर इसके फल खाऊँगा। नीललेश्यावाला विचारता है कि इस वृक्षके स्कन्धको काटकर फल खाऊँगा। कपोतलेश्यावाला विचारता है, इसकी बड़ी डाल काटकर फल खाऊँगा। तेजो लेश्यावाला विचारता है इसकी छोटी डाल काटकर फल खाऊँगा। पद्मलेश्यावाला विचारता है वृक्षको हानि न पहुँचाकर केवल फल ही तोड़कर खाऊँगा। शुक्ललेश्यावाला विचारता है गिरे हुए फलोंको ही खाऊँगा। इस प्रकार मनपूर्वक जो वचन होता है वह क्रमसे उन लेश्याओंका कार्य होता है ॥५०७-५०८॥

अब नौ गाथाओंसे लक्षणाधिकार कहते हैं—

तीव्र क्रोधी हो, वैर न छोड़े, लड़ाई-झगड़ा करनेका स्वभाव हो, दया-धर्मसे रहित

पेररं कोपिसुगुं बहुप्रकारदिदं पेररं निंदिसुगुं। बहुप्रकारदिदं पेररं दूषिसुगुं। शोकबहुलनुं भयबहुलनुं परनं सैरिसनुं परनं परिभविसुगुं तन्न बहुप्रकारदिदं प्रशंसेयं माडिकोळुगुं।

ण य पत्तियइ परं सो अप्पाणं यिव परं पि मण्णंतो।
थूसइ अभित्थुवंतो ण य जाणइ हाणि वड्ढिं वा ॥५१३॥

न च विश्वसिति परं सः आत्मानमिव परमपि मन्यमानः। तुष्यत्यभिष्टुवतो न च जानाति हानिं वृद्धिं वा।

सः अंतप्प जीवं परनं नंबुवनल्लं तन्नंतेये एंदु परनं बगेगुं। तन्न पोगळुत्तिरलु संतोषिसुगुं तनगं परगं हानियुमं वृद्धियुमं न जानाति अरियं।

मरणं पत्थेइ रणे देइ सुबहुगंपि थुव्वमाणो दु।
ण गणइ कज्जाकज्जं लक्खणमेयं तु काउस्स ॥५१४॥

मरणं प्रार्थयति रणे ददाति सुबहुकमपि स्तुवतः। न गणयति कार्य्याकार्य्यं लक्षणमेतत्कपोतलेश्यस्य।

काळगदोळु मरणमं बयसुगुं स्तुतिमाळ्पंगे बहुधनमनीगुं। कार्य्यमुमनकार्य्यमुमं गणिइसुवनल्लनितिदु कपोतलेश्येयमनुष्यंगे लक्षणमक्कुं।

जाणइ कज्जाकज्जं सेयमसेयं च सव्वसमपासी।
दयदाणरदो य मिदू लक्खणमेयं तु तेउस्स ॥५१५॥

जानाति कार्य्याकार्य्यं सेव्यमसेव्यं च सर्व्वसमदर्शी। दयादानरतश्च मृदुर्लक्षणमेतत्तेजोलेश्यस्य।

पैरस्मै[3] कुप्यति, बहुधा परं निन्दति, बहुधा परं दुष्यति, च शोकबहुलः, भयबहुलः, परं न सहते परं परिभवति आत्मानं बहुधा प्रशंसति ॥५१२॥

स परं न प्रत्येति—न विश्वसिति आत्मानमिव परमपि मन्यमानः अभिष्टुवतः परस्योपरि तुष्यति स्वपरयोर्हानिवृद्धी न च—नैव जानाति ॥५१३॥

रणे मरणं प्रार्थयते, स्तुतिं कुर्वतो बहुधनं (स्तूयमानस्तु बहुकमपि धनं) ददाति, कार्यमकार्यं च न गणयति इत्येतत्कपोतलेश्यस्य लक्षणं भवति ॥५१४॥

दूसरोंपर बहुत क्रोध करता हो, दूसरोंकी बहुत निन्दा करता हो, दूसरोंको बहुधा दोष लगाता हो, बहुत शोक करता हो, बहुत डरता हो, दूसरोंको अच्छा न देख सकता हो, अन्यकी निन्दा और अपनी बहुत प्रशंसा करता हो, दूसरोंका विश्वास न करता हो, दूसरोंको भी अपनी ही तरह अविश्वास करनेवाला मानता हो, प्रशंसा करनेवालेपर परम प्रसन्न हो, अपनी और परकी हानि-वृद्धिकी परवाह न करता हो, युद्धमें मरनेको तैयार हो, अपनी स्तुति करनेवालेको बहुत कुछ दे डालता हो, कार्य-अकार्यको न जाने, ये सब कपोतलेश्यावालेके लक्षण हैं ॥५१२-५१४॥

---

१. म. धनमं कुडुगं। २. म. समदंसी। ३. ब. अन्यस्मै कुप्यति।

लेस्साणं खलु अंसा छव्वीसा होंति तत्थ मज्झिमया ।
आउगबंधणजोग्गा अट्ठट्ठवगरिसकालभवा ॥५१८॥

लेश्यानां खल्वंशाः षड्विंशतिर्भवंति तत्र मध्यमगाः । आयुर्बंधनयोग्याः अष्टाऽष्टापकर्षकालभवाः ।

शिला भेदसमान	पृथ्वी भेदसमान	धूळीरेखासमान	जल रेखासमान
उ ००००००० ज	उ ००००००००० ज	उ ००००००००००ज	उ ००००००० ज
	कउ	तेउ	
कृ १	१।२।३।४।५।६।	६।५।४।३।२।१।	शु १
० ।१	१।१।१।४।४।४	४।१।१।१।०।०।	०
	२।	३	
	३	२० श ८	

आवं लेश्येगळगे अंशंगळनितुं कूडि षड्विंशतिगळप्पुवु २६ । अवेंतेंदोडे कृष्णाद्यशुभलेश्यात्रयक्कं जघन्यमध्यमोत्कृष्टंगळु प्रत्येकं मूरुमूरागलोंभतंशंगळप्पुवु । शुक्ललेश्यादि शुभलेश्यात्रयक्कमंतेयों भत्तंशंगळप्पुवु-। मा कपोतलेश्येय उत्कृष्टांशदिदं मुंदे तेजोलेश्येय उत्कृष्टांशदिदं पिंदे कषायोदयस्थानंगळ नडु वणादं लेश्येगल यथासंभवंगळायुर्बंधयोग्यमध्यमा-

लेश्या
४।५।६।६।५।४
४।४।४।४।१।१
स्थिति

षड्लेश्यानामंशा जघन्यमध्यमोत्कृष्टभेदादष्टादश । पुनः कपोतलेश्योत्कृष्टांशादग्रे तेजोलेश्योत्कृष्टांशात्प्राक्-कषायोदयस्थानेषु मध्यमांशा आयुर्बन्धयोग्या अष्टौ । एवं षड्विंशतिर्भवन्ति । तेषु—

शिला	पृथ्वी	धूलि	जल
उ ०००००० ज	उ ०००००० ज	उ ०००००० ज	उ०००००० ज
कृ १	१ २ ३ ४ ५ ६	६ ५ ४ ३ २ १	शु १
० १	१ १ १ ४ ४ ४	४ १ १ १ ० ०	०
	२	३ ०	
	३	२	
	० ० ० ०	० ० ० ०	
	मध्यमांशाः		

मध्यमा अष्टौ अष्टापकर्षकाले संभवन्ति । तद्यथा—भुज्यमानायुरपकृष्यापकृष्य परभवायुर्बध्यते इत्यपकर्षः । अपकर्षाणां स्वरूपमुच्यते-कर्मभूमितिर्यग्मनुष्याणां भुज्यमानायुर्जघन्यमध्यमोत्कृष्टं विवक्षितमिदं ६५६१ अत्र

छह लेश्याओंके उत्कृष्ट, मध्यम और जघन्यके भेदसे अठारह अंश होते हैं। पुनः कपोतलेश्याके उत्कृष्ट अंशसे आगे और तेजोलेश्याके उत्कृष्ट अंशसे पहले कषायके उदयस्थानोंमें आठ मध्यम अंश हैं जो आयुबन्धके योग्य होते हैं। इस प्रकार छब्बीस अंश होते हैं। आठ मध्यम अंश अपकर्ष कालमें होते हैं। जो इस प्रकार हैं—भुज्यमान अर्थात् वर्तमानमें जिसे भोग रहे हैं उस आयुका अपकर्षण कर-करके परभवकी आयुका बन्ध

१. ब. तत्स्वरूप ।

२
३

१
३
९
२७
८१
२४३
७२९
२१८७
६५६१ सर्व्वायुः

इल्लि विशेषनिर्णयं माडल्पडुगुमदें तें दोडे आवनोर्व्वं सोपक्रमायुष्यनप्प जीवं सोपक्रमायुष्यनें दें बुदेनें दोडे कदलीघातायुष्यमनुळ्ळनें बवर्त्यमवु कारणमागि देवनारकर्वं भोगभूमिजरुमनुपक्रमायुष्यरें बुदर्त्थं । आ सोपक्रमायुष्यजीवंगळु तंतम्म भुज्यमानायुष्यस्थितियोळु त्रित्रिभागमतिक्रांतमागुत्तिरलु शेषत्रिभागद प्रथमसमयं मोदल्गोंडु अंतर्म्मुहूर्त्तपर्य्यंतं परभवायुब्बंधप्रायोग्यरप्पर । मुंपेळ्व संक्षेपाद्धिपर्य्यंतमल्लि आयुस्तोकबंधाद्धा कालाभ्यंतरदोळायुर्बंधप्रायोग्यपरिणामंगळिंद केलवु जीवंगळु अष्टवारंगळं केलवु जीवंगळु सप्तवारंगळं केलवु जीवंगळु षड्वारंगळं केलवु जीवंगळु पंचवारंगळं केलवु जीवंगळु चतुर्व्वारंगळं केलवु जीवंगळु त्रिवारंगळं केलवु जीवंगळु द्विवारंगळं केलवु जीवंगळेकवारंगळं परिणमिसुववेकें दोडे स्वभावविदमेतद्बंधप्रायोग्यपरिणमनमा जीवंगळ्गे कारणांतरनिरपेक्षमें बुदर्त्थं । संदृष्टिरचने ॥

२
३
१
३
९
२७
८१
२४३
७२९
२१८७
६५६१

अत्र विशेषनिर्णयः क्रियते । सोपक्रमायुष्काः कदलीघातायुष्काः; तेन देवनारकभोगभूमिजा अनुपक्रमायुष्का भवन्ति । सोपक्रमायुष्का उक्तरीत्या आयुर्बध्नन्ति । तत्रायुस्तोकबन्धाद्धाभ्यन्तरे तद्योग्यपरिणामैः केचिदष्टवारं केचित्सप्तवारं केचित् षड्वारं केचित्पञ्चवारं केचित् चतुर्वारं केचित्त्रिवारं केचिद् द्विवारं केचिदेकवारं परिणमन्ति । स्वभावादेव तद्बन्धप्रायोग्यपरिणमनं जीवानां कारणान्तरनिरपेक्षमित्यर्थः । संदृष्टिः—

निर्णय करते हैं। जिनका विषादिके द्वारा कदलीघातमरण होता है वे सोपक्रम आयुवाले होते हैं। अतः देव, नारकी और भोगभूमिया निरुपक्रम आयुवाले होते हैं। सोपक्रम आयुवाले उक्त रीतिसे आयुबन्ध करते हैं। उन अपकर्षोंमें आयुबन्धके कालमें आयुबन्धके योग्य परिणामोंसे कोई आठ बार, कोई सात बार, कोई छह बार, कोई पाँच बार, कोई चार बार, कोई तीन बार, कोई दो बार, कोई एक बार परिणमन करते हैं। अपकर्ष कालमें ही जीवोंके आयुबन्धके योग्य परिणमन स्वभावसे होता है। उसका कोई अन्य कारण नहीं है। आयुके

पद्मलेश्योत्कृष्टांशदिदं मृतराद जीवंगळु सहस्रारमुपयांति सहस्रारकल्पदोळु पुट्टुवरु खलु स्फुटमागि। पद्मलेश्याजघन्यांशदिदं मृतराद जीवंगळु, सनत्कुमारं च माहेंद्रमुपयांति सनत्कुमार कल्पदोळं माहेंद्रकल्पदोळं पुट्टुवरु।

मज्झिमअंसेण मुदा तम्मज्झं जांति तेउजेट्ठमुदा।
साणक्कुमारमाहिंदंतिमचक्किंदसेढिम्मि ॥५२२॥

मध्यमांशेन मृताः तन्मध्यं यांति तेजोज्येष्ठमृताः सानत्कुमारमाहेंद्रांतिमचक्रेंद्रकश्रेण्यां।

पद्मलेश्यामध्यमांशदिदं मृतराद जीवंगळु तन्मध्यं यांति सहस्रारकल्पदिदं केळगे सानत्कुमारमाहेंद्रकल्पंगळिदं मेले यथासंभवरागि पुट्टुवरु। तेजोलेश्योत्कृष्टांशदिदं मृतराद जीवंगळु सानत्कुमारमाहेंद्रकल्पंगळ चरमपटलचक्रेंद्रकप्रणिधिगतश्रेणीबद्धविमानंगळोळ्पुट्टुवरु।

अवरंसमुदा सोहम्मीसाणादिमउडुम्मि सेढिम्मि।
मज्झिम अंसेण मुदा विमलविमानादिबलभद्दे ॥५२३॥

अवरांशमृताः सौधर्मैशानादिमृतुकस्त्वेंद्रके श्रेण्यां। मध्यमांशेन मृताः विमलविमानादिबलभद्रे।

तेजोलेश्याजघन्यांशदिदं मृतराद जीवंगळु सौधर्मैशानकल्पंगळादिमृतुकस्त्वेंद्रकदोळ् श्रेणीबद्धदोळं पुट्टुवरु। तेजोलेश्यामध्यमांशदिदं मृतराद जीवंगलु सौधर्मैशानकल्पद्वितीयपटलेंद्रकं विमलविमानमदु मोदलागि सानत्कुमारमाहेंद्रकल्पंगळ द्विचरमपटलेंद्रकं बलभद्रविमानमक्कु मल्लि पर्य्यंतं पुट्टुवरु।

पद्मलेश्योत्कृष्टांशेन मृता जीवाः सहस्रारकल्पमुपयान्ति खलु स्फुटम्। पद्मलेश्याजघन्यांशेन मृता जीवाः सानत्कुमारं माहेन्द्रं चोपयान्ति ॥५२१॥

पद्मलेश्यामध्यमांशेन मृता जीवाः सहस्रारकल्पादधः सानत्कुमारमाहेन्द्रद्वयादुपरि यथासंभवमुत्पद्यन्ते। तेजोलेश्योत्कृष्टांशेन मृता जीवाः सानत्कुमारमाहेन्द्रकल्पयोश्चरमपटलचक्रेन्द्रकप्रणिधिगतश्रेणीबद्धविमाने-पूत्पद्यन्ते ॥५२२॥

तेजोलेश्याजघन्यांशेन मृता जीवाः सौधर्मैशानकल्पयोरादिमृतुकस्त्विन्द्रके श्रेणीबद्धे चोत्पद्यन्ते। तेजोलेश्यामध्यमांशेन मृता जीवाः सौधर्मैशानकल्पद्वितीयपटलस्येन्द्रकं विमलनामकमादिं कृत्वा सानत्कुमारमाहेन्द्रद्विचरमपटलस्येन्द्रकं बलभद्रनामकं तत्पर्यन्तम् उत्पद्यन्ते ॥५२३॥

पद्मलेश्याके उत्कृष्ट अंशसे मरे जीव सहस्रारकल्पमें उत्पन्न होते हैं। पद्मलेश्याके जघन्य अंशसे मरे जीव सानत्कुमार माहेन्द्र स्वर्गोंमें उत्पन्न होते हैं ॥५२१॥

पद्मलेश्याके मध्यम अंशसे मरे जीव सहस्रारकल्पसे नीचे और सानत्कुमार माहेन्द्रसे ऊपर यथासम्भव उत्पन्न होते हैं। तेजोलेश्याके उत्कृष्ट अंशसे मरे जीव सानत्कुमार माहेन्द्र कल्पके अन्तिम पटल चक्रेन्द्रक सम्बन्धी श्रेणीबद्ध विमानोंमें उत्पन्न होते हैं ॥५२२॥

तेजोलेश्याके जघन्य अंशसे मरे जीव सौधर्म ऐशान कल्पके प्रथम ऋतु नामक इन्द्रकके श्रेणिबद्ध विमानोंमें उत्पन्न होते हैं। तेजोलेश्याके मध्यम अंशसे मरे जीव सौधर्म ऐशान कल्पके द्वितीय पटलके विमल नामक इन्द्रकसे लेकर सानत्कुमार माहेन्द्रके द्विचरम पटलके बलभद्र नामक इन्द्रक पर्यन्त उत्पन्न होते हैं ॥५२३॥

गळोळु चरमपटलद संप्रज्वलितेंद्रकविलदोळु जायंते पुट्टुवरु । नीललेश्यामध्यमांशदोळु मृतराद जीवंगळु तृतीयपृथ्विमेघेयनवपटलद संप्रज्वलितेंद्रकबिलदिदं केळगे चतुर्थपृथ्वि अंजनेय पटलसप्तकंगळोळु पंचमपृथ्विअरिष्टेय पटलपंचकंगळोळु चतुर्थपटलद अंधेंद्रकबिलदिदं मेले मध्यदोळु यथायोग्यमागि जायंते पुट्टुवरु ।

वरकाओदंसमुदा संजलिदं जांति तदियणिरयस्स ।
सीमंतं अवरमुदा मज्झे मज्झेण जायंते ॥५२६॥

उत्कृष्टकपोतांशमृताः संज्वलितं यांति तृतीयनरकस्य । सीमंतं अवरमृताः मध्ये मध्येन जायंते ॥

कपोतलेश्योत्कृष्टांशदिदं मृतराद जीवंगळु तृतीयपृथ्विमेघेय नवपटलंगळोळु द्विचरमाष्टमपटलद संज्वलितेंद्रकदोळ्पुट्टुवरु । केलंबरुगळु चरमसंप्रज्वलितेंद्रकबिलदोळं पुट्टुवरेंबी विशेषमरियल्पडुगुं । कापोतलेश्याजघन्यांशदिदं मृतराद जीवंगळु सीमंतं यांति घर्म्मेय प्रथमपटलद सीमंतेंद्रकबिलदोळ्पुट्टुवरु ।

कापोतलेश्यामध्यमांशदिदं मृतराद जीवंगळु सीमंतेंद्रकदिद केळगण पन्नेरडु पटलंगळोळं मेघेय द्विचरमसंज्वलितेंद्रकबिलदिद मेलण पटलंगळेळेळरोळु द्वितीयपृथ्विवंशेय पन्नोंदु पटलंगळोळं यथायोग्यमागि पुट्टुवरु ।

इति विशेषो ज्ञातव्यः । नीललेश्याजघन्यांशेन मृता जीवाः वालुकाप्रभानवपटलेषु चरमपटलस्य संप्रज्वलितेन्द्रके जायन्ते । नीललेश्यामध्यांशेन मृताः जीवाः तृतीयपृथ्वीनवमपटलस्य संप्रज्वलितेन्द्रकादधश्चतुर्थपृथ्वीपटलसप्तके पञ्चमपृथ्वी चतुर्थपटलस्यान्ध्रेन्द्रकादुपरि यथायोग्यं जायन्ते ॥५२५॥

कापोतलेश्योत्कृष्टांशेन मृता जीवाः तृतीयपृथ्वीनवपटलेषु द्विचरमाष्टमपटलस्य संज्वलितेन्द्रके उत्पद्यन्ते । केचित् चरमसंप्रज्वलितेन्द्रकेऽपीति विशेषोऽवगन्तव्यः । कापोतलेश्याजघन्यांशेन मृता जीवाः घर्माप्रथमपटलस्य सीमन्तेन्द्रके उत्पद्यन्ते । कापोतलेश्यामध्यमांशेन मृता जीवाः सीमन्तेन्द्रकादधस्तनद्वादशपटलेषु मेघाया द्विचरमसंज्वलितेन्द्रकादुपरितनसप्तपटलेषु द्वितीयपृथ्व्येकादशपटलेषु च यथायोग्यमुत्पद्यन्ते ॥५२६॥

होते हैं। नीललेश्याके मध्यम अंशसे मरे जीव तीसरी पृथ्वीके नौवें पटलके संप्रज्वलित इन्द्रक बिलेसे नीचे और चतुर्थ पृथ्वीके सातों पटलोंमें तथा पंचम पृथ्वीके चतुर्थ पटल सम्बन्धी आन्ध्रेन्द्रकसे ऊपर यथायोग्य उत्पन्न होते हैं ॥५२५॥

कापोतलेश्याके उत्कृष्ट अंशसे मरे जीव तीसरी पृथ्वीके नौ पटलोंमें-से द्विचरम आठवें पटलके संज्वलित इन्द्रक बिलेमें उत्पन्न होते हैं। कोई-कोई अन्तिम संप्रज्वलित इन्द्रकमें भी उत्पन्न होते हैं यह विशेष जानना। कापोतलेश्याके जघन्य अंशसे मरे जीव घर्मा नामक प्रथम पृथ्वीके प्रथम पटल सम्बन्धी सीमन्त इन्द्रकमें उत्पन्न होते हैं। कापोतलेश्याके मध्यम अंशसे मरे जीव सीमन्त इन्द्रकसे नीचेके बारह पटलोंमें मेघा नामक तीसरी पृथ्वीके द्विचरम संज्वलित इन्द्रकसे ऊपरके सात पटलोंमें और दूसरी पृथ्वीके ग्यारह पटलोंमें यथायोग्य उत्पन्न होते हैं ॥५२६॥

१. म°लेगळेळरोळं । २. जघन्यांशेनापि मृता. । मु. । ३. क. संप्रज्व° ।

मोदलागि सर्व्वार्त्थसिद्धिजखसानमाद सुररुं घर्म्मे मोदलागि अवधिस्थानावसानमाद वस्वलेश्यानुगमप्प नरत्वमुमं तिर्य्यंक्त्वमुमं यांति येय्दुवरु । एल्लनेय गत्यधिकारं तिदर्दुं ॥

नंतरं स्वाम्याधिकारमं गायासप्तकदिदं पेळ्दपं—

काऊ काऊ काऊ णीला णीला य णीलकिण्हा य ।
किण्हा य परमकिण्हा लेस्सा पढमादिपुढवीणं ॥५२९॥

गपोती कापोती तथा कापोती नीले नीला च नीलकृष्णे च । कृष्णा च परमकृष्णा लेश्याः दिपृथ्वीनां ॥

घर्म्मादिसप्तपृथ्विगळ नारकर्गे यथासंख्यमागि घर्म्मेय नारकर्गे कपोतलेश्याजघन्यमक्कुं । नारकर्गे कपोतलेश्यामध्यमांशमक्कुं । मेघेय नारकर्गे कपोतलेश्योत्कृष्टमुं नीललेश्याजघन्यांशमक्कुं । अंजनेय नारकर्गे नीललेश्यामध्यमांशमक्कुं । अरिष्टेय नारकर्गे नीललेश्योत्कृष्टमुं लेश्याजघन्यांशमुमक्कुं । मघविय नारकर्गे कृष्णलेश्यामध्यांशमक्कुं । माघविय नारकर्गे लेश्योत्कृष्टांशमुमक्कुं ।

णरतिरियाणं ओघो इगिविगले तिण्णि चउ असण्णिस्स ।
सण्णि-अपुण्णगमिच्छे सासणसम्मे वि असुहतियं ॥५३०॥

नरतिरश्चामोघ एकविकले तिस्रः चतस्रोऽसंज्ञिनः संज्ञ्यपूर्णमिथ्यादृष्टौ सासादनसम्यग्दृष्टावप्यशुभत्रयी ॥

नरतिरश्चामोघः नरतिर्य्यंचरुगळगे प्रत्येकं सामान्योक्तषड्लेश्येगळप्पुववरोळु तिर्य्यंचरोळु कविकलेपु एकेंद्रियजीवंगळ्गं विकलत्रयजीवंगळ्गं तिस्रः कृष्णाद्यशुभलेश्यात्रयमेयक्कुं ।

त्पद्यन्ते । भवनत्रयादि सर्वार्थसिद्धपन्तसुराः घर्मादवधिस्थानान्तनारकाश्च स्वस्वलेश्यानुगं नरतिर्यक्त्वं गन्ति ॥५२८॥ इति गत्यधिकारः ॥ अथ स्वाम्यधिकारं गाथासप्तकेनाह—

प्रथमादिपृथ्वीनारकाणां च लेश्योच्यते—तत्र घर्मायां कापोतजघन्यांशः । वंशायां कापोतमध्यमांशः । मेघायां कापोतोत्कृष्टांशनीलजघन्यांशौ । अंजनायां नीलमध्यमांशः । अरिष्टायां नीलोत्कृष्टांशकृष्णजघन्यांशौ । मघव्यां कृष्णमध्यमांशः । माघव्यां कृष्णोत्कृष्टांशः ॥५२९॥

नरतिरश्चां प्रत्येकं ओघः सामान्योक्तषड्लेश्याः स्युः । तत्र एकेन्द्रियविकलत्रयजीवेषु तिस्रः कृ—

कायिक, वायुकायिक, विकलत्रय, असंज्ञिपंचेन्द्रिय और साधारण वनस्पति [illegible]
होते हैं। भवनत्रिकसे लेकर सर्वार्थसिद्धि पर्यन्त देव और घर्मा पृथिवीसे [illegible]
पृथ्वी तकके नारकी अपनी-अपनी लेश्याके अनुसार मनुष्य और तिर्यंच होते हैं [illegible]

गतिअधिकार समाप्त हुआ।

आगे सात गाथाओंसे स्वामी अधिकार कहते हैं—

प्रथम पृथ्वी आदिके नारकियोंको लेश्या कहते हैं—घर्मामें [illegible]
अंश है। वंशामें कपोतका मध्यम अंश है। मेघामें कपोतका उत्कृष्ट [illegible]
अंश है। अंजनामें नीलका मध्यम अंश है। अरिष्टामें नीलका [illegible]
जघन्य अंश है। मघवीमें कृष्णका मध्यम अंश है। माघवीमें [illegible]

मनुष्यों और तिर्यंचोंमें [illegible] 'ओघ' अर्थात् [illegible]

परक्कुं। भवनत्रयर निर्वृत्यपर्य्याप्तकर्ग्गं अशुभलेश्यात्रयमेयक्कुमिदरिदमे वैमानिकर्निर्वृत्यपर्य्याप्त-कर्ग्गं पर्य्याप्तकर्ग्गं ततम्म लेश्येगळेयक्कुमेंदु सूचितमरियल्पडुवुदु। इंतनेय स्वाम्यधिकारं तीर्दुदु।

अनंतरं साधनाधिकारमनो दे गाथासूत्रदिदं पेळ्दपं।

> वण्णोदयसंपादिद सरीरवण्णो दु दव्वदो लेस्सा।
> मोहुदयखओवसमोवसमखयजजीवफंदणं भावो ॥५३६॥

वर्णोदयसंपादितशरीरवर्णस्तु द्रव्यतो लेश्या। मोहोदयक्षयोपशमोपशमक्षयजजीवस्पंदनं भावः॥

वर्णनामकर्म्मोदयसंपादितसंजनितशरीरवर्णमक्कु द्रव्यलेश्येयक्कुं। असंयतरोळु मोहोदयदिदं देशविरतत्रयदोळु मोहक्षयोपशमदिदं उपशमकरोळु मोहोपशमदिदं क्षपकरोळु मोहक्षयदिदं संजनितसंस्कारं जीवस्पंदमेंदु पेळल्पडुगुमदु भावलेश्येयक्कु। मा जीवनपरिणामप्रदेशस्पंदनदिद भावलेश्ये माडल्पडुवेंबुदर्थं। अदु कारणदिदं योगकषायंगळिदं भावलेश्ये एंदितु पेळल्पट्टु-दक्कुं। ओंभत्तनेय साधनाधिकारं तीर्दुदु ॥

अनंतरं संख्याधिकारमं गाथा षट्कदिदं पेळ्दपं :—

मनुष्यानुत्तरचतुर्दशविमानानां शुक्लेश्याया उत्कृष्टांशो भवति। भवनत्रयदेवाः अपर्याप्तकाले अशुभत्रिलेश्या एव, अनेन वैमानिकाः अपर्याप्तकाले स्वस्वलेश्या एवेति सूचितं ज्ञातव्यम् ॥५३४–५३५॥ इति स्वाम्यधिकारोऽष्टमः ॥

अथ साधनाधिकारमाह—

वर्णनामकर्मोदयेन संपादित-संजनित शरीरवर्णो द्रव्यलेश्या भवति। असंयतान्तगुणस्थानचतुष्के मोहस्य उदयेन, देशविरतत्रये क्षयोपशमेन, उपशमके उपशमेन, क्षपके क्षयेण च संजनितसंस्कारो जीवस्पन्दन-मतः स भावलेश्या जीवपरिणामप्रदेशस्पन्दनेन कृतेत्यर्थः। तेन कारणेन योगकषायाभ्यां भावलेश्येत्युक्तम् ॥५३६॥

इति साधनाधिकारो नवम. ॥ अथ संख्याधिकारं गाथाषट्केनाह—

शुक्ललेश्याका उत्कृष्ट अंश होता है। भवनत्रिकके देव अपर्याप्त अवस्थामें तीन अशुभ लेश्यावाले ही होते हैं। इससे यह सूचित किया जानना कि वैमानिक देवोंके अपर्याप्तकालमें अपनी-अपनी लेश्या ही होती है ॥५३४–५३५॥

आठवाँ स्वामिअधिकार समाप्त हुआ।

अब साधनाधिकार कहते हैं—

वर्णनाम कर्मके उदयसे उत्पन्न हुआ शरीरका वर्ण द्रव्यलेश्या है। असंयत पर्यन्त चार गुणस्थानोंमें मोहके उदयसे, देशविरत आदि तीन गुणस्थानोंमें मोहनीयके क्षयोपशम-से, उपशम श्रेणीके चार गुणस्थानोंमें मोहनीयके उपशमसे, क्षपक श्रेणीके चार गुणस्थानोंमें मोहनीयके क्षयसे जो संस्कार उत्पन्न होता है जिसे जीवका स्पन्द कहते हैं वह भावलेश्या है। अर्थात् जीवके परिणामों और प्रदेशोंका चंचल होना भावलेश्या है। परिणामोंका चंचल होना कषाय है और प्रदेशोंका चंचल होना योग है। इसीसे योग और कषायसे भावलेश्या कही है ॥५३६॥

नौवाँ साधनाधिकार समाप्त हुआ।

आगे छह गाथाओंसे संख्याअधिकार कहते हैं—

मक्कुं । भवनत्रयद निर्वृत्यपर्य्याप्तकर्गं अशुभलेश्यात्रयमेयक्कुमिदरिदमे देववैमानिकनिर्वृत्यपर्य्याप्तकर्गं पर्य्याप्तकर्गं ततम्म लेश्येगळेयप्पुवेंदु सूचितमरियल्पडुगुं । एंटनेय स्वाम्यधिकारं तोदुंदु ।
अनंतरं साधनाधिकारमनों दे गाथासूत्रदिदं पेळ्दपं ।

वण्णोदयसंपादिद सरीरवण्णो दु दव्वदो लेस्सा ।
मोहुदयखओवसमोवसमखयजजीवफंदणं भावो ॥५३६॥

वर्णोदयसंपादितशरीरवर्णस्तु द्रव्यतो लेश्या । मोहोदयक्षयोपशमोपशमक्षयजजीवस्पंदनं भावः ॥

वर्णनामकर्म्मोदयसंपादितसंजनितशरीरवर्णमदु द्रव्यलेश्येयक्कुं । असंयतरोळु मोहोदयदिदं देशविरतत्रयदोळु मोहक्षयोपशमदिदं उपशमकरोळु मोहोपशमदिदं क्षपकरोळु मोहक्षयदिदं संजनितसंस्कारं जीवस्पंदमेंदु पेळल्पडुगुमदु भावलेश्येयक्कुं । आ जीवनपरिणामप्रदेशपरिस्पंदादिद भावलेश्ये साधल्पट्टुदेंबुदत्थं । अदु कारणदिदं योगकषायंगळिदं भावलेश्ये एंदितु पेळल्पट्टुदक्कुं । ओंभत्तनेय साधनाधिकारं तीदुंदु ॥

अनंतरं संख्याधिकारमं गाथा षट्कदिदं पेळ्दपं :—

अनुदिशानुत्तरचतुर्दशविमानानां शुक्लोत्कृष्टांशो भवति । भवनत्रयदेवाः अपर्याप्तकाले अशुभत्रिलेश्या एव, अनेन वैमानिकाः अपर्याप्तकाले स्वस्वलेश्या एवेति सूचितं ज्ञातव्यम् ॥५३४–५३५॥ इति स्वाम्यधिकारोऽष्टमः ॥

अथ साधनाधिकारमाह—

वर्णनामकर्मोदयेन संपादित-संजनित शरीरवर्णो द्रव्यलेश्या भवति । असंयतान्तगुणस्थानचतुष्के मोहस्य उदयेन, देशविरतत्रये क्षयोपशमेन, उपशमके उपशमेन, क्षपके क्षयेन च संजनितसंस्कारो जीवस्पंदनसंज्ञः स भावलेश्या जीवपरिणामप्रदेशपरिस्पंदनेन इत्यर्थः । तेन कारणेन योगकषायाभ्यां भावलेश्येत्युक्तम् ॥५३६॥
इति साधनाधिकारो नवमः ॥ अथ संख्याधिकारं गाथाषट्केनाह—

शुक्ललेश्याका उत्कृष्ट अंश होता है। भवनत्रिकके देव अपर्याप्त अवस्थामें तीन अशुभ लेश्यावाले ही होते हैं। इससे यह सूचित किया जानना कि वैमानिक देवोंके अपर्याप्त अवस्थामें अपनी-अपनी लेश्या ही होती है ॥५३४–५३५॥

आठवाँ स्वामिअधिकार समाप्त हुआ।

अब साधनाधिकार कहते हैं—

वर्णनाम कर्मके उदयसे उत्पन्न हुआ शरीरका वर्ण द्रव्यलेश्या है। असंयत पर्यन्त चार गुणस्थानोंमें मोहके उदयसे, देशविरत आदि तीन गुणस्थानोंमें मोहनीयके क्षयोपशमसे, उपशम श्रेणीके चार गुणस्थानोंमें मोहनीयके उपशमसे, क्षपक श्रेणीके चार गुणस्थानोंमें मोहनीयके क्षयसे जो संस्कार उत्पन्न होता है जिसे जीवका स्पन्द कहते हैं वह भावलेश्या है। अर्थात् जीवके परिणामों और प्रदेशोंका चंचल होना भावलेश्या है। [illegible] चंचल होना कषाय है और प्रदेशोंका चंचल होना योग है। इनको [illegible] भावलेश्या कहते हैं ॥५३६॥

नौवाँ साधनाधिकार [illegible] हुआ।

आगे छह गाथाओंसे [illegible]

केवलणाणाणंतिमभागा भावादु किण्हतियजीवा ।
तेउतियासंखेज्जा संखासंखेज्जभागकमा ॥५३९॥

केवलज्ञानानन्तैकभागाः भावात् कृष्णत्रयजीवाः । तेजस्त्रयोऽसंख्येयाः संख्यासंख्येयभाग-क्रमाः ॥

[illegible]

जोइसियादो अहिया तिरिक्खसण्णिस्स संखभागो दु ।
सूइस्स अंगुलस्स य असंखभागं तु तेउतियं ॥५४०॥

[illegible]

[illegible]

सट्ठाणसमुग्घादे उववादे सव्वलोयमसुहाणं ।
लोयस्सासंखेज्जदिभागं खेत्तं तु तेउतिये ॥५४३॥

स्वस्थाने समुद्घाते उपपादे सर्वलोकोऽशुभानां । लोकस्यासंख्येयभागं क्षेत्रं तु तेजस्त्रितये ॥

अशुभांगळ् कृष्णनीलकपोताशुभलेश्यात्रयद स्वस्थानदोळं समुद्घातदोळं उपपाददोळमितु त्रिस्थानदोळं क्षेत्रं सर्वलोकमेयक्कुं ३ । तेजस्त्रितये तेजःपद्मशुक्लशुभलेश्यात्रयद स्वस्थानदोळं समुद्घातदोळं उपपाददोळमितो त्रिस्थानदोळं तु मत्ते क्षेत्रं क्षेत्रवु लोकस्यासंख्येयभागः सर्वलोकद असंख्यातेकभागमक्कुमितु सामान्यदिदमशुभलेश्येगळ्गं शुभलेश्येगळ्गं त्रिस्थानदोळु क्षेत्रं पेळल्पट्टुदु । विशेषदिदं षड्लेश्येगळ्गे दशस्थानंगळोळु क्षेत्रं पेळल्पडुगुमल्लि क्षेत्रमें बुदेने दोडे विवक्षितलेश्याजीवंगळिदं वर्त्तमानकालदोळु विवक्षितपदविशिष्टर्गाळदमवष्टब्धाकाशप्रदेशंगळं क्षेत्रमेंबुदर्थमेंबुदिल्लि सामान्यदिदं स्वस्थानमुं समुद्घातमुमुपपादमुमें बु त्रिपदंगळोळु लेश्येगळ्गे क्षेत्रं पेळल्पट्टुदु । विशेषदिदं दशस्थानंगळोळु षड्लेश्येगळ्गे क्षेत्रं पेळल्पडुगुमल्लि स्वस्थानं सामान्यदिदमोंदवं भेदिसिदोडे स्वस्थानस्वस्थानमें दुं विहारवत्स्वस्थानमें दु द्विविधमक्कुं ।

सामान्यदिदं समुद्घातमोंदवं भेदिसिदोडे वेदनासमुद्घातमें दुं कषायसमुद्घातमें दुं वैक्रियिकसमुद्घातमें दुं मारणांतिकसमुद्घातमें दुं तैजःसमुद्घातमें दुमाहारकसमुद्घातमें दुं केवलिसमुद्घातमें दितु समुद्घातं सप्तविधमक्कुमुपपादमेकप्रकारमेयक्कुं ।

विवक्षितलेश्याजीवैर्वर्तमानकाले विवक्षितपदविशिष्टैर्वनावष्टब्धाकाशः क्षेत्रम् । तच्च स्वस्थाने समुद्घाते उपपादे च त्र्यशुभलेश्यानां सर्वलोकः ≡ । तेजोलेश्यादित्रयस्य तु पुनः लोकस्यासंख्यातैकभागः सामान्येन भवति विशेषेण तु तत् दशपदेषूच्यते । तत्र तावत् उत्पन्नपुरग्रामादिक्षेत्रं तत् स्वस्थानस्वस्थानं, विवक्षितपर्यायपरिणतेन परिभ्रमितुमुचितक्षेत्रं तद्विहारवत्स्वस्थानमिति स्वस्थानं द्वेधा । वेदनादिवशेन निजशरीरात्जीवप्रदेशानां बहिःप्रदेशे तत्तद्योग्यविसर्पणं समुद्घातः । स च वेदनाकषायवैक्रियिकमारणान्तिकतैजसाहारककेवलिभेदात् सप्तधा । परित्यक्तपूर्वभवस्य उत्तरभवप्रथमसमये प्रवर्तनमुपपाद इति दशपदानि । तेषु स्वस्थानस्वस्थाने वेदनासमुद्घाते कषायसमुद्घाते मारणान्तिकसमुद्घाते उपपादे चेति पञ्चपदेषु कृष्णलेश्याजीवक्षेत्रं सर्वलोकः ≡ ।

विवक्षित लेश्यावाले जीव वर्तमान कालमें विवक्षित स्वस्थानादि पदसे विशिष्ट होते हुए जितने आकाशमें पाये जाते हैं उसका नाम क्षेत्र है। वह क्षेत्र स्वस्थान, समुद्घात और उपपादमें तीन अशुभ लेश्यावालोंका सर्वलोक है। तेजोलेश्या आदि तीनका क्षेत्र सामान्यसे लोकका असंख्यातवाँ भाग है। विशेष रूपसे दस स्थानोंमें कहते हैं—स्वस्थानके दो भेद हैं—स्वस्थानस्वस्थान और विहारवत्स्वस्थान। उत्पन्न होनेके ग्राम-नगर आदि क्षेत्रको स्वस्थानस्वस्थान कहते हैं। और विवक्षित पर्यायसे परिणत होते हुए परिभ्रमण करनेके उचित क्षेत्रको विहारवत्स्वस्थान कहते हैं। वेदना आदिके कारणसे अपने शरीरसे जीवके प्रदेशोंके उसके योग्य बाह्य प्रदेशमें फैलनेको समुद्घात कहते हैं। उसके सात भेद हैं—वेदना, कषाय, वैक्रियिक, मारणान्तिक, तैजस, आहारक और केवली समुद्घात। पूर्वभवको छोड़कर उत्तरभवके प्रथम समयमें प्रवर्तनको उपपाद कहते हैं। इस प्रकार ये दस स्थान हैं। उनमें-से स्वस्थानस्वस्थान, वेदना समुद्घात, कषाय समुद्घात, मारणान्तिक समुद्घात और उपपाद इन पाँच पदोंमें कृष्णलेश्यावाले जीवोंका क्षेत्र सर्वलोक है। अब

सट्ठाणसमुग्घादे उववादे सव्वलोयमसुहाणं ।
लोयस्सासंखेज्जदिभागं खेत्तं तु तेउतिये ॥५४२॥

स्वस्थाने समुद्घाते उपपादे सर्वलोकोऽशुभानां। लोकस्यासंख्येयभागं क्षेत्रं तु तेजस्त्रितये ॥

अशुभानां कृष्णनीलकापोताशुभलेश्यात्रयक्के स्वस्थानदोळं समुद्घातदोळं उपपाददोळमिन्तु त्रिस्थानदोळं क्षेत्रं सर्वलोकमेयक्कुं। तेजस्त्रितये तेजःपद्मशुक्लशुभलेश्यात्रयक्के स्वस्थानदोळं समुद्घातदोळं उपपाददोळमिन्ती त्रिस्थानदोळं तु मत्ते क्षेत्रं क्षेत्रमु लोकस्यासंख्येयभागः सर्वलोकद असंख्यातेकभागमक्कुमिन्तु सामान्यदिदमशुभलेश्येगळ्गं शुभलेश्येगळ्गं त्रिस्थानदोळु क्षेत्रं पेळल्पट्टुदु। विशेषदिदं पत्तुस्थानंगळोळु क्षेत्रं पेळल्पडुगुमल्लि क्षेत्रमें बुदेनें दोडे विवक्षितलेश्याजीवंगळिन्दं वर्त्तमानकालदोळु विवक्षितपदविशिष्टविवक्षितस्पृष्टाकाशप्रदेशंगळ् क्षेत्र-मेंबुदक्कुमल्लि सामान्यदिदं स्वस्थानमुं समुद्घातमुमुपपादमुमें दु त्रिविधंगळोळु लेश्येगळ्गे क्षेत्रं पेळल्पट्टुदु। विशेषदिदं दशस्थानंगळोळु पत्तुं लेश्येगळ्गे क्षेत्रं पेळल्पडुगुमल्लि स्वस्थानं सामान्यदिदमों दु भेदमदु विशेषदिदं स्वस्थानस्वस्थानमें दुं विहारवत्स्वस्थानमें दु द्विविधमक्कुं।

सामान्यदिदं समुद्घातमों दु भेदमदु विशेषदिदं वेदनासमुद्घातमें दुं कषायसमुद्घातमें दुं वैक्रियिकसमुद्घातमें दुं मारणान्तिकसमुद्घातमें दुं तैजससमुद्घातमें दुमाहारकसमुद्घातमें दुं केवलिसमुद्घातमें दिन्तु समुद्घातं सप्तविधमक्कुमुपपादमेकप्रकारमेयक्कुं।

विवक्षितलेश्याजीवैर्वर्तमानकाले विवक्षितपदविशिष्टैरवगाह्यमानाकाशं क्षेत्रम्। तच्च स्वस्थाने समुद्घाते उपपादे च अशुभलेश्यानां सर्वलोक एव। तेजोलेश्यादित्रयस्य तु पुनः लोकस्यासंख्यातैकभागः सामान्येन भवति विशेषेण तु दश स्थानेषूच्यते। तत्र तावत् उत्पन्नग्रामादिक्षेत्रं तत् स्वस्थानस्वस्थानं, विवक्षितपर्यायपरिणतेन परिभ्रमितुमुचितक्षेत्रं तद्विहारवत्स्वस्थानमिति स्वस्थानं द्वेधा। वेदनादिवशेन निजशरीराज्जीवप्रदेशानां बहिर्निर्गमनं तत्समीपोऽवस्थानं समुद्घातः। स च वेदनाकषायवैक्रियिकमारणान्तिकतैजसाहारककेवलिभेदात् सप्तधा। परित्यक्तपूर्वभवस्य उत्तरभवप्रथमसमये प्रवर्तनमुपपाद इति दशस्थानानि। तेषु स्वस्थानस्वस्थाने वेदनासमुद्घाते कषायसमुद्घाते मारणान्तिकसमुद्घाते उपपादे चेति पञ्चपदेषु कृष्णलेश्याजीवक्षेत्रं सर्वलोकः॥

विवक्षित लेश्यावाले जीव वर्तमान कालमें विवक्षित स्वस्थानादि पदसे विशिष्ट होते हुए जितने आकाशमें पाये जाते हैं उसका नाम क्षेत्र है। यह क्षेत्र स्वस्थान, समुद्घात और उपपादमें तीन अशुभ लेश्यावालोंका सर्वलोक है। तेजोलेश्या आदि तीनका क्षेत्र सामान्यसे लोकका असंख्यातवाँ भाग है। विशेष रूपसे दस स्थानोंमें कहते हैं—स्वस्थानके दो भेद हैं—*स्वस्थानस्वस्थान* और *विहारवत्स्वस्थान*। उत्पन्न होनेके ग्राम-नगर आदि क्षेत्रको स्वस्थानस्वस्थान कहते हैं। और विवक्षित पर्यायसे परिणत होते हुए परिभ्रमण करनेके उचित क्षेत्रको विहारवत्स्वस्थान कहते हैं। वेदना आदिके कारणसे अपने शरीरसे जीवके प्रदेशोंके उसके योग्य बाह्य प्रदेशमें फैलनेको समुद्घात कहते हैं। उसके सात भेद हैं—*वेदना, कषाय, वैक्रियिक, मारणान्तिक, तैजस, आहारक* और *केवली समुद्घात*। पूर्वभवको छोड़कर उत्तरभवके प्रथम समयमें प्रवर्तनको उपपाद कहते हैं। इस प्रकार ये दस स्थान हैं। उनमें-से स्वस्थानस्वस्थान, वेदना समुद्घात, कषाय समुद्घात, मारणान्तिक समुद्घात और उपपाद इन पाँच पदोंमें कृष्णलेश्यावाले जीवोंका क्षेत्र सर्वलोक है। अब

सीनुपपादपद कृष्णलेश्याजीवंगळ संख्येयं फल राशियं माडि मारणांतिकसमुद्घातकालप्रमाणमंत-र्मुहूर्तमदनिच्छाराशियं माडि गुणियिसुत्तं विरलु प्र स १ फ = १३ – / ३—५। ५५। २१ इच्छे २७। लब्ध-राशियं मूलराशिय संख्यातेकभागमक्कुमा मारणांतिकसमुद्घातपददोळु कृष्णलेश्याजीवंगळप्पुवु १३ / ३—१ मत्तं कृष्णलेश्याप्रसपर्य्याप्तराशियं संख्यातदिदं भागिसि बहुभागमं =४ / ३—४।५ / ५ स्वस्थान-स्वस्थानदोळिप्पु दोषैकभागमं मत्तं संख्यातदिदं भागिसि बहुभागमं =४ / ३—४।५।५ / ५— विहारवत्स्वस्थान-पददोळिप्पु दोषैकभागमं $\overset{=}{४}$। ३—। १ / ५ ।५।५ शेषपदंगळोळु यथायोग्यमागि ज्ञातव्यमप्पुवु।

त्रसपर्य्याप्तमध्यमावगाहनजनितसंख्यातघनांगुलंगळं फलराशियंमाडि विहारवत्स्वस्थानकृष्णलेश्या-जीवराशियनिच्छाराशियं माडि प्र १ फ ६१ ६ =४ / ३—४।५।५ लब्धराशियनपवर्त्तिसिदोडे संख्यात-सूच्यंगुलगुणितजगत्प्रतरमात्रं विहारवत्स्वस्थानदोळु क्षेत्रमक्कुं। = सू २१। मत्तं पल्यासंख्यात-

---

भागः—४। ३—५। स्वस्थानस्वस्थानेऽस्तीति देयः। शेषैकभागस्य संख्यातभक्तबहुभागो =४ / ४। ३—५।५ / ५— विहार-वत्स्वस्थाने देयः। शेषैकभागः = १ / ४। ३ ५।५ / ५— शेषपदेषु यथायोग्यं पतितोऽस्तीति ज्ञातव्यः। त्रसपर्याप्तमध्य-मावगाहनं संख्यातघनाङ्गुलं फलराशिं कृत्वा विहारवत्स्वस्थानकृष्णलेश्याजीवराशिमिच्छां कृत्वा—

प्र १। फ ६ १। इ =४ / ४। ३—५।५ / ५— लब्धमपवर्तितं संख्यातसूच्यङ्गुलगुणितजगत्प्रतरो विहारवत्स्वस्थाने क्षेत्रं

त्रस जीवोंके प्रमाणको संख्यातसे भाग देकर बहुभाग प्रमाण स्वस्थानस्वस्थानवाले जीव हैं। शेष एक भागमें संख्यातका भाग देकर बहुभाग प्रमाण विहारवत्स्वस्थानवाले जीव हैं। शेष एक भाग रहा सो शेष स्थानोंमें यथायोग्य जानना। त्रसपर्याप्त जीवोंकी मध्यम अवगाहनाके अनेक प्रकार हैं। उसे बराबर करनेपर एक त्रसपर्याप्त जीवकी मध्यम अवगाहना संख्यात घनांगुल है। उसे फलराशि करके और विहारवत्स्वस्थान की अपेक्षा कृष्ण-लेश्यावाले जीवोंकी राशिको इच्छाराशि करो। तथा एक जीवको प्रमाणराशि करो। फलसे इच्छाको गुणा करके प्रमाण राशिका भाग देनेपर संख्यात सूच्यंगुलसे गुणित जगत्प्रतर प्रमाण विहारवत्स्वस्थानका क्षेत्र आता है।

---

१. म °भागमसंख्यात बहुभागं°। २. म °ब्यंगळप्पुवु। ३. ब. °ति ज्ञातव्यः।

	स्वस्थान स्वस्थान	विहार	वेदना-समुद्घात	कषाय समुद्घात	वैक्रियिक समुद्घात	मारणान्तिक समुद्घात	तैज	आहा	के	उपपाद	
क्र	३।१३-४ / ३-५	३।१९६ / ११५५	३।१३-४ / ३-५५	३।१३-४ / ३-५५५	-१९१६ / ३-५५५५	३।१३- / ३-७	०	०	०	११- / ३-९३।७	सर्वलोक
ती	३।१३-४ / ३५	३।१९६ / ३७५५	३।१३-४ / ३१५५	३।१३-४ / ३-५५५	-१९१६ / ८५५५५	३१३- / ३७	०	०	०	११- / ३९३।७	सर्वलोक
म	३।१३-४ / ३-५	३।१९६ / ३१५५	३।१३-४ / ३१५५	३।१३-४ / ३-५५५	-१९१६ / ३५५५५	३।१३- / ३७	०	०	०	११- / ३९३।७	मनुष्यलोक

भत्तं सामान्यलोकम अधोलोकमूर्ध्वलोकमूर्ध्वं तिर्यग्लोकमूर्ध्वं मनुष्यलोकमूर्ध्वं [illegible] स्वस्थानस्वस्थान - वेदनापद - मारणान्तिक [illegible] [illegible] विहारवत्स्वस्थान [illegible] सामान्यदि पूर्व लोकम [illegible] [illegible] [illegible] वैक्रियिकपद [illegible] सामान्यदि [illegible] मनुष्यलोक [illegible]

[illegible]

पुनः सामान्य लोक, अधोलोक, ऊर्ध्वलोक, तिर्यक् लोक और मनुष्यलोक इन पाँचों की अपेक्षा करके कथन करते हैं—स्वस्थानस्वस्थान और [illegible], वेदना, कषाय, मारणान्तिक और उपपाद [illegible] [illegible] रहते हैं। [illegible] विहारवत्स्वस्थानमें सामान्यलोक, अधोलोक, [illegible] [illegible] रहते हैं। [illegible] [illegible] रहते हैं। [illegible] रहते हैं। वैक्रियिक समुद्घात [illegible]

१. म [illegible]।

(७)

॥ १ = ४। ६५=१५५५५ इल्लि सप्तधनुरुत्सेधमुं ७ तद्दशमभागमुखविस्तारमुं ७/१० अप्प देवावगाहनंगळोळु:-

"वासो तिगुणो परिही वासचउत्थाहदो दु खेत्तफळं, ७।३।७।७ / १०।१०।४ खेत्तफळं वेहगुणं ७।३।७।७ / १०।१०।४ खादफळं होइ सव्वत्थ।"

एंदी देवावगाहनमं घनात्मकंगळप्प धनुगळंगुळंगळं माडल्वेडि तों भत्तारर घनात्मकदिंदं गुणियिसि मत्तमादंगुलंगळं प्रमाणांगुलंगळं माडल्वेडि पंचशतदिंदं घनात्मकदिंदं भागिसि स्थापिसि— ७।३।७।७।९६।९६।९६ / १०।१०।४।५००।५००।५०० अपवर्त्तितिरोडे देवावगाहनं प्रमाणघनांगुलसंख्यातैकभाग- (७) ॥ = ४।६५।=७५७ १।४।९। मत्तमी येकावगाहनद एकादि-

घनायधुर्गुणात्रे च हत्वा ॥ = ४।६५=१।५।५।५।५ १— १४ घेपैकभागो वैक्रियिकसमुद्घाते देवः

॥ = ४।६५=१५।५।५।५ १— ११ अत्र स्वस्थानस्वस्थानराशिः सप्तधनुरुत्सेध ७ तद्दशांशमुखविस्तारविस्तार ७/१० देवावगाहनेन वासोत्तिगुणेत्यानीतघनरूपखातफलेन ७।३।७।७ / १०।१०।४ घनाङ्गुलीकर्तुं षण्णवतिघनगुणितेन पुनः प्रमाणाङ्गुलीकर्तुं पञ्चशतघनभक्तेन ७।३।७।७।९६।९६।९६ / १०।१०।४।५००।५००।५०० अपवर्तिते जातघनाङ्गुल-

प्रकार जीवोंका प्रमाण कहा। स्वस्थानस्वस्थान अपेक्षा क्षेत्रका प्रमाण लानेके लिए कहते हैं—तेजोलेश्या मुख्य रूपसे भवनत्रिक आदि देवोंमें होती है। उनमें एक देवकी अवगाहना-का प्रमाण सात धनुष ऊँचा और सात धनुषके दसवें भाग चौड़ा है। इसका क्षेत्रफल लानेके लिए सात धनुषके दसवें भाग चौड़ाईको तिगुना करनेपर परिधि होती है क्योंकि चौड़ाईसे तिगुनी परिधि कही है। इस परिधिको चौड़ाईके चतुर्थ भागसे गुणा करनेपर क्षेत्रफल होता है। इसको ऊँचाई सात धनुषसे गुणा करनेपर घनरूप क्षेत्रफल होता है। घनरूप राशिके गुणकार भागहार घनरूप ही होते हैं। सो यहाँ घनांगुल करनेके लिए एक [illegible] छियानवे अंगुल होते हैं अतः घनरूप क्षेत्रफलको छियानवेके घनसे [illegible] गुलसे है और देवोंके शरीरका प्रमाण उत्सेधांगुलसे [illegible] अतः [illegible] भाग

१. म°गलुमनंगुल°।

[illegible] विस्तारद्दु [illegible] २ । २ संख्यातघनाङ्गुलदिंदं विहारवत्-
१ । १
मो १

[illegible] गुणिसुत्तं $\frac{\overset{॥}{=} \cdot \frac{1}{}}{}$ १४ । ६ ७ / ४ । ६५ = ५६ [illegible] विशुनिसिद

[illegible] संख्यातघनाङ्गुलदिंदं वैक्रियिक समुद्घातराशियं गुणिसुत्तं—

= ११६ । ७ / ४६५ = ७११११ [illegible] गुणिसुत्तं विरलु [illegible] । [illegible]

[illegible] । १०००० । [illegible] ७ ११ भा १२ =

[illegible] = ४६५ = ८१ । १० । ७११ [illegible]

[illegible] भागिसि एकभागमं [illegible]

[illegible] ६५ = ८१ । १० । ७११ [illegible] मारणान्तिकसमुद्घातरहित-

[illegible]

[illegible] ६ । ९ [illegible] विहारवत्स्वस्थानराशिः
१ । २

[illegible] ७ । २ अनिर्गतंख्यातघनाङ्गुलैः ६ १ [illegible]
१ १
मो १

[illegible] संख्यातघनाङ्गुलैः ६ १ [illegible] १०००० [illegible] ७ ११ [illegible]

[illegible] = [illegible] ६ । ६५ = ८१ । १० । ७ ११

...की क्षेत्रका प्रमाण आता है। वैक्रियिक समुद्घातके सम्बन्धमें यह तात्पर्य है कि ...मूलशरीर तो अपने क्षेत्रमें रहते हैं और विहार करते हुए विक्रियात्मक शरीर अन्य ...होते हैं। दोनोंके बीचमें आत्माके प्रदेश सूच्यंगुलके संख्यातवें भागमात्र ऊँचे चौड़े हैं। और उतर सूच्यंगुलकी अपेक्षा संख्यात योजन लम्बे रहते हैं। तथा देव अपनी ...हाथी, घोड़ा इत्यादि रूप विक्रिया करते हैं। उसकी अवगाहना एक जीवकी ...संख्यात घनांगुल प्रमाण है। इससे पूर्वमें कहे वैक्रियिक समुद्घात करनेवाले जीवों-...को गुणा करनेपर *सर्व जीव सम्बन्धी वैक्रियिक समुद्घातमें क्षेत्रका परिमाण आता* ...पंचेन्द्रियोंमें व्यन्तर देवोंका प्रमाण अधिक होता है अतः उनकी मुख्यतासे यहाँ ...वैक्रियिक समुद्घात सम्बन्धी कथन करते हैं। व्यन्तर देवोंकी संख्यामें एक व्यन्तर देवकी

...[illegible] बहिर्निर्गतात्मप्रदेशावगाहनाघेन २ २ अनिर्गतंख्यातघनाङ्गुलै ६ १ इत्यनेनः।
१ १

तंख्यातदिदं संडिसिद बहुभागं विग्रहगतियोळप्पुवु -३ प मत्तमिदं पल्यासंख्यातदिदं
प प
a a

सिद बहुभागंगळु मारणांतिकसमुद्घातमुळ्ळवप्पुवु - ३ प प इवर पल्यासंख्यातैकभाग-
a a
प प प
a a a

गळु दूरमारणांतिकसमुद्घातजीवंगळप्पुवु -३ प प ई दूरमारणांतिकसमुद्घातजीव-
a a
प प प प
a a a a

य द्वितीयदीर्घदंडस्थितमारणांतिकपूर्व्वोपपादजीवागमनार्त्थं पल्यासंख्यातदिदं भागिसिदेक-

मुपपादजीवंगळप्पुवु -३ प प ईयुपपादजीवराशियं समीकरणकृततिर्य्यग्जीवमुखप्रमाण-
a a
प प प प प
a a a a a

तेन भक्ते एकभाग. प्रतिसमयं म्रियमाणराशिर्भवति—३ तस्मिन् पल्यासंख्यातेन भक्ते बहुभागो विग्रहगतौ
प
a

—३ प तस्मिन् पल्यासंख्यातेन भक्ते बहुभागो मारणान्तिकसमुद्घाते भवति
प प a
a a

—३ प प अस्य पल्यासंख्यातैकभागो दूरमारणान्तिके जीवा भवन्ति —३ । प प १
प प a a प प प प a a
a a a a a a

न् द्वितीयदीर्घदण्डस्थितमारणान्तिकपूर्वोपपादजीवानानेतुं पल्यासंख्यातेन भक्ते एकभाग उपपादजीव-

---

की मुख्यतासे कहते हैं। सो सौधर्म और ऐशान स्वर्गके देवोंकी राशि घनांगुलके तीसरे मूलसे गुणित जगतश्रेणि प्रमाण है। इसमें पल्यके असंख्यातवें भागसे भाग देनेपर एक भाग प्रमाण प्रतिसमय मरनेवाले जीवोंकी राशि होती है। उसमें पल्यके असंख्यातवें भागसे भाग देनेपर बहुभाग प्रमाण विग्रहगतिवाले जीवोंका प्रमाण होता है। उस प्रमाणमें पल्यके असंख्यातवें भागसे भाग देनेपर बहुभाग प्रमाण मारणान्तिक समुद्घात करनेवाले जीवोंका प्रमाण होता है। उसमें पल्यके असंख्यातवें भागसे भाग देनेपर एक भाग प्रमाण दूर मारणान्तिक करनेवाले जीव होते हैं। इसमें द्वितीय दीर्घदण्डमें स्थित मारणान्तिक समुद्घातसे पूर्व होनेवाले उपपादसे युक्त जीवोंका प्रमाण लानेके लिए पल्यके असंख्यातवें भागसे भाग देनेपर एक भाग प्रमाण उपपाद जीवोंका प्रमाण होता है। यहाँ तिर्यंचोंके उत्पन्न होने-

यगाहनमं वासो तिगुणो परिहीत्यादि २००० । ३ । २००० २००० ददं संख्यातघनांगुलंगळिवं
९ ९ । ४
गुणिसि स्व – स्व – = ४ । ६ । ३ विहारव स्वस्थान = ४ । ६ । ३
४ । ६५ = ३ । ६ । ५ ४ । ६५ = ३ । ५ । ५ ५

मत्तमा पाढंमात्रदिवं ६ ३ । ९ तृतीयचतुर्थराशिगळुमं गुणिसिवु वेद = ४६ । ७१९ कषा
२ ४६५ = ३ । ६ । ५ । ५ । ५

= ६ । ३ । ९ इंतु गुणिसुत्तं विरलु स्वस्थानस्वस्थानादि चतुःपदंगळोळु
४ । ६५ = ३ । ६ । ५ । ५ । ५ । २

क्षेत्रंगळप्पुवु । मत्तं सनत्कुमारमाहेंद्र देवराशियं निजेकावगमूलभाजितजगच्छ्रेणिप्रमितमं संख्यात-

दिवं भागिसि बहुबहुभागमं स्वस्थानस्वस्थानदोळिरुत्तं विरिपुवु –४ शेषैकभागमं संख्यातदिवं
११ ५

भागिसिद बहुभागमं विहारवत् स्वस्थानदोळिर्पुदे विवरिपुवु –४ शेषैकभागं संख्यातबहुभागं
११ । ५ । ५

शेषैकभागः कषायसमुद्घाते वेद = १ अत्र पद्मलेश्यानां अवगाहनमाद-
६ । ६५ = ३ । ६ । ५ । ५ ।

मुख्यत्वात्क्षेत्रं तस्यावगाहनेन वासो तिगुणो परिहीत्यादि २००० । ३ । २००० । २००० नीतसंख्यात-
९ ९ । ४

घनांगुलेन । ६ । ३ । गुणयेत् । स्व स्व = ४ । ६ । ३ वि = ४ । ६ । ३ तृतीयचतुर्थराशी च
४६५ = ३ । ६ । ५ ४ । ६५ = ३ । ६ । ५ । ५

सार्धचतुर्गुणावगाहनेन ६ । ३ । ९ गुणयेत् । वेद = ४ । ६ । ३ । ९ कषा = ६ । ३ । ९
२ २ २
४ । ६५ = ३ । ६ । ५ । ५ । ५ ४ । ६५ = ३ । ६ । ५ । ५ । ५

तथा सति स्वस्थानादिचतुःपदेषु क्षेत्राणि भवन्ति । पुनः सनत्कुमारमाहेन्द्रदेवराशौ निजैकादशमूलभाजितजगच्छ्रे-

णिप्रमिते ११ संख्यातेन भक्तेऽनन्तस्य बहुभागबहुभागः स्वस्थानस्वस्थाने ११ । ५ । विहारवत्स्वस्थाने ११ । ५ । ५

भाग कषाय समुद्घातका जानना। इस प्रकार जीवोंकी संख्या जानना। पद्मलेश्यावाले तिर्यंच जीवोंकी अवगाहना बहुत है। अतः यहाँ उनकी मुख्यतासे क्षेत्रका कथन करते हैं— स्वस्थान-स्वस्थान और विहारवत्स्वस्थानमें एक तिर्यंच जीवकी अवगाहना एक कोस लम्बी और उसके नौवें भाग मुखका विस्तार है। इसका क्षेत्रफल 'वासो तिगुणो परिही' इत्यादि सूत्रके अनुसार संख्यात घनांगुल होता है। इससे स्वस्थानस्वस्थानवाले जीवोंकी संख्याको गुणा करनेपर स्वस्थानस्वस्थान सम्बन्धी क्षेत्र होता है। इसे विहारवत्स्वस्थानवाले जीवोंकी संख्यासे गुणा करनेपर विहारवत्स्वस्थानका क्षेत्र होता है। उक्त अवगाहनासे पूर्वोक्त प्रकारसे साढ़े चार गुना क्षेत्र एक जीवकी अपेक्षा वेदना और कषाय समुद्घातमें होता है। इससे पूर्वोक्त वेदना और कषाय समुद्घातवाले जीवोंकी संख्यामें गुणा करनेसे वेदना और कषाय समुद्घातकी अपेक्षा क्षेत्र होता है।

वैक्रियिक समुद्घातमें पद्मलेश्यावाले जीव सानत्कुमार [illegible] स्वर्गमें बहुत हैं इसलिए उनकी अपेक्षा कथन करते हैं—सानत्कुमार माहेन्द्रमें [illegible] जगतश्रेणीके

[illegible]समुद्घात जीवक्षेत्रफलं — [illegible] [illegible] [illegible]

[illegible]समुद्घातजीवक्षेत्रफलं — [illegible] [illegible] [illegible]

[illegible]समुद्घातजीवक्षेत्रफलं — [illegible] [illegible] [illegible]

[illegible]

[illegible] — [illegible] [illegible] [illegible]

[illegible] — [illegible] [illegible]

[illegible]

'मरदि असंखेज्जदिमं' इत्यादि गाथासूत्रके अनुसार सानत्कुमार माहेन्द्र स्वर्गके देवोंके प्रमाणमें पल्यके असंख्यातवें भागसे भाग दें। एक भाग प्रमाण देव प्रतिसमय मरते हैं। इस राशिमें भी पल्यके असंख्यातवें भागसे भाग दें। बहुभाग प्रमाण विग्रहगतिवाले जीव होते हैं। इस राशिको पल्यके असंख्यातवें भागसे भाग दें। बहुभाग प्रमाण मारणान्तिक समुद्घातवाले जीव हैं। इस राशिको भी पल्यके असंख्यातवें भागसे भाग दें। एक भाग प्रमाण दूर मारणान्तिक समुद्घात करनेवाले जीव हैं। इस राशिको भी पल्यके असंख्यातवें भागसे भाग दें। एक भाग प्रमाण [illegible] जीवोंका प्रमाण है। सानत्कुमार माहेन्द्रके देवोंके द्वारा किये गये मारणान्तिक दण्डका क्षेत्र तीन राजू लम्बा और सूच्यंगुलके संख्यातवें भाग चौड़ा व ऊँचा है। उसका घनक्षेत्रफल घनांगुलके संख्यातवें भागसे तीन राजूको गुणा करनेपर जो प्रमाण हो उतना है। इस घनक्षेत्रफलसे दूर मारणान्तिक समुद्घातवाले जीवोंकी राशिको गुणा करनेपर मारणान्तिक समुद्घातमें क्षेत्रका प्रमाण होता

१. ब. °र्ति मरन्तु°।

भागिसि भागिसि बहुभागबहुभागंगळं स्वस्थानस्वस्थानदोळं प ४ विहारवत् स्वस्थानदोळं
ӘȘ ५
प ४ वेदनासमुद्घातदोळं प ४ कषायसमुद्घातदोळं प ४ कोट्टु शेषैकभागमं
ə ५५ ə ५५५ ə ५५५५
वैक्रियिकसमुद्घातदोळीयुदु प १ वलिक्कमो पंचराशिगळोळु प्रथमराशियं तृतीयराशियं
ə ५५५५
चतुर्थराशियुमं यथासंख्यमागि त्रिहस्तोत्सेध तद्दशमभागमुखव्यासदिंदं "व्यासस्त्रिगुणः परिधिर्व्यासचतुर्थाहतस्तु क्षेत्रफलम् । क्षेत्रफलं वेदगुणं खातफलं भवति सर्वत्र ।" एंदी सूत्राभिप्रायदिंदं ह । ३ । ३ । ह ३ । ह ३ जनितदेवावगाहनप्रमाणवृंदांगुलसंख्यातैकभागदिंदं
१० । १० । ४
मत्तं नवार्द्धघनांगुलसंख्यातभागदिंदं मत्तं तावन्मात्रदिंदं गुणिसिदोडे यथाक्रमदिं स्वस्थानपरस्थानवेदनासमुद्घातकषायसमुद्घातक्षेत्रंगळप्पुवु । स्व = स्व - प ४ । ६ वेद
ə ५ । १
प ४ । ६ । ९ कषाय— प ४ । ६ । ९ मत्तं विहारवत्स्वस्थानद्वितीयपदजीवराशियसंख्यात-
ə ५५५१।२ ə ५५५५१ । २
योजनायामसूच्यंगुलसंख्यातभागविष्कंभोत्सेध २ १ २ १ क्षेत्रघनफलं संख्यातघनांगुलंगळिदं गुणिसि-
यो १

वैक्रियिकसमुद्घाते दद्यात्—प १ अत्र प्रथमराशौ त्रिहस्तोत्सेधतद्दशमभागमुखव्यासैकदेवावगाहनस्य
ə ५५५५
व्यासो तिगुणो परिहीत्याद्यानीत ह ३ । ३ ह । ३ ह ३ घनफलेन घनाङ्गुलसंख्यातैकभागेन ६ पुनस्तृतीयराशौ
१० । १० । ४ । १
नवार्धघनाङ्गुलसंख्यातभागेन ६ । ९ पुनश्चतुर्थराशौ तावतैव च ६ । ९ गुणिते सति क्रमेण
१ । २ १ । २
स्वस्थानस्वस्थानवेदनासमुद्घातक्षेत्राणि भवन्ति—स्व = प । ४ । ६ वेद —प ४ । ६ । ९ कषा
ə ५ । १ ə ५५५ १ । १
= प ४ ६ । ९ पुनः द्वितीयराशौ संख्यातयोजनायामसूच्यङ्गुलसंख्यातभागविष्कम्भोत्सेध—२१ । २१
१ ५५५५५ १ २ यो १

शेष एक भाग प्रमाण जीव वैक्रियिक समुद्घातमें जानना। शुक्ललेश्यावाले देवोंकी मुख्यता होनेसे एक देवकी अवगाहना तीन हाथ ऊँची और उसके दसवें भाग मुखकी चौड़ाई है। 'वासो तिगुणो परिही' इत्यादि सूत्रके अनुसार क्षेत्रफल घनांगुलका संख्यातवाँ भाग होता है। इससे स्वस्थानस्वस्थानवाले जीवोंके प्रमाणको गुणा करनेपर स्वस्थानस्वस्थान सम्बन्धी क्षेत्रका परिमाण होता है। एक जीवका मूलशरीरकी अवगाहनासे साढ़े चार गुणा क्षेत्र वेदना तथा कषाय समुद्घातमें होता है। इस साढ़े चार गुणा घनांगुलके संख्यातवें भागसे वेदना और कषाय समुद्घातवाले जीवोंके प्रमाणको गुणा करनेपर वेदना और कषाय समुद्घातमें क्षेत्र होता है। एक देवके विहार करते हुए अपने मूलशरीरसे बाहर निकल उत्तर विक्रियासे उत्पन्न हुए शरीर पर्यन्त आत्माके प्रदेश संख्यात योजन लम्बे और सूच्यंगुलके संख्यातवें भाग चौड़ा व ऊँचा क्षेत्र रोकते हैं। इसका घनरूप क्षेत्रफल संख्यात घनांगुल होता है। इससे विहारवत्स्वस्थान जीवोंके प्रमाणको गुणा करनेपर

[illegible] कपाटसमुद्घाते [illegible] लोकपूरणसमुद्घाते [illegible] [illegible]

[illegible] [illegible] [illegible] [illegible] [illegible] [illegible] [illegible]

[illegible] [illegible] [illegible] [illegible] १२ । ३ । १२ । [illegible] [illegible]

४ । ७

[illegible] —४ । [illegible] [illegible] [illegible] [illegible] [illegible] [illegible] [illegible] [illegible] [illegible] पूर्वाभिमुख [illegible] —मू २ । ९१० ॥ [illegible]

[illegible]

[illegible] ४ । ४

[illegible]

केवलिसमुद्घात दण्ड, कपाट, प्रतर और लोकपूरणके भेदसे चार प्रकारका है। दण्ड समुद्घात स्थित और उपविष्टके भेदसे दो प्रकारका है। कपाट समुद्घात भी पूर्वाभिमुख, उत्तराभिमुखके भेदसे तथा स्थित और उपविष्टके भेदसे चार प्रकारका है। प्रतर और लोकपूरण समुद्घात एक-एक ही है। [illegible]

---

१. [illegible]

सत्तासीदिचतुस्सदसहस्सतिसीदिलक्खउणवीसं ।
चउवीसधियं कोडीसहस्सगुणिदं तु जगपदरं ॥
सट्ठीसत्तसएहिं णवयसहस्सेगलक्खभजिदं तु ।
सव्वं वादारुद्धं गुणिधं भणिदं समासेण ॥ —त्रिलोक. १३९-१४० गा. ।

एंदी सूत्रद्वयदिदं पेळल्पट्ट सर्व्ववातावरुद्धक्षेत्रयुतियं = १०२४१९८३४८७ / १०१९७ २० सर्व्वलोकासंख्यातेकभागमं ≡ १ / a कळेदुळिद सर्व्वलोकमेकजीवप्रतिबद्धप्रतरसमुद्घातक्षेत्रमक्कु ≡ -- / a a लोकपूरणसमुद्घातदोळमेकजीवप्रतिबद्धक्षेत्रमुं सर्व्वलोकमक्कु ≡ । मिल्लि आरोह-

---

घातचत्वारिंशत्सूच्यङ्गुलहतजगत्प्रतरमुत्तराभिमुखासीनकवाटसमुद्घातक्षेत्रं भवति = सू २ । १४४० प्रतर-समुद्घातस्य बहिर्वातत्रयाभ्यन्तरे सर्वलोके व्याप्तत्वात् तद्वातक्षेत्रफलेन लोकासंख्यातैकभागेन ≡ । १ / a ऊनं लोकमात्रमेकजीवप्रतिबद्धक्षेत्रं भवति ≡ -- / a a लोकपूरणसमुद्घाते एकजीवप्रतिबद्धक्षेत्रं सर्वलोको भवति ≡ अत्र

अधोलोकके नीचे सात राजू चौड़ा है। क्रमसे घटते-घटते मध्यलोकमें एक राजू चौड़ा है। इसका क्षेत्रफल निकालनेके लिए करणसूत्रके अनुसार मुख एक राजू, भूमि सात राजू दोनोंको जोड़नेपर आठ हुए। उसका आधा चारको अधोलोककी ऊँचाई सातसे गुणा करनेपर अठाईस राजू अधोलोकका प्रतररूप क्षेत्रफल होता है। मध्यलोकमें एक राजू चौड़ा है। वहाँसे बढ़ते-बढ़ते ब्रह्मस्वर्गके निकट पाँच राजू चौड़ा है। सो यहाँ मुख एक राजू, भूमि पाँच राजू। दोनोंको जोड़नेपर छह हुए। उसका आधा तीनसे मध्य लोकसे ब्रह्मस्वर्ग तक की ऊँचाई साढ़े तीन राजूसे गुणा करनेपर आधे ऊर्ध्वलोकका क्षेत्रफल साढ़े दस राजू होता है। इतना ही क्षेत्रफल ऊपरके आधे ऊर्ध्वलोकका होता है। इसमें अधोलोकका फल मिलानेपर जगत्प्रतर होता है। बारह अंगुल प्रमाण उत्तर-दक्षिण दिशामें ऊँचा है। सो जगत्प्रतरको बारह सूच्यंगुलसे गुणा करनेपर एक जीव-सम्बन्धी क्षेत्र बारह अंगुल गुणित जगत्प्रतर प्रमाण होता है। इसको चालीससे गुणा करनेपर चार सौ अस्सी अंगुलसे गुणित जगत्प्रतर प्रमाण उत्तराभिमुख कपाट समुद्घातका क्षेत्र होता है। स्थितमें ऊँचाई बारह अंगुल कही, उपविष्टमें (बैठनेपर) उससे तिगुनी छत्तीस अंगुल ऊँचाई होती है। अतः उक्त प्रमाणको तीनसे गुणा करनेपर एक हजार चार सौ चालीस सूच्यंगुलसे गुणित जगत्प्रतर प्रमाण उत्तराभिमुख बैठे हुए कपाट समुद्घातसम्बन्धी क्षेत्र होता है। प्रतरसमुद्घातमें तीन वातवलयको छोड़कर सर्वलोकमें प्रदेश व्याप्त होते हैं। सो तीन वातवलयका क्षेत्रफल लोकका असंख्यातवाँ भाग है। इसे लोकमें घटानेपर जो शेष रहे उतना एक जीव सम्बन्धी

१. ब. °मुखस्थितक°।

क्षे	स्वस्थानस्वस्थान	विहा.स्वस्थान	वेदना समुद्घात	कषाय समुद्घात	वैक्रि. समुद्घात	मारणांति. समुद्घात	तैजस	आहार.
ते	≡ ३ । ४ । ६ ४६५=७ । ५ । ७	≡ ३ । ४ । ६।७ ४ । ६५=७ । ५५	≡ ३ । ४।६।९ ७ २ ४६५=७५५५	≡ ३ । ४।६ । ९ ७२ ४६५=७५५५५	≡ ३ । ४ । ६।७ ४।६।५=७।५५५५	≡ प प १०३-४ a a ७७ ४६५=८:।१०३७ प प प a a a	७।६७	७६७
प	=६७।४ ४।६५=७६५	=४ । ६७ ४।६५=७६५५	=४६ । ७ । ९ ४।६५=७६५५५२	=६ । ७ । ९ ४।६५=७६।५५५२	–६७ ११ । ५५५५	प प ३ ३ । ४ a a ११ प प प प ७ a a a a	७।६७	७६७
धु	प ४ । ६ a ५ । ७	प ४ । ६७ a ५५	प ४ । ६९ a ५५५७२	प ४ । ६ । ९ a ५५५५।७२	प ६७ a ५५५५	७–६ । ४ ७ ७	७।६७	७६७

विशेषविदं स्वस्थानस्वस्थानादिदशपदंगळोळु स्पर्शं पेळल्पडुगुमदेंतेंदोडे तिर्य्यग्लोकद रज्जुप्रतरक्षेत्रदोळु ७ जलचरसहितंगळप्प लवणोदकालोदस्वयंभूरमणसमुद्रमेंबी समुद्रत्रय-



७

रहितसर्व्वसमुद्रक्षेत्रफलमं कळेयुत्तिरलु शेषक्षेत्रं शुभत्रयलेश्यास्वस्थानस्वस्थानस्पर्शक्षेत्रमक्कुं । तदानयनक्रमं पेळल्पडुगुमदेंतेंदोडे जंबूद्वीपमादियागि स्वयंभूरमणसमुद्रपर्य्यंतमाद सर्व्वद्वीपसमुद्रंगळु द्विगुणद्विगुण विस्तीर्णंगळागिरुतिर्प्पुवु १ ल । २ ल । ४ ल । ८ ल । १६ ल । ३२ ल । ६४ ल । १२८ ल । २५६ ल । ५१२ ल । इल्लि लक्षयोजनविष्कंभमप्प जंबूद्वीपसूक्ष्मक्षेत्रफलं :—

सत्त णव सुण्ण पंच य छण्णव चउरेक्क पंच सुण्णं च ।
जंबूदीवस्सेदं गुणिदफळं होदि णादव्वं ॥

७९०५६९४१५० एतावन्मात्रं जंबूद्वीपगुणितफलमक्कुमिदनोंदु खंडमेंदु माडल्पडुवुदु । १ । मत्तं लवणसमुद्रदोळु तत्प्रमाणखंडंगळु चतुर्व्विंशतिगळप्पुवु । २४ । धातकीषंडद्वीपदोळु चतुरुत्तरचत्वारिंशच्छतप्रमितंगळप्पुवु । १४४ ।

कालोदकसमुद्रदोळु षट्छतद्वासप्ततिप्रमाणंगळप्पुवु ६७२ । पुष्करवरद्वीपदोळु अशीत्युत्तराष्टाविंशतिशतप्रमितंगळप्पुवु २८८० । तत्समुद्रदोळु एकादशसहस्रनवशतचतुःप्रमितखंडंगळप्पुवु

उक्तः । विशेषेण तु दशपदेषु उच्यते—तिर्यग्लोकस्य रज्जुप्रतरस्य क्षेत्रे ७ जलचरसहितलवणोदककालोदक-



७

स्वयंभूरमणसमुद्रेभ्यः शेषसर्वसमुद्रक्षेत्रफलेऽपनीते शेषं शुभत्रयलेश्यास्वस्थानस्वस्थाने स्पर्शो भवति । तद्यथा जम्बूद्वीपादयः स्वयंभूरमणसमुद्रपर्यन्ताः सर्वे द्वीपसमुद्राः द्विगुणद्विगुणविस्ताराः सन्ति । तत्र लक्षयोजनविष्कम्भो जम्बूद्वीपः तस्य सूक्ष्मक्षेत्रफलं—

सत्तणवसुण्णपंचयछण्णवचउरेक्कपंचसुण्णं च ।

इत्येतावत् ७९०५६९४१५० इदमेकखण्डं कृत्वा लवणसमुद्रे तादृशानि चतुर्विंशतिः २४ । धातकीखण्डे शतचतुश्चत्वारिंशत् १४४ । कालोदके समुद्रे षट्शतद्वासप्ततिः ६७२ । पुष्करद्वीपे द्विसहस्राष्टशताशीतिः ।२८८०।

स्पर्श है । उपपादस्थानमें त्रसनालीके चौदह भागोंमें-से कुछ कम डेढ़ भाग प्रमाण स्पर्श है । यह सामान्यसे तेजोलेश्याके तीन स्थानोंमें स्पर्श कहा । विशेषसे दस स्थानोंमें स्पर्श कहते हैं—तिर्यग्लोक एक राजू लम्बा व चौड़ा है । इसमें लवणोदक, कालोदक और स्वयम्भूरमण समुद्रमें ही जलचर जीव पाये जाते हैं शेष समुद्रोंमें नहीं । सो तिर्यग्लोकके क्षेत्रमें-से जिन समुद्रोंमें जलचर जीव नहीं हैं उन समुद्रोंका क्षेत्रफल घटानेपर जितना शेष रहे उतना तीन शुभ लेश्याओंका स्वस्थानस्वस्थानमें स्पर्श जानना । उसीको कहते हैं— जम्बूद्वीपसे लेकर स्वयम्भूरमण समुद्रपर्यन्त सब द्वीपसमुद्र दूने-दूने विस्तारवाले हैं । उनमें-से जम्बूद्वीपका विस्तार एक लाख योजन है । उसका सूक्ष्म क्षेत्रफल इस प्रकार है—सात नौ शून्य पाँच छह नौ चार एक पाँच और शून्य ७९०५६९४१५० । इसे एक खण्ड मानकर लवण समुद्रमें इतने

१. ब. °याः स्वस्थाने ।

रूऊणसळा २ । वारस । १२ । सळाग २ । गुणिदे दु २ । १२ । २ । वळयखंडाणि । २४ । वाहिरसूइ सळागा ५ कदी २५ । तदंतालिळा खंडा ।

वाहिरसूईवलयवासूणा चउगुणिद्रुवासहवा ।
इगिलक्खवग्गभजिवा जंबूसमवलयखंडाणि ॥ —त्रि. सा. ३१८ गा. ।

वाहिरसूई ५ ल । वळयं । वास २ ल । ऊणा ३ ल । चउगुण ३ ल । ४ । इट्ठवास २ ल । हुदा २४ ल ल । इगिलक्खवग्ग १ ल ल भजिदा $\frac{२४ ल ल}{१ ल ल}$ जंबूसमवलयखंडाणि २४ । इल्लि सर्व्वद्वीपखंडंगळं बिट्टु समुद्रखंडंगळने याव्तुकोंडु प्रकृतं पेळल्पडुगुमवें तेंदोडे लवणसमुद्रदोळु जंबूद्वीपोपमानखंडंगळु चतुर्विंशतिप्रमितग २४ । ळवनोंदु लवणसमुद्रखंडमें दु माडि १ । या चतुर्विंशतिखंडंगळिदं कालोदकसमुद्रद जंबूद्वीपसमानद सर्व्वखंडंगळं भागिसिदोडे $\frac{६७२}{२४}$ लवणसमुद्रोपमानलब्धखंडंगळप्पुवुविप्पत्तेंदु २८ । मतमा चतुर्विंशतिखंडंगळिदं पुष्करसमुद्रद जंबूद्वीप-

---

खण्डानि २४ । रूऊणसला २ वारस १२ सलाग २ । गुणिदे दु २ १२ । २ वलयखण्डाणि २४ । वाहिरसुई सलागा ५ कदी २५ तदन्तालिलाखण्डा । वहिरसूई ५ ल वलयव्वासू २ ल, णा ३ ल, चउगुणिद्वुवास ४२ ल, हुदा २४ ल ल, इगिलक्खवग्गभजिदा $\frac{२४ ल ल}{१ ल ल}$ जम्बूसमवलयखण्डाणि २४ । अत्र सर्वद्वीपखण्डानि त्यक्त्वा सर्वसमुद्रखण्डेषु जम्बूद्वीपसमचतुर्विंशतिखण्डैर्भक्तेषु लवणसमुद्रे लवणसमुद्रसमखण्डमेकं १ । कालोदकखण्डेषु भक्तेषु $\frac{६७२}{२४}$ अष्टाविंशतिः २८ । पुष्करसमुद्रखण्डेषु[2] भक्तेषु $\frac{११९०४}{२४}$ चतुःशतपण्णवतिः ४९६,

---

शेष रहे चौबीस लाख लाख योजन। इस तरह बाह्य सूचीके वर्गमें-से अभ्यन्तर सूचीके वर्गको घटाना। फिर उसे जम्बूद्वीपके व्यास लाख योजनके वर्गसे भाग देनेपर चौबीस लब्ध आया। उतने ही खण्ड लवणसमुद्रमें होते हैं। तथा लवणसमुद्रका व्यास दो लाख होनेसे उसकी शलाका दो हैं। उसमें-से एक घटानेपर एक रहा। उसको बारह और शलाका दोसे गुणा करनेपर चौबीस वलयखण्ड होते हैं। तथा लवणसमुद्रकी बाह्य सूची पाँच लाख योजन है अतः शलाकाका प्रमाण पाँच, उसका वर्ग पचीस। सो लवण समुद्र पर्यन्त पचीस खण्ड होते हैं। तथा लवण समुद्रकी बाह्य सूची पाँच लाख योजन, उसमें-से उसका व्यास दो लाख योजन घटानेपर तीन लाख शेष रहे। इनको चौगुणे व्यास आठ लाख योजनसे गुणा करनेपर चौबीस लाख हुए। इसमें एक लाखके वर्गसे भाग देनेपर चौबीस आये। उतने ही जम्बूद्वीपके समान वलयाकार खण्ड लवण समुद्रमें होते हैं।

सो यहाँ सर्वद्वीप सम्बन्धी खण्डोंको छोड़कर सर्वसमुद्र सम्बन्धी खण्ड ही लेना। तथा जम्बूद्वीप समान चौबीस खण्डोंका भाग समुद्रके खण्डोंमें देना। तब लवणसमुद्रमें लवणसमुद्रके समान एक खण्ड होता है। कालोदके छह सौ बहत्तर खण्डोंमें चौबीससे भाग देनेपर कालोद समुद्रमें लवणसमुद्रके समान अठाईस खण्ड होते हैं। पुष्कर समुद्रके ग्यारह

---

१. ब. कालोदके अष्टावि॰। २. ब. ॰समुद्रे चतुः।

[illegible] ।

[illegible] ॥—

चरमेसे गुणयारे अण्णोण्णं गुणिय रूव परिहीणे ।
रूऊणगुणेणहिये गुणेण गुणियम्मि गुणगणियं ॥

२	१६	१६	१६	१६	१	४	४	४	४	[illegible]
२	१६	१६	१६		१	४	४	४		[illegible]
२	१६	१६			१	४	४			[illegible]
२	१६				१	४				[illegible]
२	१				१					[illegible]
धन					ऋण					

[illegible]

इस प्रकार स्वयंभूरमण पर्यंत जानना चाहिए। [illegible] समान [illegible] हैं।

[illegible] —

समुद्र	धनराशि				ऋणराशि				
[illegible]	२	१६	१६	१६	१६	१	४	४	४	४
[illegible]	२	१६	१६	१६		१	४	४	४	
[illegible]	२	१६	१६			१	४	४		
[illegible]	२	१६				१	४			
[illegible]	२	१				१				

यहाँ दो आदि [illegible] ।

[illegible]

=४ । २ । १६ । १६ । २४ । ७९०५६९४१५० । ७६८००० । ७६८०००
४ । ७ । ७ । १५ । १ ल । १ ल । ७६८००० । ७६८००० । ४ । १६ । १६ । १६

अपवर्त्तितं =७९०५६९४१५० / ७ । ७ । १ ल १ ल । ४।५ हारंगळं गुणिसिदोडिदु =७९०५६९४१५० / ९८०००००००००० इदनपवर्त्तिसुव क्रममें तें दोडे भाज्यदि भागहारमं भागिसिद शेषमे भागहारमनकुं मंतु भागिसुत्तिरलु घगरय भक्त-जगत्प्रतरप्रमितमक्कु = / १२ । ३९ । १ । ई संकलनधनदोळिर्प्प ऋणं पदमेत्ते इत्यादिइंदं गच्छार्द्धनिमित्तं गुणोत्तरद मूलं ग्राह्यमप्पुदरिदं गुणोत्तरं नाल्कवर मूलमेरडरिदं रज्जुछेदंगळ विरळिसि वर्गित-संवर्गं माडिदोडे रज्जु पुट्टुगुं । रूवपरिहीणे रूपमेकप्रदेशमदरिदं परिहीन माडिदोडिदु ७ ऋ ऋणगुणेणहिए ७ । ३ मूहेण गुणियंमि गुणगणियं । मुखं पुष्करसमुद्रमप्पुदरिं पदिनारॅरिं गुणिसि-दोडिदु ७ / ७ ३ १६ इदं चतुर्व्विंशतिखंडंगळिदमुं जंबूद्वीपक्षेत्रफलदिदमुं एकयोजनांगुलंगळ

भक्त्वा भाज्यभागहारान् निरीक्ष्य=४ । २ । १६ । १६ । २४ । ७९०५६९४१५० । ७६८००० । ७६८०००
४।७।७।१५ । १ल । १ल । ७६८००० । ७६८०० । ४ । १६ । १६ । १६

अपवर्त्य =७९०५६९४१५० / ७ । ७ । १ ल । १ ल । ४ । ५ हारान् परस्परं गुणयित्वा =७९०५६९४१५० / ९८००००००००००

भक्ते साधिकघगरयभक्तजगत्प्रतरं स्यात् = १ / १२३९ । अत्रत्य ऋणमानीयते 'पदमेते गुणयारे अण्णोण्णं गुणिय' अत्रापि गच्छार्धत्वाद् गुणोत्तरचतुष्कस्य मूलं गृहीत्वा गच्छमात्रद्विकेषु परस्परं गुणितेषु रज्जु— ७ रूवपरिहीणे— ७ ऋण

हारमें पन्द्रह और सोलहको परस्परमें गुणा करनेसे दो सौ चालीस होते हैं। इसे अड़तालीस-से अपवर्तित करनेपर भागहारमें पाँच रहे। इस प्रकार करनेसे स्थिति इस प्रकार रही—

= ४ । २ । १६ । १६ । २४ । ७९०५६९४१५० । ७६८००० । ७६८००० / ४।७।७।१५।१ ल., १ल. । ७६८००० । ७६८००० । ४ । १६ । १६ । १६ अपवर्तन करनेपर ७९०५६९४१५० / ७।७।१ल. । १ ल. ।४।५। सब भागहारोंको परस्परमें गुणा करनेपर और उनको गुणकारके अंकोंसे भाग देनेपर धनराशिमें सर्वक्षेत्र फल 'साधिक धगरय' अर्थात् कुछ अधिक बारह सौ उनतालीससे भाजित जगत्प्रतर प्रमाण होता है। अब ऋण लाना है। सो जलचर सहित समुद्रोंका ऋणरूप क्षेत्रफल लाते हैं—'पदमेत्ते गुणयारे' इत्यादि सूत्रके अनुसार गच्छमात्र गुणकार चारका परस्परमें गुणा करना चाहिए। सो राजूके अर्धच्छेदोंके आधे प्रमाण चारको परस्परमें गुणा करनेसे एक राजू होता है। यहाँ गच्छ सर्वद्वीप समुद्रोंके प्रमाणसे आधा है। अतः गुणकार चारका वर्गमूल दो ग्रहण करना। सम्पूर्ण गच्छमें एक राजूके अर्धच्छेद कहे हैं। अतः एक राजूके अर्धच्छेद मात्र दोको परस्परमें गुणा करनेसे एक राजूका प्रमाण होता है वह जगतश्रेणीका सातवाँ भाग है। उसमें एक घटानेपर जो प्रमाण हो उसको एकहीन गुणकार तीनसे भाग दें। तथा पुष्कर समुद्रकी अपेक्षा आदि स्थानमें प्रमाण सोलह है

पूर्व्वोक्तधनरप भक्तजगत्प्रतरमात्रऋणक्षेत्रं सिद्धमावुदारणक्षेत्रमं रज्जुप्रतरमात्रक्षेत्रवोळ् $\frac{=}{\text{४९}}$ समच्छेदं माडिकळिदोडे शेषमिदु $\frac{=\text{११९०}}{\text{४९।१२३९}}$ इदंनपवर्त्तिसलेंदु भाज्यदि भागहारमं भागिसिदोडे साधिकक्काम ५१ भक्तजगत्प्रतरमात्रं विवक्षितक्षेत्रद तलस्पर्शमक्कुं $\frac{=\text{१}}{\text{५१}}$ इदनूर्ध्वस्पर्शग्रहणार्थं मागि जीवोत्सेधजनितसंख्यातसूच्यंगुलंगळिदं गुणिसिदोडे शुभलेश्यगळ्गे स्वस्थानस्वस्थानस्पर्शमक्कुं $\frac{=\text{२१}}{\text{५१}}$ इदं कदाक्षिसि तेजोलेश्येगे स्वस्थानस्वस्थानापेक्षेयिदं लोकासंख्यातभागं स्पर्शमेंदु पेळल्पट्टुदु। विहारवत् स्वस्थानदोळं वेदनाकषायवैक्रियिकसमुद्घातदोळं तेजोलेश्येगे अष्टचतुर्द्दशभागंगळ् किंचिदूनंगळागि $\frac{\text{८}=}{\text{१४}}$ प्रत्येकं नाल्कुंडेयोळुमक्कुमी किंचिदूनाष्टचतुर्द्दशभागं

ऋणक्षेत्रं सिद्धम्। इदं रज्जुप्रतरे $\frac{=}{\text{४९}}$ समच्छेदेनापनीय $\frac{=\text{११९०}}{\text{४९।१२३९}}$ अपवर्तनार्थं भाज्येन भागहारं भक्त्वा साधिकक्काम ५१ भक्तजगत्प्रतरं विवक्षितक्षेत्रस्य तलस्पर्शो भवति $\frac{=\text{१}}{\text{५१}}$। इदमूर्ध्वस्पर्शग्रहणार्थं जीवोत्सेधजनितसंख्यातसूच्यङ्गुलैर्गुणितं शुभलेश्यानां स्वस्थानस्वस्थानस्पर्शो भवति $\frac{=\text{२१}}{\text{५१}}$। इदं दृष्ट्वा तेजोलेश्यायाः स्वस्थानस्वस्थानापेक्षया लोकासंख्येयभागः स्पर्शः इत्युक्तम्। विहारवत्स्वस्थाने वेदनाकषायवैक्रियिकसमुद्घाते च तेजोलेश्याया अष्टचतुर्दशभागः किंचिदूनः स्यात् $\frac{\text{८}-}{\text{१४}}$। कुतः? सनत्कुमारमाहेन्द्रजानां तेजोलेश्योत्कृष्टानां

सूच्यंगुलसे गुणित जगतश्रेणि मात्र क्षेत्रफल हुआ। इसे पूर्वोक्त धनराशिरूप क्षेत्रफलमें-से घटाना चाहिए। सो किंचित्हीन साधिक बारह सौ उनतालीससे भाजित जगत्प्रतर प्रमाण सर्वजलचर रहित समुद्रोंका ऋणरूप क्षेत्रफल हुआ। इसको एक राजू लम्बा चौड़ा तथा जगत्प्रतरका उनचासवाँ भाग मात्र रज्जु प्रतरक्षेत्रमें-से समच्छेद करके घटाइए। तब जगत्प्रतरमें ग्यारह सौ नब्बेका गुणकार और उनचास गुणा बारह सौ उनतालीसका भागहार हुआ। $\frac{\text{ज. प्र.}\times\text{११९०}}{\text{४९}\times\text{१२३९}}$। अपवर्तन करनेके लिए भाज्यसे भागहारमें भाग देनेपर साधिक इक्यावनसे भाजित जगत्प्रतर प्रमाण विवक्षित क्षेत्रका प्रतररूप तलस्पर्श होता है। इसको ऊँचाईका स्पर्श ग्रहण करनेके लिए जीवोंकी ऊँचाईके प्रमाण संख्यात सूच्यंगुलसे गुणा करनेपर कुछ अधिक इक्यावनसे भाजित संख्यात सूच्यंगुल गुणित जगत्प्रतर मात्र शुभलेश्याओंका स्वस्थान-स्वस्थान सम्बन्धी स्पर्श होता है। इसको देखकर तेजोलेश्याका स्वस्थान-स्वस्थानकी अपेक्षा स्पर्श लोकका असंख्यातवाँ भाग मात्र कहा है।

समस्तप्रकृतिस्थितिअनुभागप्रदेशबंधयोग्यंगळप्प स्थितिबंधाध्यवसायानुभागबंधाध्यवसाययोगस्थानंगळेनितोळवनितुं पुष्पियोळु भावसंसारदोळ्तोळल्व जीवनिवमनुभविसल्पट्टुवु। इल्लि स्थितिबंधाध्यवसायजघन्य मोदल्गोंडुत्कृष्टपर्य्यंतमंते अनुभागबंधाध्यवसायजघन्यस्थानमोदल्गोंडुत्कृष्टस्थानपर्य्यंतं योगस्थानंगळ जघन्यं मोदल्गोंडुत्कृष्टस्थानपर्य्यंतं सर्व्वजघन्यस्थितिसंबंधिगळ्मोदलागि सर्व्वोत्कृष्टस्थितिपर्य्यंतं तत्तत्संबंधिगळं स्थापिसि अक्षसंचारक्रमदिवं भावसंसारदोळनुभविसल्पट्ट स्थितिबंधाध्यवसायादिगळुमं साधिसुवुदें बुदर्थं।

इल्लि एकपुद्गलपरिवर्तनकालमनंतमक्कुमदं नोडलु क्षेत्रपरिवर्तनकालमनंतगुणं अदं नोडलु कालपरिवर्तनवारंगळनंतगुणमदं नोडलु भवपरिवर्त्तनकालमनंतगुणमदं नोडलुं भावपरिवर्त्तनकालमनंतगुणमक्कुमिल्लि संदृष्टिरचनेयिदु:—भाव। ख ख ख ख ख

भव। ख ख ख ख

काल। ख ख ख

क्षेत्र। ख ख

द्रव्य। ख

ओर्व्वं जीवंगे अतीतकालदोळु भावपरिवर्त्तनवारंगळु अनंतंगळु। ख। अदं नोडलु भवपरिवर्त्तनवारंगळनंतगुणंगळवं नोडलु कालपरिवर्त्तनवारंगळु अनंतगुणंगळवं नोडलु क्षेत्रपरिवर्त्तनवारंगळु अनंतगुणंगळवं नोडलु द्रव्यपरिवर्त्तनवारंगळनंतगुणंगळप्पुवु। संदृष्टि:—

सर्वप्रकृतिस्थित्यनुभागप्रदेशबन्धयोग्यानि।

स्थानान्यनुभूतानि भ्रमता भुवि भावसंसारे॥

अत्र स्थितिबन्धाध्यवसायजघन्यादुत्कृष्टपर्यन्तानि पुनः अनुभागबन्धाध्यवसायजघन्यादुत्कृष्टपर्यन्तानि योगस्थानजघन्यादुत्कृष्टपर्यन्तानि च सर्वजघन्यस्थितिसंबन्धीनि आदि कृत्वा सर्वोत्कृष्टस्थितिपर्यन्तं तत्तत्संबन्धीनि संस्थाप्य अक्षसंचारक्रमेण भावसंसारे अनुभूतस्थित्यादिस्थितिबन्धाध्यवसायादीन् साधयेदित्यर्थः। अनेकपुद्गलपरावर्तनकालः अनन्तः। ततः क्षेत्रपरिवर्तनकालः अनन्तगुणः। अतः कालपरिवर्तनकालः अनन्तगुणः, ततो भवपरिवर्तनकालः अनन्तगुणः। ततो भावपरिवर्तनकालः अनन्तगुणः। संदृष्टिः—

भाव	ख ख ख ख ख	
भव	ख ख ख ख	
काल	ख ख ख	एकजीवस्य अतीतकाले भावपरिवर्तनवारा अनन्ताः। तेभ्यः भवपरिवर्तनवारा
क्षेत्र	ख ख	अनन्तगुणाः। तेभ्यः क्षेत्रपरिवर्तनवारा अनन्तगुणाः। तेभ्यः द्रव्यपरिवर्तनवारा
द्रव्य	ख	अनन्तगुणाः। संदृष्टिः—

'भावसंसारमें भ्रमण करते हुए जीवने सब प्रकृतियोंके स्थितिबन्ध, अनुभागबन्ध और प्रदेशबन्धके योग्य स्थानोंका अनुभव किया।'

सबसे जघन्य स्थितिसे लेकर उत्कृष्ट स्थिति पर्यन्त तत्सम्बन्धी स्थिति बन्धाध्यवसायस्थान, अनुभागबन्धाध्यवसायस्थान और योगस्थान जघन्यसे लेकर उत्कृष्ट पर्यन्त स्थापित करके जैसे पहले प्रमादोंमें अक्षसंचार कहा है उसी क्रमसे भावसंसारमें अनुभूत स्थिति आदि सम्बन्धी स्थिति बन्धाध्यवसाय आदिको साधना चाहिए।

यहाँ एक पुद्गलपरावर्तन काल सबसे थोड़ा अर्थात् अनन्त है। उससे क्षेत्रपरिवर्तन काल अनन्त गुणा है। उससे कालपरिवर्तनका काल अनन्त गुणा है। उससे भवपरिवर्तनका काल अनन्त गुणा है। उससे भावपरिवर्तनकाल अनन्त गुणा है। इसीसे एक जीवके अतीत

जीवाजीवं दव्वं रूवारूविति होदि पत्तेयं ।
संसारत्था रूवा कम्मविमुक्का अरूवगया ॥५६३॥

जीवाजीवद्रव्ये रूपारूपिणेति भवतः प्रत्येकं। संसारस्था रूपाः रूपाण्येषां संतोति -रूपाः कर्म्मविमुक्ता अरूपगताः ॥

सामान्यदिवं संग्रहनयापेक्षेयिदं द्रव्यमों दु। अदं भेदिसिदोडे जीवद्रव्यमें दु अजीवद्रव्यमें दु द्विविधमक्कुमल्लि जीवद्रव्यं रूपि जीवद्रव्यमें दुमरूपिजीवद्रव्यमें दुं द्विविधमप्पुवल्लि संसारस्थंगळु रूपिजीवद्रव्यंगळप्पुवु । कर्म्मविमुक्तसिद्धपरमेष्ठिजीवंगळु अरूपगतजीवद्रव्यंगळप्पुवु। अजीवद्रव्यमुं रूप्यजीवद्रव्यमें दुमरूप्यजीवद्रव्यमें दु द्विविधमक्कु।

अज्जीवेसु य रूवी पोग्गलदव्वाणि धम्म इदरो वि ।
आगासं कालो वि य चत्तारि अरूविणो होंति ॥५६४॥

अजीवेषु च रूपीणि पुद्गलद्रव्याणि धर्म्मः इतरोपि च। आकाशं कालोपि च चत्वार्य्यरूपीणि भवंति ॥

अजीवद्रव्यंगळोळु पुद्गलद्रव्यंगळु रूपिद्रव्यंगळप्पुवु। इल्लि

"वर्णगंधरसस्पर्शैः पूरणं गलनं च यत् ।
कुर्व्वंति स्कंधवत्तस्मात्पुद्गलाः परमाणवः ॥" [ ]

एंदितु परमाणुगळगं पुद्गलत्वमुंटागुत्तं विरलु द्विप्रदेशादि स्कंधंगळगेये ग्रहणमक्कुमेक दोडे प्रदेशपूरणगलनरूपदिदं द्रवति द्रोष्यति अदुद्रुवन्निति पुद्गलद्रव्यमें दितु द्व्यणुकादिस्कंधंगळगेये पुद्गलशब्दवाच्यत्वं यथावत्तागि संभविसुगुमप्पुदरिदं परमाणुविंगे "षट्केन युगपद्योगात्परमाणोः

सामान्येन संग्रहनयापेक्षया द्रव्यमेकम् । तदेव भेदविवक्षया जीवद्रव्यं अजीवद्रव्यं च। तत्र जीवद्रव्यं रूप्यरूपि च। तत्र संसारस्थाः रूपिणः, कर्मविमुक्ताः सिद्धा अरूपिणो भवन्ति। अजीवद्रव्यमपि रूप्यरूपि च ॥५६३॥

अजीवेषु पुद्गलद्रव्याणि रूपीणि भवन्ति धर्मद्रव्यं तथा अधर्मद्रव्यं आकाशद्रव्यं कालद्रव्यं चेति चत्वारि अरूपीणि भवन्ति। अत्र "वर्णगन्धरसस्पर्शैः पूरणं गलनं च यत्। कुर्वन्ति स्कन्धवत् तस्मात्पुद्गलाः परमाणवः" इत्येवं परमाणूनां पुद्गलत्वे द्व्यणुकादीनामेव कथं ? प्रदेशपूरणगलनरूपेण द्रवन्ति द्रोष्यन्ति अदुद्रुवन्निति ब्रूमः। ननु—

सामान्यसे संग्रहनयकी अपेक्षा द्रव्य एक है। भेदविवक्षासे दो प्रकारका है—जीव द्रव्य और अजीव द्रव्य। उसमें जीव द्रव्यके दो प्रकार हैं—रूपी और अरूपी। संसारी जीव रूपी है और कर्मोंसे मुक्त सिद्ध अरूपी हैं। अजीव द्रव्य भी रूपी और अरूपी होता है ॥ ५६३ ॥

अजीवोंमें पुद्गल द्रव्य रूपी होते हैं। धर्मद्रव्य, अधर्मद्रव्य, आकाशद्रव्य और कालद्रव्य ये चार अरूपी हैं।

शंका—कहा है कि 'परमाणु स्कन्धकी तरह वर्ण, गन्ध, रस, स्पर्शके द्वारा पूरण गलन करते हैं अतः वे पुद्गल हैं' इस प्रकार परमाणुको पुद्गल कहनेपर द्व्यणुक आदिमें पुद्गलपना कैसे घटित होता है ?

समाधान—द्व्यणुक आदि प्रदेशोंके पूरण गलन रूपके द्वारा अन्य परमाणुओंको प्राप्त

गदिठाणोग्गहकिरिया जीवाणं पोग्गलाणमेव हवे ।
धम्मतिये ण हि किरिया मुक्खा पुण साधगा होंति ॥५६६॥

गतिस्थानावगाहक्रियाः जीवानां पुद्गलानामेव भवेयुः । धर्म्मत्रये न हि क्रियाः मुख्या पुनः साधका भवंति ॥

गतिस्थानावगाहक्रियेगळें बी मूरुं जीवंगळ्गं पुद्गलंगळ्गेयप्पुवु । धर्म्मत्रये धर्म्माधर्म्माकाशंगळें बी मूरुं द्रव्यंगळोळु [redacted] हि क्रिया क्रियेयिल्लेकेंदोडे स्थानचलनमुं प्रदेशचलनमुमिल्लप्पुदरिदं । पुनः मत्तेनेंदोडे धर्म्मादिद्रव्यंगळु गत्यादिगळ्गे मुख्यसाधकंगळप्पुवु अदें तें दोडे :—

जत्तस्स पहं ठत्तस्स आसणं णिवसगस्स वसदी वा ।
गदिठाणोग्गहकरणे धम्मतियं साधगं होति ॥५६७॥

गच्छतः पंथाः तिष्ठतः आसनं नियसकस्य वसतिरिव गतिस्थानावगाहकरणे धर्म्मत्रयं साधकं भवति ॥

नडेवंगे बट्टेयुं कुळ्ळिप्पंवंगासनमुं इप्पंवंगे निवासमुमेंतिंतु गतिस्थानावगाहकरणदोळु *साधकंगळप्पुवंते धर्म्मत्रयमुं गमनादिकरणदोळु साधकमक्कुं । कारणमक्कुमें बुदत्थं ।*

वत्तणहेदू कालो वत्तणगुणमविय दव्वणिचयेसु ।
कालाधारेणेव य वट्टंति सव्वदव्वाणि ॥५६८॥

वर्त्तनाहेतुः कालो वर्त्तनगुणोपि च द्रव्यनिचयेषु । कालाधारेणैव वर्त्तंते सर्व्वद्रव्याणि ॥

[1]णिजंतमप्प वृतु ई धातुविनत्तणिदं कर्म्मदोळं मेण्भावदोळं स्त्रीलिंगदोळं वर्त्तना एंदितु शब्दस्थितियक्कु । वर्त्यते वर्त्तनमात्रं वा वर्त्तना । धर्म्मादिद्रव्यंगळ्गे स्वपर्यायनिवृत्तियं कुरुतु

गतिस्थानावगाहनक्रियास्तिस्रः जीवपुद्गलयोरेव भवन्ति, धर्माधर्माकाशेषु क्रिया नहि स्थानचलनप्रदेशचलनयोरभावात् । किं तर्हि ? धर्मादिद्रव्याणि गत्यादीनां मुख्यसाधिकानि भवन्ति ॥५६६॥ तद्यथा—

गच्छतः पन्थाः, तिष्ठतः आसने, निवसतो निवासो, यथा गतिस्थानावगाहकरणे साधका भवन्ति तथा धर्मादित्रयमपि साधकं कारणमित्यर्थः ॥५६७॥

णिजन्तात् वृतुन्धातोः कर्मणि भावे वा वर्तनाशब्दव्यवस्थितिः वर्त्यते वर्तनमात्रं वेति । धर्मादि-

---

गति, स्थिति और अवगाह ये तीन क्रियाएँ जीव और पुद्गलमें ही होती हैं। धर्म, अधर्म और आकाशमें क्रिया नहीं है क्योंकि न तो ये अपने स्थानको छोड़कर अन्य स्थानमें जाते हैं और न इनके प्रदेशोंमें ही चलन होता है। किन्तु ये धर्मादि द्रव्य, गति आदि *क्रियाओंमें मुख्य साधक होते हैं ॥ ५६६ ॥*

वही कहते हैं—

जैसे जाते हुएको मार्ग, बैठनेवालेको आसन, निवास करनेवालेको निवासस्थान, चलने, ठहरने, अवगाह करनेमें साधक होता है उसी तरह धर्मादि तीन द्रव्य भी सहायक कारण होते हैं ॥ ५६७ ॥

णिजंत वृतु् धातुसे कर्ममें अथवा भावमें वर्तना शब्द निष्पन्न होता है। सो वर्ते या वर्तन मात्र वर्तना है। धर्मादि द्रव्य अपनी-अपनी पर्यायोंकी निर्वृतिके प्रति स्वयं ही

---

१. म वृत्तिगे णिजंतदत्तणिंद ।

जीवपुद्गलंगळोळु परिणामादिपरत्वापरत्वंगळु काणल्पडुगुं । धर्म्माद्यमूर्त्तद्रव्यंगळोळु परिणामादिगळें तें दोडे पेळ्दपं :—

धम्माधम्मादीणं अगुरुगलहुगं तु छहिंहि वड्ढीहिं ।
हाणीहिं वि वड्ढंतो हायंतो वट्टदे जम्हा ॥५६९॥

धर्म्माधर्म्मादीनां अगुरुलघुकस्तु षड्भिरपि वृद्धिभिर्हानिभिरपि वर्द्धमानो हीयमानो वर्त्तते यस्मात् ॥

आवुदों दु कारणदिदं धर्म्माधर्म्मादिद्रव्यंगळ अगुरुलघुगुणाविभागप्रतिच्छेदंगळु स्वद्रव्यत्वक्के निमित्तमप्प शक्तिविशेषंगळु षड्वृद्धिगळिदं षड्हानिगळिदं वर्द्धमानंगळु हीयमानंगळुमागुत्तं परिणमिसुववु । कारणं मुख्यकालमेयक्कुं ।

ण य परिणमदि सयं सो ण य परिणामेइ अण्णमण्णेहिं ।
विविहपरिणामियाणं हवदि हु कालो सयं हेदू ॥५७०॥

न च परिणमति स्वयं सः न च परिणामयति अन्यदन्यैः । विविधपरिणामिकानां भवति हु कालः स्वयं हेतुः ॥

सः कालः आ कालं न च परिणमति संक्रमविधानदिदं स्वकीयगुणंगळिदं अन्यद्रव्यदोळ्परिणमिसदु । यं तोगळु परद्रव्यगुणंगळं तन्नोळु संक्रमदिदं परिणमनमिस्लतें मत्तं हेतु कर्त्तृत्वदिदं अन्यद्रव्यमनन्यगुणंगळोळ्कूडि न च परिणमयति परिणमनमं माडिसदु । मत्तेनें दोडे विविधपरिणामिकानां विविधपरिणामिगळप्प द्रव्यंगळ परिणमनक्के कालं ताने उदासीननिमित्तमक्कुं ।

कालं अस्सिय दव्वं सगसगपज्जायपरिणदं होदि ।
पज्जायावट्ठाणं सुद्धणए होदि खणमेत्तं ॥५७१॥

कालमाश्रित्य द्रव्यं स्वस्वपर्य्यायपरिणतं भवति । पर्य्यायावस्थानं शुद्धनये भवति क्षणमात्रं ॥

यतः धर्माधर्मादीनां अगुरुलघुगुणाविभागप्रतिच्छेदाः स्वद्रव्यत्वस्य निमित्तभूतशक्तिविशेषाः षड्वृद्धिभिर्वर्धमाना षड्हानिभिश्च हीयमानाः परिणमन्ति ततः कारणात्तत्रापि च मुख्यकालस्यैव कारणत्वात् ॥५६९॥

स कालः संक्रमविधानेन स्वगुणैरन्यद्रव्ये न परिणमति । न च परद्रव्यगुणान् स्वस्मिन् परिणामयति । नापि हेतुकर्तृत्वेन अन्यद् द्रव्यम् अन्यगुणैः सह परिणामयति । किं तर्हि ? विविधपरिणामिकानां द्रव्याणां परिणमनस्य स्वयमुदासीननिमित्तं भवति ॥५७०॥

अपरत्व उपकार कालके ही कहे हैं । और ये जीव और पुद्गलमें ही देखे जाते हैं ॥५६८॥

अब धर्मादि अमूर्तद्रव्योंमें वर्तना कैसे होती है यह बतलाते हैं—

यतः धर्म, अधर्म आदिमें अपने द्रव्यत्वमें निमित्त भूत शक्ति विशेष अगुरुलघु नामक गुणके अविभागी प्रतिच्छेद छह प्रकारकी वृद्धिसे वर्धमान और छह प्रकारकी हानिसे हीयमान होकर परिणमन करते हैं । इस कारणसे वहाँ भी मुख्य काल ही कारण है ॥५६९॥

वह काल संक्रमविधानके द्वारा अपने गुणोंसे अन्य द्रव्यके रूपमें परिणमन नहीं करता । और अन्य द्रव्यके गुणोंको अपने रूपमें भी नहीं परिणमाता । हेतुकर्ता होकर अन्य द्रव्यको अन्य द्रव्यके गुणोंके साथ भी नहीं परिणमाता । किन्तु अनेक रूपसे स्वयं परिणमन करनेवाले द्रव्योंके परिणमनमें उदासीन निमित्त होता है ॥ ५७० ॥

आकाशद एकप्रदेशदोळिर्द परमाणु मंदगतियिदं परिणतमादुदु द्वितीयमनंतरक्षेत्रमं याव- पिनितु पोर्त्तिगेय्दुगुमदु समयमें ब कालमक्कुमा नभः प्रदेशमें बुदें तें दोडे :—

जेत्ति वि खेत्तमेत्तं अणुणा रुद्धं खु गयणदव्वं च ।
तं च पदेसं भणियं अवरावरकारणं जस्स ॥ [ ]

आवुदों दु परमाणुविगे अपरापरकारणं पिंदु मुंदुमें बो व्यवस्थितिगे निमित्तमप्प गगनद्रव्य- क्षेत्रमात्रं परमाणुविदं व्यापिसल्पट्टुदु खु स्फुटमागि सः अदु प्रदेशो भणितः प्रदेशमें दु दुदु ।

अनंतरं व्यवहारकालमं पेळ्दपं :—

आवलि असंखसमया संखेज्जावलिसमूहमुस्सासो ।
सत्थुस्सासो थोवो सत्तत्थोवो लवो भणियो ॥५७४॥

आवलिरसंख्यसमया संख्येयावलिसमूह उच्छ्वासः । सप्तोच्छ्वासा स्तोकः सप्तस्तोका लवो

… यें बुदु असंख्यातसमयंगळनुळ्ळुदेकें दोडे युक्तासंख्यातजघन्यराशिप्रमाणमप्पुदरिदं। … समूहमुच्छ्वासमें बुदक्कुमा उच्छ्वासमें तप्परोळें दोडे :—

अड्ढस्स अणलसस्स य णिरुवहदस्स य हवेज्ज जीवस्स ।
उस्सासो णिस्सासो एगो पाणोत्ति आहीदो ॥ [ ]

… एकप्रदेशस्थितपरमाणुः मन्दगतिपरिणतः सन् द्वितीयमनन्तरक्षेत्रं यावद्याति स समयाख्य- … । स च प्रदेशः कियान्—

जेत्तीवि खेत्तमेत्तं अणुणा रुद्धं खु गयणदव्वं च ।
तं च पदेसं भणियं अवरावरकारणं जस्स ॥२॥

…तोः अपरपरकारणं गगनद्रव्यं यावत्क्षेत्रमात्रं परमाणुना व्याप्तं स्फुटं स प्रदेशो भणितः ॥२॥

…—

…ख्यातसमयराशिः आवलिः । संख्याताावलिसमूह उच्छ्वासः । स च कियान् ?

अड्ढस्स अणलसस्स य णिरुवहदस्स य हवेज्ज जीवस्स ।
उस्सासणिस्सासो एगो पाणोत्ति आहीदो ॥१॥

… दो गाथाओंका अर्थ इस प्रकार है—

… प्रदेशमें स्थित परमाणु मन्द गतिसे चलता हुआ अनन्तरवर्ती दूसरे … जाता है वह समय नामक काल है। वह प्रदेश कितना है यह कहते … क्षेत्रको एक परमाणु रोकता है उसे प्रदेश कहते हैं। वह दूर और … ण होता है।

… कालको कहते हैं—

… ात प्रमाण समयोंके समूहका नाम आवली है। संख्यात आवलीके … है। वह सुखी, निरालसी और नीरोगी जीवका उच्छ्वास-

विवसमें दुं पक्षमें दुं मासमें दुं ऋतुमें दुमयनमें दुं वर्षमें दित्यवमाविगळु स्फुटमागि आवल्यादिभेर्दादवं संख्यातासंख्यातानंतपर्य्यंतं यथासंख्यमागि श्रुतावधिकेवलज्ञानविषयतेयिदं विकल्पंगळप्पुववेल्लं व्यवहारकालमक्कुं ।

ववहारो पुण कालो माणुसखेत्तम्मि जाणिदव्वो दु ।
जोइसियाणं चारे ववहारो खलु समाणोत्ति ॥५७७॥

व्यवहारः पुनः कालो मनुष्यक्षेत्रे ज्ञातव्यस्तु । ज्योतिष्काणां चारे व्यवहारः खलु समान इति ॥

व्यवहारकालमें बुदु मत्ते मनुष्यक्षेत्रदोळु ज्ञातव्यमक्कुमेकें दोडे ज्योतिष्कचारवोळु व्यवहारकालं तु मत्ते खलु स्फुटमागि समानमें वितिदु कारणमागि ।

ववहारो पुण तिविहो तीदो वट्टंतगो भविस्सो दु ।
तीदो संखेज्जावलिहदसिद्धाणं पमाणो दु ॥५७८॥

व्यवहारः पुनस्त्रिविधोऽतीतो वर्त्तमानो भविष्यंस्तु । अतीतः संख्याताबलिहतसिद्धानां प्रमाणं तु ॥

व्यवहारकालमें बुदु मत्ते त्रिविधमक्कुं । अतीतकालमें दुं वर्त्तमानकालमें दुं भविष्यत्कालमें दितु । अल्लि अतीतकालप्रमाणं तु मत्ते संख्यातावलियिदं गुणिसल्पट्ट सिद्धरुगळ प्रमाणमेनितनितेयक्कुमेकें दोडे त्रैराशिक सिद्धमप्पुदरिदमा त्रैराशिकमें तें दोडे अरुनूर एंटु जीवंगळु मुक्तिगे सलुत्तिरलु अर्ताविगळमेलें टु समयकालमागुत्तिरलु सर्व्वजीवराशिय अनंतैकभागमात्रमप्प जीवंगळु

विवसः पक्षः मासः ऋतुः अयनं वर्षं इत्यादयः स्फुटं आवल्यादिभेदतः संख्यातासंख्यातानन्तपर्यन्तं क्रमशः श्रुतावधिकेवलज्ञानविषयविकल्पाः सर्वे व्यवहारकालो भवति ॥५७६॥

व्यवहारकालः पुनः मनुष्यक्षेत्रे स्फुटं ज्ञातव्यः । कुतः ? ज्योतिष्काणां चारे स समान इति कारणात् ॥५७७॥

व्यवहारकालः पुनस्त्रिविधः अतीतोऽनागतो वर्तमानश्चेति । तु—पुनः अत्रातीतः संख्यातावलिगुणितसिद्धराशिर्भवति, कुतः ? अष्टोत्तरषट्छतजीवानां मुक्तिगमनकालोऽष्टसमयाधिकषण्मासाः तदा, सर्वजीवराश्य-

एक समय अधिक आवली जघन्य अन्तर्मुहूर्त है। एक समय कम मुहूर्त उत्कृष्ट अन्तर्मुहूर्त है। दोनोंके मध्यमें असंख्यात भेद हैं वे सब अन्तर्मुहूर्त जानना।

दिवस, पक्ष, मास, ऋतु, अयन, वर्ष इत्यादि आवली आदिसे लेकर संख्यात, असंख्यात अनन्तपर्यन्त क्रमसे श्रुतज्ञान, अवधिज्ञान और केवलज्ञानके विषयभूत सब विकल्प व्यवहार काल है ॥५७६॥


व्यवहारकाल मनुष्यलोकमें ही जाना जाता है क्योंकि ज्योतिषी देवोंके चलनेसे ही व्यवहारकाल निष्पन्न होता है अतः ज्योतिषी देवोंके चलनेका काल और व्यवहार काल दोनों समान हैं ॥ ५७७ ॥

व्यवहारकाल तीन प्रकारका है—अतीत, अनागत और वर्तमान। अतीतकाल संख्यात आवलीसे गुणित सिद्धराशि प्रमाण है। क्योंकि छह सौ आठ जीवोंके मुक्ति जानेका काल आठ समय अधिक छह मास है। तब समस्त जीव राशिके अनन्तवें भाग मुक्त जीवोंका

लोगस्स असंखेज्जदिभागप्पहुडिं तु सव्वलोगोत्ति ।
अप्पपदेसविसप्पणसंहारे वावदो जीवो ॥५८४॥

लोकस्यासंख्येयभागप्रभृतिस्तु सर्व्वलोकपर्य्यंतमात्मप्रदेशविसर्प्पणसंहारे व्यापृतो जीवः ॥

सूक्ष्मनिगोदलब्ध्यपर्याप्तजघन्यावगाहं मोदल्गोंडु महामत्स्यावगाहपर्यंतं प्रदेशोत्तरवृद्धिक्रमंगळप्पुवु ६ ६ ६०००६११११३ (प ७ । ७ / ७) वेदनायुतंगे एकप्रदेशोत्तरवृद्धिक्रमदिदं जघन्यदिदं मेले नडेवुत्कृष्टं त्रिगुणितमक्कुं ६ १ १ १ १ १ ३ । मेले मत्ते मारणांतिकसमुद्घातजघन्यं मोदल्गोंडु ६ १ १ १ १ १ ३ पदेशोत्तरक्रमदिदं नडेदुत्कृष्टंस्वयंभूरमणसमुद्रबहिस्स्थितस्थंडिलक्षेत्रदोळिर्द्द महामत्स्यसंबंधि सप्तमपृथ्विय महारौरवनामश्रेणीबद्धदं कुरुत्तु मारणांतिकसमुद्घातदंडमुत्कृष्टमक्कुं १५ । ४१ / १ २ मी क्षेत्रक्के संदृष्टि :—



सूक्ष्मनिगोदलब्ध्यपर्याप्तजघन्यात्मप्रदेशोत्तरेषु महामत्स्यपर्यन्तेषु तदुपरि प्रदेशोत्तरेषु वेदनासमुद्घातस्य त्रिगुणव्यासमहामत्स्यपर्यन्तेषु तदुपरि प्रदेशोत्तरेषु स्वयंभूरमणसमुद्रबाह्यस्थण्डिलक्षेत्रस्थितमहामत्स्येन सप्तमपृथ्वीमहारौरवनामश्रेणीबद्धं प्रति मुक्तमारणान्तिकसमुद्घातस्य पञ्चशतयोजनतदर्धविष्कम्भोत्सेधैकार्धषड्रज्ज्वायतप्रथमद्वितीयतृतीयवक्रोत्कृष्टपर्यन्तेषु तदुपरिलोकपूरणपर्यन्तेषु च अवगाहनविकल्पेषु आत्मप्रदेशविसर्पणसंहारे


सूक्ष्मनिगोदिया लब्ध्यपर्याप्तककी जघन्य अवगाहनासे लेकर एक-एक प्रदेश बढ़ते-बढ़ते महामत्स्यपर्यन्त उत्कृष्ट अवगाहना होती है। उससे ऊपर एक-एक प्रदेश बढ़ते हुए वेदना समुद्घातवालेका क्षेत्र महामत्स्यकी अवगाहनासे तीन गुणा लम्बा, चौड़ा होता है पुनः एक-एक प्रदेश बढ़ते हुए स्वयंभूरमण समुद्रके बाहर स्थण्डिलक्षेत्रमें रहनेवाला महामत्स्य सप्तम पृथ्वीके महारौरव नामक श्रेणीबद्ध बिलेकी ओर मारणान्तिक समुद्घात करता है तब पाँच सौ योजन चौड़ा, अढ़ाई सौ योजन ऊँचा तथा प्रथम मोड़ेमें एक राजू, दूसरेमें आधा राजू और तीसरेमें छह राजू लम्बा उत्कृष्टक्षेत्र होता है। उसके ऊपर केवलिसमुद्घातमें लोकपूरण

लोगस्स असंखेज्जदिभागप्पहुडिं तु सव्वलोगोत्ति ।
अप्पपदेसविसप्पणसंहारे वावदो जीवो ॥५८४॥

लोकस्यासंख्येयभागप्रभृतिस्तु सर्व्वलोकपर्य्यंतमात्मप्रदेशविसर्पणसंहारे व्यापृतो जीवः ॥

सूक्ष्मनिगोदलब्ध्यपर्य्याप्तजघन्यावगाहं मोदल्गोंडु महामत्स्यावगाहपर्य्यंतं प्रदेशोत्तरवृद्धिक्रमंगळप्पुवु ६ ६ ६०००६११११११ वेदनापुलंगे एकप्रदेशोत्तरवृद्धिक्रमदिदं जघन्यदिदं मेले
प ७ । ७
७

तदुत्कृष्टं त्रिगुणितमक्कुं ६ १ १ १ १ १ १ ३ । मेले मत्ते मारणांतिकसमुद्घातजघन्यं मोदल्गोंडु ६ १ १ १ १ १ १ ३ परदेशोत्तरक्रमदिदं भदेदुत्कृष्टंस्वयंभूरमणसमुद्रबहिःस्थितस्थंडिलक्षेत्रदोळिर्द्द महामत्स्यसंबंधि सप्तमपृथ्विय महारौरवनामश्रेणीबद्धदं कुरुत्तु मारणांतिकसमुद्घातदुत्कृष्टमक्कुं १५ । ४१ मी क्षेत्रदके संदृष्टि :—
१ २



सूक्ष्मनिगोदलब्ध्यपर्याप्तजघन्यात्मप्रदेशोत्तरेषु महामत्स्यपर्यन्तेषु तदुपरि प्रदेशोत्तरेषु वेदनासमुद्घातस्य त्रिगुणायातमहामत्स्यपर्यन्तेषु तदुपरि प्रदेशोत्तरेषु स्वयंभूरमणसमुद्रबाह्यस्थण्डिलक्षेत्रस्थितमहामत्स्येन सप्तमपृथ्वीमहारौरवनामश्रेणीबद्धं प्रति मुक्तमारणान्तिकसमुद्घातस्य पञ्चशतयोजनतदर्धविष्कम्भोत्सेधे कार्यपद्‍रज्ज्वायतप्रथमद्वितीयतृतीयवक्रोत्कृष्टपर्यन्तेषु तदुपरि लोकपूरणपर्यन्तेषु च अवगाहनविकल्पेषु आत्मप्रदेशविसर्पणसंहारे

सूक्ष्मनिगोदिया लब्ध्यपर्याप्तककी जघन्य अवगाहनासे लेकर एक-एक प्रदेश बढ़ते-बढ़ते महामत्स्यपर्यन्त उत्कृष्ट अवगाहना होती है। उससे ऊपर एक-एक प्रदेश बढ़ते हुए वेदना समुद्घातवालेका क्षेत्र महामत्स्यकी अवगाहनासे तीन गुणा लम्बा, चौड़ा होता है पुनः एक-एक प्रदेश बढ़ते हुए स्वयंभूरमण समुद्रके बाहर स्थण्डिलक्षेत्रमें रहनेवाला महामत्स्य सप्तम पृथ्वीके महारौरव नामक श्रेणीबद्ध बिलेकी ओर मारणान्तिक समुद्घात करता है तब पाँच सौ योजन चौड़ा, अढ़ाई सौ योजन ऊँचा तथा प्रथम मोड़ेमें एक राजू, दूसरेमें आधा राजू और तीसरेमें छह राजू लम्बा उत्कृष्टक्षेत्र होता है। उसके ऊपर केवलिसमुद्घातमें लोकपूरण

विंशतिभेदंगळप्पुवु । इल्लिगुपयोगिश्लोकमिदु :—

"मूर्त्तिमत्सु पदार्त्थेषु संसारिण्यपि पुद्गलाः ।
अकर्म्मकर्म्म नोकर्म्मजातिभेदेषु वर्ग्गणाः ॥" [ ]

मूर्त्तिमंतंगळप्प पदार्त्थंगळोळं संसारिजीवनोळं पुद्गलशब्दं, अकर्म्मजातिगळोळं कर्म्म-जातिगळोळं नोकर्म्मजातिगळोळं वर्ग्गणे[2] येंब शब्दं वर्त्तिसुगुं । इल्लियणुवर्ग्गणेगळु सुगमंगळु । संख्याताणुसमूह वर्ग्गणेगळु द्व्यणुक त्र्यणुकं मोदलागसदृश धनिकंगळु मेले मेलेकैक परमाणुविवर्धिकंगळु नडदु चरमदोळु संख्यातोत्कृष्टप्रमितपरमाणुस्कंधंगळु सदृशधनिकंगळु तद्योग्यंगळप्पुवु उ १५ । १५ । १५ । असंख्यातवर्ग्गणेगळोळु जघन्यवर्ग्गणेगळु सदृशधनिकंगळु । परि-

ᱹ
८ ३ । ३ । ३ । ३ । ३ । ३
ज २ । २ । २ । २ । २
अणु १ । १ । १ । १ । १ । १

मितासंख्यातजघन्याराशिप्रमितपरमाणुस्कंधंगळप्पुवु । मेलेकैकपरमाणुचयक्रमदिदं पोगि चरमदोळु द्विकवारासंख्यातोत्कृष्टराशिप्रमितपरमाणुगळ स्कंधंगळु सदृशधनिकंगळप्पुवु

मूर्तिमत्सु पदार्थेषु संसारिण्यपि पुद्गलः ।
अकर्मकर्मनोकर्मजातिभेदेषु वर्गणाः ॥१॥

मूर्तिमत्सु पदार्थेषु संसारिजीवे च पुद्गलशब्दो वर्तते । अकर्मजातिषु कर्मजातिषु नोकर्मजातिषु च वर्गणाशब्दो वर्तते । अत्राणुवर्गणा (सुगमा) एकैकपरमाणुरूपा स्यात् १ । १ । १ । १ । १ । अणुवर्गणा । संख्याताणुवर्गणा द्व्यणुकादयः एकैकाण्वधिकाः, उत्कृष्टसंख्याताणुकस्कन्धपर्यन्ताः—

उ १५ । १५ । ०० १५
म ३ ३ ०० ३
ज २ २ ०० २

असंख्याताणुवर्गणा जघन्यपरिमितासंख्याताणुकादयः एकैकाण्वधिका उत्कृष्टद्विकवारासंख्याताणुस्कन्ध-पर्यन्ताः—

हैं—पुद्गल शब्द मूर्तिमान् पदार्थोंका और संसारी जीवोंका वाचक है। और वर्गणाशब्द अकर्मजातिके, कर्म जातिके और नोकर्मजातिके पुद्गलोंको कहता है।

इनमें-से अणुवर्गणा सुगम है। एक-एक परमाणुको अणुवर्गणा कहते हैं। अन्य बाईस वर्गणाओंमें भेद हैं सो उनमें जघन्य और उत्कृष्ट भेद कहते हैं। द्व्यणुकसे लेकर एक-एक परमाणु बढ़ते-बढ़ते उत्कृष्ट संख्यात परमाणुओंके स्कन्ध पर्यन्त संख्याताणुवर्गणा है। उसमें जघन्य दो अणुओंका स्कन्ध है और उत्कृष्ट-उत्कृष्ट संख्यात अणुओंका स्कन्ध है। जघन्य परिमितासंख्यात परमाणुओंसे लेकर एक-एक अणु बढ़ते-बढ़ते उत्कृष्ट असंख्यातासंख्यात परमाणुओंके स्कन्ध पर्यन्त असंख्याताणुवर्गणा है। यहाँ जघन्य परीतासंख्यात परमाणुओंका स्कन्ध है और उत्कृष्ट असंख्यातासंख्यात परमाणुओंका स्कन्ध है। संख्याताणुवर्गणा और असंख्याताणुवर्गणामें विवक्षितवर्गणाको लानेके लिए गुणकार नीचेकी वर्गणासे विवक्षित-

---

१. म पुद्गलंगल् । २. म °णेगळेंबुवप्पुवु ।

विजातिभेदंगळप्पुवु । इल्लियुपयोगिश्लोकमिदु :—

"मूर्त्तिमत्सु पदार्थेषु संसारिष्वपि पुद्गलाः ।
अकर्म्मकर्म्म नोकर्म्मजातिभेदेषु वर्ग्गणाः ॥" [ ]

मूर्त्तिमंतंगळप्प पदार्थंगळोळं संसारिजीवंगळोळं पुद्गलशब्दं, अकर्म्मजातिगळोळं कर्म्मजातिगळोळं नोकर्म्मजातिगळोळं वर्ग्गणे[1] येंब शब्दं वर्तिसुगुं । इल्लियणुवर्ग्गणेगळु सुगमंगळु । संख्याताणुसमूह वर्ग्गणेगळु द्व्यणुक त्र्यणुकं मोदल्गोंडसदृश घनिकंगळु मेले मेलेकेक परमाणुविवर्धितंगळु नडदु चरमदोळु संख्यातोत्कृष्टप्रमितपरमाणुस्कंधंगळु सदृशघनिकंगळु तद्योग्यंगळप्पुवु उ १५ । १५ । १५ । असंख्यातवर्ग्गणेगळोळु जघन्यवर्ग्गणेगळु सदृशघनिकंगळु । परि-

०
० ३ । ३ । ३ । ३ । ३ । ३
ज २ । २ । २ । २ । २
अनु १ । १ । १ । १ । १ । १

मितासंख्यातजघन्यराशिप्रमितपरमाणुस्कंधंगळप्पुवु । मेलेकैकपरमाणुचयक्रमदिदं पोगि चरमदोळु द्विकवारासंख्यातोत्कृष्टराशिप्रमितपरमाणुगळ स्कंधंगळु सदृशघनिकंगळप्पुवु

मूर्तिमत्सु पदार्थेषु संसारिष्वपि पुद्गलः ।
अकर्मकर्मनोकर्मजातिभेदेषु वर्गणाः ॥१॥

मूर्तिमत्सु पदार्थेषु संसारिजीवे च पुद्गलशब्दो वर्तते । अकर्मजातिषु कर्मजातिषु नोकर्मजातिषु च वर्गणाशब्दो वर्तते । अत्राणुवर्गणा (सुगमा) एकैकपरमाणुरूपा स्यात् १ । १ । १ । १ । १ । अणुवर्गणा । संख्याताणुवर्गणा द्व्यणुकादयः एकैकाग्रधिकाः, उत्कृष्टसंख्याताणुस्कन्धपर्यन्ताः—

उ १५ । १५ । ०० १५
० ० ०
० ० ०
म ३ ३ ०० ३
ज २ २ ०० २

असंख्याताणुवर्गणा जघन्यपरिमितासंख्याताणुकादयः एकैकाग्रधिका उत्कृष्टद्विकवारासंख्याताणुस्कन्धपर्यन्ताः—

है—पुद्गल शब्द मूर्तिमान् पदार्थोंका और संसारी जीवोंका वाचक है। और वर्गणाशब्द अकर्मजातिके, कर्म जातिके और नोकर्मजातिके पुद्गलोंको कहता है।

इनमें-से अणुवर्गणा सुगम है। एक-एक परमाणुको अणुवर्गणा कहते हैं। अन्य बाईस वर्गणाओंमें भेद हैं सो उनमें जघन्य और उत्कृष्ट भेद कहते हैं। द्व्यणुकसे लेकर एक-एक परमाणु बढ़ते-बढ़ते उत्कृष्ट संख्यात परमाणुओंके स्कन्ध पर्यन्त संख्याताणुवर्गणा है। उसमें जघन्य दो अणुओंका स्कन्ध है और उत्कृष्ट-उत्कृष्ट संख्यात अणुओंका स्कन्ध है। जघन्य परिमितासंख्यात परमाणुओंसे लेकर एक-एक अणु बढ़ते-बढ़ते उत्कृष्ट असंख्यातासंख्यात परमाणुओंके स्कन्ध पर्यन्त असंख्याताणुवर्गणा है। यहाँ जघन्य परीतासंख्यात परमाणुओंका स्कन्ध है और उत्कृष्ट असंख्यातासंख्यात परमाणुओंका स्कन्ध है। संख्याताणुवर्गणा और असंख्याताणुवर्गणामें विवक्षितवर्गणाको लानेके लिए गुणकार नीचेकी वर्गणासे विवक्षित-

1. म पुद्गलंगलु । 2. म °णेगळेंबुवप्पुवु ।

प्पुवुत्कृष्टं। तज्जघन्यानंतैकभागदिं विशेषाधिकमक्कुं उ २५६ ख ख मेलणऽग्राह्यवर्गणेगळोळु
आ ०
ज २५६ ख

जघन्यमेकपरमाणुविंदमधिकमक्कुं। तदुत्कृष्टं जघन्यमं नोडलनंतगुणितमक्कुं :—

उ २५६ ख १ ख ख तदनंतरोपरितनतेजःशरीरवर्गणेगळोळु जघन्यवर्गणे एकपरमाणु-
अग्रा ० ख
ख
ज २५६ ख १ ख

विंदधिकमक्कुं तदुत्कृष्टं तदनंतैकभागदिंदं विशेषाधिकमक्कुं उ २५६ ख १ ख १ ख ख
तेज ० ख ख
जघ २५६ ख १ ख १ ख
ख

तनमनन्तवर्गणाजघन्यमेकाणुनाधिकं तदुत्कृष्टं ततोऽनन्तगुणं उ २५६ ख तदनन्तरोपरितनाहारवर्गणाजघन्य- ५
०
०
ज २५६

मेकाणुनाधिकं तदुत्कृष्टं तदनन्तैकभागेनाधिकं उ २५६ ख ख तदनन्तरोपरितनाग्राह्यवर्गणाजघन्यमेकाणु-
० ख
आहा ०
ज २५६ ख

नाधिकं तदुत्कृष्टं ततोऽनन्तगुणं— उ २५६ ख १ ख ख तदनन्तरोपरितनतैजसशरीरवर्गणाजघन्यमेकाणुनाधिकं
० ख
अगेज्ज ०
ज २५६ ख १ ख
ख

उत्कृष्ट होता है। उत्कृष्ट आहारवर्गणामें एक परमाणु अधिक होनेपर उससे ऊपरकी अग्राह्य-
वर्गणाका जघन्य होता है। उसमें सिद्धराशिके अनन्तवें भागसे भाग देकर जो लब्ध आवे उसे
उसीमें मिला देनेपर अग्राह्यवर्गणाका उत्कृष्ट होता है। इसमें एक परमाणु अधिक होनेपर उससे १०

मेकपरमाणुविवधिकमक्कुं तदुत्कृष्टमनंतगुणितमक्कुं

उ २५६ ख १ ख १ ख १ ख ख ख ख
अग्रा ः ख ख ख

ज २५६ ख १ ख १ ख १ ख १ ख १ ख
ख ख ख

तदनंतरोपरितनमनोवर्गणेगळोळु जघन्यमेकपरमाणुविवधिकमक्कुं तदुत्कृष्टमनंतैकभागदिं विशेषाधिकमक्कुं

उ २५६ ख ख ख ख १ ख १ ख १ ख १ ख
मनोवर्गणा ः ख ख ख ख

तदनंतरोपरितना-

ज २५६ ख १ ख १ ख १ ख ख ख ख
ख ख ख

ग्राह्यवर्गणेगळोळु जघन्यमेकपरमाणुविवधिकमक्कुं तदुत्कृष्टं तज्जघन्यमं नोडलनंतगुणितमक्कुः—

उ २५६ ख १ ख १ ख १ ख १ ख १ ख ख १ ख ख
अग्राह्य ः ख ख ख ख

ज २५६ ख १ ख ख ख १ ख ख १ ख १ ख
ख ख ख ख

तदनन्तरोपरितनाग्राह्यवर्गणाजघन्यं एकाणुनाधिकं तदुत्कृष्टं ततोऽनन्तगुणं—

उ २५६ ख १ ख १ ख १ ख १ ख १ ख ख
० ख ख ख
अग्रेग्रा ः

ज २५६ ख १ ख १ ख १ ख १ ख १ ख
ख ख ख

तदनन्तरोपरितनमनोवर्गणाजघन्यमेकाणुनाधिकं तदुत्कृष्टं तदनन्तैकभागेनाधिकं—

उ २५६ ख १ ख १ ख १ ख १ ख १ ख १ ख
० ख ख ख ख
मनोव ः

ज २५६ ख १ ख १ ख १ ख १ ख १ ख १ ख
ख ख ख

तदनन्तरोपरितनाग्राह्यवर्गणाजघन्यमेकाणुनाधिकं तदुत्कृष्टं ततोऽनन्तगुणं—

उससे ऊपरकी भाषा वर्गणाका जघन्य है। उसमें सिद्धराशिके अनन्तवें भागसे भाग देनेपर जो लब्ध आवे उसे उसीमें मिलानेपर उसका उत्कृष्ट होता [illegible] में एक परमाणु अधिक होनेपर उससे ऊपरकी अग्राह्यवर्गणाका जघन्य है। उससे [illegible] । उसका उत्कृष्ट होता है। उसमें एक परमाणु अधिक होनेपर उससे ऊपरकी [illegible] है। उसमें सि[illegible]

तदनंतरोपरितनसांतरनिरंतरवर्गणेगळोळु जघन्यमेकपरमाणुविनधिकमक्कुं । तदुत्कृष्ट तज्जघन्यमं नोडलनंतजीवराशिगुणितमक्कुमदक्के संदृष्टि :—

उ २५६ स १ ससससससस १ ससस १६ स १६ स
सांतर नि ० ■ ■ स स स

ज २५६ स १ सस १ससस १ स १ ससस १६ स
■ ■ ■ ■ स

इल्लि विशेषं पेळल्पडुगुं । परमाणुवर्गणे मोदल्गोंडु ई सांतरनिरंतरवर्गणेगळ उत्कृष्टवर्गणे पर्य्यंतं पदिनैदुं वर्गणेगळ सदृशधनिकवर्गणेगळु अनंतपुद्गलवर्गमूलमात्रंगळप्पुवु । पु=पुद्गलानंतगुणं विशेषहीनक्रमंगळप्पुवल्लि प्रतिभागहारं सिद्धानंतैकभागमक्कुमें दितु तदनंतरोपरितनशून्यवर्गणेगळोळु जघन्यमेकरूपाधिकमक्कुमुत्कृष्टमनंतजीवराशि गुणितमक्कुं :—

उ २५६ स १ स १ स १ ससससस १ सस १६ स १६ स १६ स
शून्य ० स ■ स स स

ज २५६ स १ ससस १ सस १ सस १ सस १ १६ स १६ स
सस सस स

यितु पदिनारुं वर्गणेगळेकप्रकारदिदं सिद्धंगळप्पुवु ।

तदनन्तरोपरितनसान्तरनिरन्तरवर्गणाजघन्यमेकाणुनाधिकं तदुत्कृष्टं ततोऽनन्तजीवराशिगुणं—

उ २५६ स १ स १ स १ स १ स १ स १ स १ स १ स १६ स १६ स
स ■ स स स

सान्तर ०
निरन्तर ०

ज २५६ स १ स १ स १ स १ स १ स १ स १ स १ स १ स १६ स
स ■ स स स

अत्रायं विशेषः—परमाणुवर्गणामादिं कृत्वा सान्तरनिरन्तरवर्गणापर्यन्तं पञ्चदशवर्गणानां सदृशधनिकानि अनन्तगुणपुद्गलवर्गमूलमात्राण्यपि विशेषहीनक्रमाणि भवन्ति । तत्र प्रतिभागहारः सिद्धानन्तैकभागः । तदनन्तरोपरितनशून्यवर्गणाजघन्यं एकरूपाधिकं तदुत्कृष्टं ततोऽनन्तजीवराशिगुणं—

जघन्य है। उसे अनन्तजीवराशिसे गुणा करनेपर उसका उत्कृष्ट होता है। उससे एक परमाणु अधिक उससे ऊपरकी सान्तरनिरन्तरवर्गणाका जघन्य है। उसे अनन्तजीवराशिसे गुणा करनेपर उसका उत्कृष्ट होता है। यहाँ इतना विशेष है कि परमाणुवर्गणासे लेकर सान्तरनिरन्तरवर्गणा पर्यन्त पन्द्रह वर्गणाओंका समानधन अनन्तगुणे पुद्गलोंके वर्गमूल प्रमाण होनेपर भी क्रमसे विशेषहीन है। उनका प्रतिभागहार सिद्धराशिका अनन्तवाँ भाग है।

पर्य्याप्ततेजस्कायिकजीवंगळेकबंधनबद्धंगळसंख्यातावलिवर्गप्रमितंगळवरोळु गुणितकर्म्मांशगळप्प जीवंगळु यदि सुष्ठु बहुकंगळप्पुवादोडमावल्यसंख्यातैकभागप्रमितंगळेयप्पुवुळिदवेल्लम गुणितकर्म्मांशंगळेयप्पुवा गुणितकर्म्मांशंगळेकबंधनबद्धंगळु बादरपर्य्याप्ततेजस्कायिकंगळ सविस्रसोपचयत्रिशरीरसंचयं औदारिकतैजसकार्म्मणशरीरसंचयं प्रत्येकदेहोत्कृष्टवर्गणेयक्कुं :—

उ स ३२ ‍ ‍ स स १ २ ‍ १६ स ८ ‍ ई प्रत्येकशरीरोत्कृष्टवर्गणेये रूपाधिकमादोडे
प्रत्येक शरीर

ज स ‍ ‍ स १२– १६ स ३

ध्रुवशून्यवर्ग्गणेगळोळु जघन्यवर्गणेयक्कुं। बादरनिगोदजघन्यवर्गणेयावेडेयोळसंभविसुगुमें दोडे— आवनोव्वं क्षपितकर्म्मांशलक्षणदिदं बंदु पूर्व्वकोटिवर्षायुष्यंमनुष्यनागि पुट्टि गर्ब्भाद्यष्टवर्षमंतर्म्मुहूर्त्ताधिकंगळमेले सम्यक्त्वमुमं संयममुमं युगपत्कैकोंडु कर्म्मंगळुत्कृष्टगुणश्रेणिनिर्ज्जरेयं देशोनपूर्व्वकोटिवर्षंवरं माडियंतर्म्मुहूर्त्तावशेषदोळु सिद्धितम्यनेंदितु क्षपकश्रेणियनेरिदोनुत्कृष्टकर्म्मनिर्ज्जरेयं क्रियमाणं क्षीणकषायनादोनातंगे शरीरदोळु जघन्यदिदमुत्कृष्टदिदमुमेकबंधनबद्धंगळप्प

तेषु गुणितकर्मांशाः सुष्ठु बहुत्वेऽपि आवल्यसंख्यातैकभागमात्राः ८ तेषां सविस्रसोपचयत्रिशरीरसंचयस्तदुत्कृष्टं भवति— उ

स ३२ ‍ ‍ स स १२– १६ स ८ ‍ इदमेव रूपाधिकं ध्रुवशून्यवर्गणाजघन्यं
पतेयशरीर

ज स ‍ ‍ स स १२– १६ स ३

भवति। कश्चित् क्षपितकर्मांशलक्षणो जीवः पूर्वकोटिवर्षायुः मनुष्यो भूत्वा अन्तर्मुहूर्ताधिकगर्भाद्यष्टवर्षोपरि सम्यक्त्वसंयमौ युगपत् स्वीकृत्य कर्मणामुत्कृष्टगुणश्रेणिनिर्जरां देशोनपूर्वकोटिवर्षपर्यन्तं कुर्वन् अन्तर्मुहूर्ते सिद्धितम्यमास्ते तदा क्षपकश्रेण्यारूढः उत्कृष्टकर्मनिर्जरां कुर्वन् क्षीणकषायो जातः, तच्छरीरे जघन्येन उत्कृष्टेन

आवलीके वर्ग प्रमाण बादर पर्याप्त तेजस्कायिक जीवोंके शरीरोंका एक स्कन्ध रूप है। उनमें गुणित कर्मांश जीव बहुत अधिक होनेपर भी आवलीके असंख्यातवें भागमात्र हैं। उनका औदारिक तैजस कार्मणशरीरोंका विस्रसोपचयसहित उत्कृष्ट संचय उत्कृष्ट प्रत्येक शरीरवर्गणा है। उसमें एक परमाणु अधिक होनेपर जघन्य ध्रुवशून्यवर्गणा होती है। इस जघन्यको सब मिथ्यादृष्टि जीवोंके प्रमाणको असंख्यात लोकसे भाग देनेपर जो प्रमाण आवे उससे गुणा करनेपर उत्कृष्ट भेद होता है। उससे एक परमाणु अधिक बादरनिगोद वर्गणा है। बादर निगोदिया जीवोंके विस्रसोपचय सहित कर्म-नोकर्म परमाणुओंके एक स्कन्धको बादरनिगोदवर्गणा कहते हैं। वह कहाँ पायी जाती है यह कहते हैं—क्षपितकर्मांश लक्षणवाला कोई जीव एक पूर्वकोटि वर्षकी आयुवाला मनुष्य हुआ। अन्तर्मुहूर्त अधिक आठ वर्षके ऊपर सम्यक्त्व और संयमको एक साथ धारण करके कुछ कम पूर्व कोटिवर्ष पर्यन्त कर्मोंकी उत्कृष्ट गुणश्रेणि निर्जरा करते हुए जब सिद्ध पद प्राप्त करनेमें अन्तर्मुहूर्तकाल शेष रहा तब

एकबंधनबद्धावल्यसंख्यातैकभागमात्रपुळविगळोळिर्द्दुत्तिर्द्द क्षपितकर्मांशानंतानंतसूक्ष्मनिगोदंगळ सविस्रसोपचयत्रिशरीरसंचयमं कोळ्तुधिरलकु सूक्ष्मनिगोद

व स ७ ७ ख ख १२– १६ ख १२।८ज१।२८–८२ ७ / १ ≡ ७ ५– ७ ७

रिरोत्रेकरूपं कळेयुत्तिरलु तृतीयशून्यवर्गणेगळोळु उत्कृष्टवर्गणेयक्कुं :—

व स ७ ७ ख ख १२ १६ ख १२–८ ≡ ७ ८ २ ७ / १ ≡ ७ ५ ७ ७ इल्लिंयोपकनिते बादरनिगोदोत्कृष्ट-

तृतीयशून्यवर्ग

वर्गणेयोळु पुळविगळु श्रेण्यसंख्येयभागमात्रंगळु जघन्यसूक्ष्मनिगोदवर्गणेयोळु पुळविगळु आवल्य-संख्यातैकभागमात्रंगळवुदरिंदमागि पुळगळवादरनिगोदवर्गणेयिदं केळगे सूक्ष्मनिगोदजघन्यवर्गणेया-गलेवेळकुमें दने दोडिदु दोषमल्तेके दोडे बादरनिगोदवर्गणेगळ निगोदशरीरंगळ्गे नोडलु सूक्ष्म-निगोदवर्गणाशरीरंगळ्गे सूच्यंगुलासंख्यातैकभागमात्रगुणकारोपलंभमप्पुदरिंद । सूक्ष्मनिगोद-

जले स्थले आकाशे वा एकबन्धनबद्धावल्यसंख्यातैकभागपुळविषु स्थितानां क्षपितकर्मांशानन्तानन्तसूक्ष्म-निगोदानां सविस्रसोपचयत्रिशरीरसंचयः सूक्ष्मनिगोदजघन्यवर्गणा भवति ।

व स ७ ७ ख ख १२—१६ ख १२—८ ज ७ २ ८ ७ / १ ≡ ७ ५ ७ ७ इतमेकरूपोना तृतीयशून्यवर्गणोत्कृष्टं भवति—

दिव व ७ स ७ ७ ख ख १२—१६ ख १२—८ ज ७ २ ८ ७ / १ ≡ ७ ५ ७ ७ । ननु बादरनिगोदवर्गणोत्कृष्टे पुळवयः

सूक्ष्मवर्गणा

श्रेण्यसंख्येयभागः सूक्ष्मनिगोदवर्गणाजघन्ये तु आवल्यसंख्यातैकभागः तेन तत्पोत्रेन भाव्यम् इति, तन्न-बादर-निगोदवर्गणानिगोदशरीरेभ्यः सूक्ष्मनिगोदवर्गणाशरीराणां सूच्यङ्गुलासंख्यातैकभागगुणकारोपलम्भात् । सूक्ष्म-

यह उत्कृष्ट बादरनिगोदवर्गणा है। उसमें एक परमाणु अधिक होनेपर तीसरी शून्यवर्गणा-का जघन्य होता है। यह कैसे है सो कहते हैं—जल-थल अथवा आकाशमें एकबन्धनबद्ध आवलीके असंख्यातवें भाग पुळवियोंमें क्षपितकर्मांश अनन्तानन्त सूक्ष्मनिगोद जीव रहते हैं उनके विस्रसोपचय सहित औदारिक तैजस कार्मणशरीरका संचय सूक्ष्मनिगोद जघन्य वर्गणा है। उसमें एक परमाणु हीन करनेपर तीसरी शून्यवर्गणाका उत्कृष्ट होता है।

शंका—बादरनिगोदवर्गणाके उत्कृष्टमें पुळवियाँ श्रेणिके असंख्यातवें भाग कही हैं और सूक्ष्मनिगोदवर्गणाके जघन्यमें आवलीके असंख्यातवें भाग कही हैं। अतः बादरनिगोद वर्गणासे पहले सूक्ष्मनिगोदवर्गणा होनी चाहिए। क्योंकि पुळवियोंका प्रमाण बहुत होनेसे परमाणुओंका प्रमाण बहुत होना सम्भव है?

१. म घोरदं ।

तन्महास्कंधोत्कृष्टवर्गणेयक्कुमेंबुदत्थं ।

संखेज्जासंखेज्जे गुणगारो सो दु होदि हु अणंते ।
चत्तारि अगेज्झेसु वि सिद्धाणमणंतिमो भागो ॥५९८॥

संख्यातासंख्यातयोर्व्वर्गणयोर्गुणकारो तो तु भवतः खलु अनंते । चतुर्ष्वग्राह्येष्वपि सिद्धानामनंतैकभागः ॥

संख्यातवर्गणेयोळं असंख्यातवर्गणेयोळं तंतम्मुत्कृष्टवर्गणानिमित्तमागि गुणकारं यथासंख्यमागि तु मत्ते तो आ संख्यातमुमसंख्यातमुं भवतः अप्पुवु। अवें तें दोडे संख्यातवर्गणाजघन्यराशियनुत्कृष्टसंख्याताउँदिदं गुणिसिदोडे संख्यातोत्कृष्टवर्गणेयक्कु २१५/२ अपवत्तितमिदु १५ । असंख्यातवर्गणाजघन्यराशियं परिमितासंख्यातजघन्यमं तद्राशिविभक्तद्विकवारासंख्यातोत्कृष्टराशियिदं गुणिसुत्तिरलु तदुत्कृष्टवर्गणेयक्कु १६।२५५/१६ मपवत्तितमिदु २५५। अनंतदोळमग्राह्यचतुष्टयदोळं तदुत्कृष्टवर्गणानिमित्तं गुणकारं सिद्धानंतैकभागमात्रमक्कुमा गुणकारदिदं तंतम्म जघन्यवर्गणेयं गुणिसुत्तिरलु तंतम्मुत्कृष्टवर्गणेगळप्पुवें बुदत्थं ।

जीवादोणंतगुणो धुवादितिण्हं असंखभागो दु ।
पल्लस्स तदो तत्तो असंखलोगवहिदो मिच्छो ॥५९९॥

जीवादनंतगुणो ध्रुवादितिसृणां असंख्यातभागस्तु पल्यस्य ततस्ततोऽसंख्यलोकापहृतमिथ्यादृष्टिः ॥

तैकभागः ॥५९७॥

तु—पुनः संख्यातासंख्यातवर्गणयोस्तदर्थं स्वस्वजघन्यस्य गुणकारः स संख्यातवर्गणायां स्वजघन्यभक्तस्वोत्कृष्टमात्रसंख्यातः १५/२ असंख्यातवर्गणायां स्वजघन्यभक्तस्वोत्कृष्टमात्रासंख्यातो भवति २५५/१६ ताभ्यां स्वस्वजघन्यं गुणयित्वा २ । १५/२ । १६ । २५५/१६ मपवर्तिते १५ । २५५ खलु स्फुटं तयोरुत्कृष्टे स्याताम् इत्यर्थः । अनन्तवर्गणायां अग्राह्यवर्गणाचतुष्के च उत्कृष्टार्थं गुणकारः सिद्धानन्तैकभागः ॥५९८॥

जघन्यमें मिलानेपर अपना-अपना उत्कृष्ट होता है। अन्तिम महास्कन्धका उत्कृष्ट लानेके लिए भागहार पल्यका असंख्यातवाँ भाग है ॥५९७॥

संख्याताणुवर्गणा और असंख्याताणुवर्गणामें अपने-अपने उत्कृष्टमें अपने-अपने जघन्यसे भाग देनेपर जो प्रमाण आवे उतना ही गुणकार होता है। उनसे अपने-अपने जघन्यको गुणा करनेपर अपना-अपना उत्कृष्ट होता है। अनन्ताणुवर्गणा और चार अग्राह्यवर्गणामें उत्कृष्ट लानेके लिए गुणकार सिद्धराशिका अनन्तवाँ भाग है ॥५९८॥

वा गुणकारंगळिदं तंतम्म जघन्यवर्ग्गणेयं गुणिसिदोडे तंतम्मुत्कृष्टवर्ग्गणेगळप्पुवेंदुदत्थं-मवरोळु शून्यवर्ग्गणेयोळु सूच्यंगुलासंख्यातगुणकारमें तें दोडे :—सूक्ष्मनिगोदजघन्यवर्ग्गणेयोळु्ळ सूच्यंगुलासंख्यातं तद्वर्ग्गणेयोळेकरूपहीनमागि शून्यवर्ग्गणोत्कृष्टवर्ग्गणेयादुदप्पुदरिना गुणकारं तज्जघन्यदोळिल्लप्पुदरिदं सूक्ष्मनिगोदवर्ग्गणेयोळु पल्यासंख्यातगुणकारमें तें दोडे गुणितकर्म्मांश-जीवप्रतिबद्धसमयप्रबद्धमुत्कृष्टयोगार्जितमप्पुदरिदं पल्यच्छेदासंख्यातेकभागं गुणकारमप्पुदरिद ।

इंतु त्रयोविंशतिवर्ग्गणेगळेकश्रेण्याश्रितंगळु पेळल्पट्टुविन्नु नानाश्रेणियनाश्रयिसि पेळल्प-ट्टपुवदें तें दोडे :—परमाणुवर्ग्गणे मोदल्गोंडु सांतरनिरंतरवर्ग्गणोत्कृष्टवर्ग्गणावसानमाद वर्ग्गणे-गळु सदृशधनिकवर्ग्गणेगळु अनंतपुद्गलवर्ग्गमूलमात्रंगळागुत्तलुं मेले मेले विशेषहीनंगळप्पुवल्लि प्रतिभागहारं सिद्धानंतेकभागमक्कुं । प्रत्येकदेहजघन्यसदृशधनिकंगळु वर्त्तमानकालदोळु क्षपितकर्म्मां-शलक्षणदिदं बंदयोगिचरमसमयदोळु नाल्केयप्पुवु । ४ । युत्कृष्टवर्ग्गणेगळु वर्त्तमानकालदोळु एनितु संभविसुगुमें दोडे स्वयंभूरमणद्वीपदकाडिच्चु मोदलादवरोळु आवल्यसंख्यातैकभाग-मात्रंगळु संभविसुववु । बादरनिगोदजघन्यवर्ग्गणेगळु वर्त्तमानकालदोळेनितु संभविसुगुमें दोडे क्षीणकषायचरमसमयदोळु नाल्केयप्पुवु । तदुत्कृष्टवर्ग्गणेगळु महामत्स्यादिगळोळु आवल्य-

---

यत्र तदुत्कृष्टंभवात् । सूक्ष्मनिगोदवर्गणायां पल्यासंख्यातगुणकारोऽपि तत्समयप्रबद्धानां गुणितकर्मांशजीवप्रति-बद्धत्वात् । एवं त्रयोविंशतिवर्गणा एकश्रेण्याश्रिताः कथिताः । इदानीं नानाश्रेण्योराश्रित्योच्यन्ते—तद्यथा—परमाणुवर्गणातः सांतरनिरन्तरोत्कृष्टावसानवर्गणानां सदृशधनिकानि अनन्तपुद्गलवर्गमूलमात्राण्यपि उपर्युपरि विशेषहीनानि भवन्ति । तत्र प्रतिभागहारः सिद्धानन्तैकभागः । प्रत्येकदेहजघन्यसदृशधनिकानि वर्तमानकाले क्षपितकर्मांशलक्षणेनागत्य अयोगिचरमसमये चत्वारि । उत्कृष्टानि स्वयम्भूरमणद्वीपस्य दावानलादिषु आवल्य-संख्यातैकभागमात्राणि बादरनिगोदजघन्यानि वर्तमानकाले क्षीणकषायचरमसमये चत्वारि तदुत्कृष्टानि

असंख्यातवाँ भाग और जगत्प्रतरका असंख्यातवाँ भाग होता है, यहाँ जो शून्यवर्गणामें सूच्यंगुलके असंख्यातवें भाग गुणकार कहा है उसका कारण यह है कि सूक्ष्मनिगोदवर्गणाके जघन्यमें एक घटानेपर शून्यवर्गणाका उत्कृष्ट होता है। सूक्ष्मनिगोद वर्गणामें गुणकार पल्यके असंख्यातवें भाग कहा है सो उसके समयप्रबद्ध गुणित कर्मांश जीवसे सम्बद्ध होनेसे कहा है। इस प्रकार एक श्रेणि रूपसे तेईस वर्गणाएँ कहीं। अब नाना श्रेणियोंको लेकर कहते हैं—

अर्थात् जो ये वर्गणा कही है वे लोकमें वर्तमान कोई एक कालमें कितनी-कितनी पायी जाती हैं, यह कहते हैं—परमाणुवर्गणासे लेकर सान्तरनिरन्तरवर्गणा पर्यन्त पन्द्रह वर्गणाएँ समानधनवाली हैं। ये पुद्गल द्रव्यराशिके वर्गमूलको अनन्तसे गुणा करनेपर जो प्रमाण हो उतनी-उतनी लोकमें पायी जाती हैं किन्तु आगे-आगे कुछ-कुछ कम होती जाती हैं। इनमें प्रति भागहार सिद्धराशिका अनन्तवाँ भाग है अर्थात् जितनी अणुवर्गणाएँ हैं उनमें सिद्धराशिके अनन्तवें भागसे भाग देनेपर जो प्रमाण आये उतना अणुवर्गणाके परिमाणमें घटानेपर जो प्रमाण शेष है उतनी संख्याताणुवर्गणा जगत्में होती हैं। इसी प्रकार आगे जानना। किन्तु सामान्यसे प्रत्येक पृथक्-पृथक् वर्गणाका प्रमाण अनन्त पुद्गल राशिका वर्गमूल मात्र है। प्रत्येक शरीरवर्गणाका जघन्य वर्तमानकालमें क्षपितकर्मांशरूपसे आकर अयोगकेवलीके अन्त समयमें पाया जाता है सो उत्कृष्टसे चार है। उत्कृष्ट प्रत्येक शरीरवर्गणा

मागि। ई त्रयोविंशतिवर्ग्गणेगळोळु प्रत्येकवर्ग्गणेयुं बादरनिगोदवर्ग्गणेयुं सूक्ष्मनिगोदवर्ग्गणेयुमें बी मूरुं वर्ग्गणेगळु सचित्तवर्ग्गणेगळवरोळु अयोगिचरमसमयदोळु प्रथमप्रत्येकशरीरवर्ग्गणेयोळु जघन्यवर्ग्गणाद्रव्यं स्यादस्ति स्यान्नास्ति यद्यस्ति तदा एकं मेणु द्वयं मेणु त्रयं मेणु उत्कृष्टदिदं चतुष्टयमक्कुं द्वितीयवर्ग्गणेयोळु द्रव्यं स्यादस्ति स्यान्नास्ति यद्यस्ति तदा एकं वा द्वयं वा त्रयं वा उत्कृष्टेन चत्वारि भवंति इंतवस्थितक्रमदिदमनंतवर्ग्गणेगळु सलुत्तंविरलु बळिक्कल्लि मेले यावुदोंदनंतरवर्ग्गणेयो वर्ग्गणेयोळु द्रव्यंगळु स्यादस्ति स्यान्नास्ति यद्यस्ति तदा एकं वा द्वयं वा त्रयं वा उत्कृष्टेन पंच भवंति सदृशधनिकानि। इंतवस्थितक्रमदिदमनंतवर्ग्गणेगळु सलुत्तं विरलु बळिक्कमावुदोंदनंतरवर्ग्गणेयदरोळु वर्ग्गणेगळु कथंचिदुंटु कथंचिदिल्लि येत्तलानुमुंटक्कुमप्पोडागळु एकं मेणु द्वयं मेणु त्रयं मेणु उत्कृष्टदिदं सदृशधनिकंगळु षड्जीवंगळप्पुवो क्रमदिदं सप्ताष्ट-सप्तषट्पंचचतुस्त्रिद्विसदृशधनिकवर्ग्गणेगळु संभविसुववु। ई यभिप्रायव मध्यप्ररूपणे भव्यसिद्ध-प्रायोग्यस्थानंगळोळु गृहीतव्यमक्कु-। मल्लिदं मेले यावुदोंदनंतरवर्ग्गणेयदु संसारिजीवप्रायोग्य-वर्ग्गणेयक्कुमवरोळु वर्ग्गणेगळु कथंचिदुंटु कथंचिदिल्ल एत्तलानुमुंटक्कुमप्पोडागळु एकं मेणु द्वयं

चलु स्फुटम्। तासु प्रत्येकबादरनिगोदसूक्ष्मनिगोदवर्गणाः तिस्रः सचित्ताः। तत्र अयोगिचरमसमये प्रत्येकशरीर-जघन्यं स्यादस्ति स्यान्नास्ति? यद्यस्ति तदा एकं वा द्वयं वा त्रयं वा उत्कृष्टेन चत्वारि। तथा तद्द्वितीय-वर्गणाद्रव्यं स्यादस्ति स्यान्नास्ति। यद्यस्ति तदा एकं वा द्वयं वा त्रयं वा उत्कृष्टेन चत्वारि इत्यवस्थितक्रमेणा-नन्तवर्गणा अतीत्य अनन्तरवर्गणाद्रव्यं स्यादस्ति स्यान्नास्ति। यद्यस्ति तदा एकं वा द्वयं वा त्रयं वा उत्कृष्टेन पञ्च इत्यवस्थितक्रमेण अनन्तवर्गणा अतीत्य अनन्तरवर्गणाद्रव्यं कथञ्चिदस्ति कथञ्चिन्नास्ति। यद्यस्ति तदा एकं वा द्वयं वा त्रयं वा उत्कृष्टेन षट् अनेन क्रमेण सप्ताष्ट सप्तषट् पञ्चचतुस्त्रिद्विसदृशधनिकानि भवन्ति। इदं यवमध्यप्ररूपणा भव्यसिद्धप्रायोग्यस्थानेषु ग्राह्या। अनन्तरवर्गणा या संसारिजीवप्रायोग्या तद् द्रव्यं कथञ्चिदस्ति कथञ्चिन्नास्ति यद्यस्ति तदा एकं वा द्वयं वा त्रयं वा उत्कृष्टेन आवल्यसंख्यातैकभागः इत्यवस्थित-

---

वर्गणाके भेद लिये हुए पुद्गल द्रव्योंका कथन किया है। उनमें प्रत्येक शरीर, बादरनिगोद और ये तीन वर्गणा सचित्त हैं। उनका विशेष कहते हैं—उनमें-से अयोगकेवलीके अन्तिम समयमें पायी जानेवाली जघन्य प्रत्येक शरीरवर्गणा लोकमें होती भी है और नहीं भी होती। यदि होती हैं तो एक या दो या तीन या उत्कृष्टसे चार तक होती हैं। उस जघन्य वर्गणासे एक परमाणु अधिक द्वितीय प्रत्येक शरीरवर्गणा होती भी है और नहीं भी होती। यदि होती है तो एक या दो या तीन या उत्कृष्टसे चार होती हैं। इसी अवस्थित क्रमसे एक-एक परमाणु बढ़ाते-बढ़ाते अनन्त वर्गणाओंके होनेपर उसके अनन्तर एक परमाणु अधिक वर्गणा लोकमें होती भी है और नहीं भी होती। यदि है तब एक या दो या तीन या उत्कृष्टसे पाँच होती हैं। इसी अवस्थित क्रमसे एक-एक परमाणु बढ़ाते-बढ़ाते अनन्त वर्गणाएँ बीतनेपर पुनः एक परमाणु अधिक वर्गणा होती भी है और नहीं भी होती। यदि है तब एक या दो या तीन या उत्कृष्टसे छह होती हैं। इसी क्रमसे अनन्तवर्गणा पर्यन्त उत्कृष्ट सात, आठ, सात, छह, पाँच, चार, तीन-दो वर्गणा लोकमें समान परमाणुओंके परिमाणको लिये हुए होती हैं। यह यवमध्यप्ररूपणा मोक्ष जानेवाले भव्य जीवोंके योग्य स्थानोंमें ग्रहण करनेके योग्य है। अब जो अनन्तरवर्गणा संसारि जीवोंके योग्य हैं उसे कहते हैं। पूर्वमें कही प्रत्येक

बादरबादरबादर बादरसुहुमं च सुहुमथूलं च ।
सुहुमं च सुहुमसुहुमं धरादियं होदि छब्भेयं ॥६०३॥

बादरबादरं बादरसूक्ष्मं च सूक्ष्मस्थूलं च । सूक्ष्मं च सूक्ष्मसूक्ष्मं धरादिकं भवति षड्भेदं ॥

पृथ्विरूपपुद्गलद्रव्यमं बादरबादरमें बुदु । छेदिसल्कं भेदिसल्कं अन्यत्रमोय्वडं शक्यमप्पुदु बादरबादरमें बुदत्थं । जलमं बादरमें बुदु । आवुदोंदु छेदिसल्कं भेदिसल्कं अशक्यमन्यत्रमोय्वडे शक्यमदु बादरमें बुदर्त्थं । छायेयं बादरसूक्ष्ममें बुदु । आवुदोंदु छेदिसल्कं भेदिसल्कवुमन्यत्रमोय्वडमशक्यमप्पुददु बादरसूक्ष्ममें बुदर्त्थं । आवुदोंदु चक्षुरिंद्रियरहितशेषचतुरिंद्रियविषयमप्प बाह्यार्त्थमदं सूक्ष्मस्थूलमें बुदु । कर्म्ममं सूक्ष्ममें बुदु । आवुदोंदु द्रव्यं देशावधिपरमावधिविषयमदु सूक्ष्ममेंबुदर्त्थं । परमाणुवं सूक्ष्मसूक्ष्ममें बुदु । आवुदोंदु पुद्गलद्रव्यमदु सर्व्वावधिविषयमेयावोडे सूक्ष्मसूक्ष्ममें-बुदर्त्थं ।

खंधं सयलसमत्थं तस्स य अद्धं भणंति देसो त्ति ।
अद्धद्धं च पदेसो अविभागी चेव परमाणू ॥६०४॥

स्कंधं सकलसमर्थं तस्य चार्द्धं भणंति देश इति । अर्द्धार्द्धं च प्रदेशः अविभागी चेव परमाणुः ॥

स्कंधमें बुदु सर्व्वांशंगळिंदं संपूर्णमक्कुमदरर्द्धमं देशमें दितु पेळ्वरु । अर्द्धस्यार्द्धमर्द्धार्द्धमदं प्रदेशमें दु पेळ्वरु । अविभागियप्पुदरिदं परमाणुवें दु पेळ्वरु गणधरादिपरमागमज्ञानिगळु । इंतु स्थानस्वरूपाधिकारंतिद्दुंदु ।

पृथ्वीरूपपुद्गलद्रव्यं बादरबादरं छेत्तुं भेत्तुं अन्यत्र नेतुं शक्यं तद्बादरबादरमित्यर्थः । जलं बादरं, यच्छेत्तुं भेत्तुमशक्यं, अन्यत्र नेतुं शक्यं तद्बादरमित्यर्थः । छाया बादरसूक्ष्मं यच्छेत्तुं भेत्तुमन्यत्र नेतुमशक्यं तद्बादरसूक्ष्ममित्यर्थः । यः चक्षुर्वर्जितचतुरिन्द्रियविषयो बाह्यार्थः तत्सूक्ष्मस्थूलम् । कर्म सूक्ष्मं, यद्द्रव्यं देशावधिपरमावधिविषयं तत्सूक्ष्ममित्यर्थः । परमाणुसूक्ष्मसूक्ष्मं तत्सर्वावधिविषयं तत्सूक्ष्मसूक्ष्ममित्यर्थः ॥६०३॥

स्कन्धं सर्वांशसंपूर्णं भणन्ति तदर्धं च देशं, अर्धस्यार्धं प्रदेशं अविभागिभूतं परमाणुम् ॥६०४॥ इति स्थानस्वरूपाधिकारः ।

पृथ्वीरूप पुद्गल द्रव्य बादर-बादर है। जिसका छेदन-भेदन किया जा सके, जिसे एक स्थानसे दूसरे स्थानपर ले जाया जा सके वह बादर-बादर है। जिसका छेदन-भेदन तो न हो सके किन्तु अन्यत्र ले जाया जा सके वह बादर है। छाया बादरसूक्ष्म है। जो छेदन-भेदन और अन्यत्र ले जानेमें अशक्य हो वह बादर सूक्ष्म है। जो चक्षुको छोड़ शेष चार इन्द्रियोंका विषय बाह्य पदार्थ है वह सूक्ष्म स्थूल है। कर्मस्कन्ध सूक्ष्म है। जो द्रव्य देशावधि और परमावधिज्ञानका विषय होता है वह सूक्ष्म है। परमाणु सूक्ष्मसूक्ष्म है। जो सर्वावधिज्ञानका विषय है वह सूक्ष्मसूक्ष्म है ॥६०३॥

जो सब अंशोंसे पूर्ण हो उसे स्कन्ध कहते हैं। उसके आधेको देश कहते हैं। और आधेके आधेको प्रदेश कहते हैं। जिसका विभाग न हो सके वह परमाणु है ॥६०४॥

स्थानाधिकार समाप्त हुआ।

१. म चक्षुरिंद्रियविषयवर्ज्जं नाल्किंद्रियविषयमप्प ।

बादरबादरबादर बादरसुहुमं च सुहुमथूलं च ।
सुहुमं च सुहुमसुहुमं धरादियं होदि छब्भेयं ॥६०३॥

बादरबादरं बादरसूक्ष्मं च सूक्ष्मस्थूलं च । सूक्ष्मं च सूक्ष्मसूक्ष्मं धरादिकं भवति षड्भेदं ॥

पृथ्विरूपपुद्गलद्रव्यमं बादरबादरमें बुदु । छेदिसल्कं भेदिसल्कं अन्यत्रमोय्वडं शक्यमप्पुदु बादरबादरमें बुदत्थं । जलमं बादरमें बुदु । आवुदोंदु छेदिसल्कं भेदिसल्कं अशक्यमन्यत्रमोय्वडे शक्यमदु बादरमें बुदत्थं । छायेयं बादरसूक्ष्ममें बुदु । आवुदोंदु छेदिसल्कं भेदिसल्कदुमन्यत्रमोय्वडं-शक्यमप्पुददु बादरसूक्ष्ममें बुदत्थं । आवुदोंदु चक्षुरिंद्रियरहितशेषचतुरिंद्रियविषयमप्प बाह्यार्त्थमदं सूक्ष्मस्थूलमें बुदु । कर्म्ममं सूक्ष्ममें बुदु । आवुदोंदु द्रव्यं देशावधिपरमावधिविषयमदु सूक्ष्ममेंबुदत्थं । परमाणुवं सूक्ष्मसूक्ष्ममें बुदु । आवुदोंदु पुद्गलद्रव्यमदु सर्व्वावधिविषयमेयावोडे सूक्ष्मसूक्ष्ममें-बुदत्थं ।

खंधं सयलसमत्थं तस्स य अद्धं भणंति देसो त्ति ।
अद्धद्धं च पदेसो अविभागी चेव परमाणू ॥६०४॥

स्कंधं सकलसमर्थं तस्य चार्द्धं भणंति देश इति । अर्द्धार्द्धं च प्रदेशः अविभागी चैव परमाणुः ॥

स्कंधमें बुदु सर्व्वांशंगळिदं संपूर्णमक्कुमदरर्द्धमं देशमें दिंतु पेळ्वरु । अर्द्धस्यार्द्धमर्द्धार्द्धमदं प्रदेशमें दु पेळ्वरु । अविभागियप्पुदरिदं परमाणुवें दु पेळ्वरु गणधरादिपरमागमज्ञानिगळु । इंतु स्थानस्वरूपाधिकारंसिद्धुंदु ।

पृथ्वीरूपपुद्गलद्रव्यं बादरबादरं छेत्तुं भेत्तुं अन्यत्र नेतुं शक्यं तद्बादरबादरमित्यर्थः । जलं बादरं, यच्छेत्तुं भेत्तुमशक्यं, अन्यत्र नेतुं शक्यं तद्बादरमित्यर्थः । छाया बादरसूक्ष्मं यच्छेत्तुं भेत्तुमन्यत्र नेतुमशक्यं तद्बादरसूक्ष्ममित्यर्थः । यः चक्षुर्वर्जितचतुरिन्द्रियविषयो बाह्यार्थः तत्सूक्ष्मस्थूलम् । कर्म सूक्ष्मं, यद्द्रव्यं देशावधिपरमावधिविषयं तत्सूक्ष्ममित्यर्थः । परमाणुसूक्ष्मसूक्ष्मं तत्सर्वावधिविषयं तत्सूक्ष्मसूक्ष्ममित्यर्थः ॥६०३॥

स्कन्धं सर्वांशसंपूर्णं भणन्ति तदर्धं च देशं, अर्धस्यार्धं प्रदेशं अविभागिभूतं परमाणुम् ॥६०४॥ इति स्थानस्वरूपाधिकारः ।

पृथ्वीरूप पुद्गल द्रव्य बादर-बादर है। जिसका छेदन-भेदन किया जा सके, जिसे एक स्थानसे दूसरे स्थानपर ले जाया जा सके वह बादर-बादर है। जिसका छेदन-भेदन तो न हो सके किन्तु अन्यत्र ले जाया जा सके वह बादर है। छाया बादरसूक्ष्म है। जो छेदन-भेदन और अन्यत्र ले जानेमें अशक्य हो वह बादर सूक्ष्म है। जो चक्षुको छोड़ शेष चार इन्द्रियोंका विषय बाह्य पदार्थ है वह सूक्ष्म स्थूल है। कर्मस्कन्ध सूक्ष्म है। जो द्रव्य देशावधि और परमावधिज्ञानका विषय होता है वह सूक्ष्म है। परमाणु सूक्ष्मसूक्ष्म है। जो सर्वावधिज्ञानका विषय है वह सूक्ष्मसूक्ष्म है ॥६०३॥

जो सब अंशोंसे पूर्ण हो उसे स्कन्ध कहते हैं। उसके आधेको देश कहते हैं। और आधेके आधेको प्रदेश कहते हैं। जिसका विभाग न हो सके वह परमाणु है ॥६०४॥

स्थानाधिकार समाप्त हुआ।

---

१. म चक्षुरिंद्रियविषयवर्ज्जं नाल्किंद्रियविषयमप्प ।

पातमागुत्तं विरलु विपच्यमानत्वदिदं पौद्गलिकमेंदे निश्चैसल्पडुवुवु । वाग् द्विप्रकारमक्कुं द्रव्यवाक् भाववाक्केंदितल्लि भाववाक्केंबुदु वीर्य्यांतरायमतिश्रुतज्ञानावरणक्षयोपशमांगोपांगनामलाभनिमित्तत्वदिदं पौद्गलिकमेयक्कुमेकेंदोडे तदभावमागुत्तिरलु तद्वृत्यभावमप्पुदरिदं । तत्सामर्थ्योपेतत्वदिदं क्रियावंतनप्पात्मनिदं प्रेर्य्यमाणंगळप्प पुद्गलंगळु वाक्त्वदिदं परिणमिसुववेंदितु द्रव्यवाक्कुं पौद्गलिकमेयक्कुं मेकेंदोडे श्रोत्रेंद्रियविषयत्वदिदं इतरेंद्रियविषयमेनु कारणमागदेंदोडे तद्ग्रहणायोग्यत्वदिदं घ्राणग्राह्यगंधद्रव्यदोळु रसाद्यनुपलब्धियंते, अमूर्त्त वाक्कें देसलानुमें देपप्पोडे युक्तमल्तेकेंदोडे मूर्त्तिमद्ग्रहणावरोधव्याघाताभिभवादिदर्शनदिदं मूर्त्तिमत्त्व सिद्धियप्पुदरिदं।

मनमुं द्विप्रकारमक्कुं द्रव्यभावभेददिदवल्लि भावमनस्सेंबुदु लब्ध्युपयोगलक्षणं पुद्गलावलंबनदिदं पौद्गलिकमक्कुं । द्रव्यमनमुं ज्ञानावरणवीर्य्यांतरायक्षयोपशमांगोपांगनामलाभप्रत्ययमप्प गुणदोषविचारस्मरणादिप्रणिधानाभिमुखमप्पात्मंगनुग्राहकपुद्गलंगळु मनस्त्वदिदं परिणतंगळेंदितु पौद्गलिकमक्कुं । वोव्वंनें दपं :—मनं द्रव्यांतरं रूपादिपरिणमनविरहितमणुमात्र-

---

पमाङ्गोपाङ्गनामकर्मलाभनिमित्तत्वात् पौद्गलिका तदभावे तद्वृत्त्यभावात् । तत्सामर्थ्योपेतत्वेन क्रियावताऽऽत्मना प्रेर्यमाणपुद्गलाः वाक्त्वेन परिणमन्तीति द्रव्यवागपि पौद्गलिकैव श्रोत्रेन्द्रियविषयत्वात् । इतरेन्द्रियविषयापि कुतो न स्यात् तद्ग्रहणायोग्यत्वात् घ्राणग्राह्ये गन्धद्रव्ये रसाद्यनुपलब्धिवत् । अमूर्ता वाग् इत्यप्ययुक्तं मूर्तग्रहणावरोधव्याघाताभिभवादिदर्शनात् मूर्तत्वसिद्धेः । मनोऽपि तथा द्वेधा । तत्र भावमनः लब्ध्युपयोगलक्षणं पुद्गलावलम्बनात् पौद्गलिकम् । द्रव्यमनोऽपि ज्ञानावरणवीर्यान्तरायक्षयोपशमाङ्गोपाङ्गनामकर्मलाभप्रत्ययगुणदोषविचारस्मरणादिप्रणिधानाभिमुखस्यात्मनोऽनुग्राहकपुद्गलानां तथात्वेन परिणमनात् पौद्गलिकम् । कश्चिदाह—मनः द्रव्यान्तरं रूपादिपरिणमनविरहितमणुमात्रं, पौद्गलिकं न । आचार्य आह—तेन आत्मनः

यरण और श्रुतज्ञानावरणके क्षयोपशम तथा अंगोपांग नामक कर्मके उदयके निमित्तसे होनेसे पौद्गलिक है। उसके अभावमें भाववचन—बोलनेकी शक्ति नहीं होती। भाववचनकी शक्तिसे युक्त क्रियावान् आत्माके द्वारा प्रेरित पुद्गल वचन रूप परिणत होते हैं इसलिए द्रव्यवाक् भी पौद्गलिक ही है क्योंकि श्रोत्र इन्द्रियका विषय है।

शंका—जब वचन पौद्गलिक है तो अन्य इन्द्रियोंका भी विषय क्यों नहीं है ?

समाधान—वह अन्य इन्द्रियोंसे ग्रहण करनेके अयोग्य है। जैसे घ्राण इन्द्रियसे ग्राह्य सुगन्धित द्रव्यमें रसना आदि इन्द्रियोंकी प्रवृत्ति नहीं होती।

वचन अमूर्तिक है ऐसा कहना भी अयुक्त है क्योंकि मूर्त इन्द्रियके द्वारा शब्दका ग्रहण होता है, मूर्त दीवार आदिसे रोका जाता है, मूर्त पदार्थसे टकराता है तथा बहुत तीव्र शब्दसे मन्द शब्द दब जाता है इससे वचन मूर्तिक सिद्ध होता है। मन भी दो प्रकारका है—भावमन और द्रव्यमन। भावमन लब्धि और उपयोग लक्षणवाला है। वह पुद्गलके अवलम्बनसे होता है। इसलिए पौद्गलिक है। द्रव्यमन भी पौद्गलिक है क्योंकि ज्ञानावरण और वीर्यान्तरायके क्षयोपशम तथा अंगोपांग नामकर्मके उदयसे जब आत्मा गुण-दोषके विचार, स्मरण आदिके अभिमुख होता है तो उसके उपकारी पुद्गल मन रूपसे परिणमन करते हैं इसलिए पौद्गलिक है। किसीका कहना है—मन एक पृथक् द्रव्य है उसमें रूपादि

पातमागुत्तं विरलु विपच्यमानत्वदिदं पौद्गलिकमें वे निःचैसल्पडुवुदु । वाग् द्विप्रकारमक्कुं द्रव्यवाक् भाववाक्केंदितल्लि भाववाक्कें बुदु वीर्य्यांतरायमतिश्रुतज्ञानावरणक्षयोपशमांगोपांगनामलाभनिमित्तत्वदिदं पौद्गलिकमेयक्कुमेकें दोडे तदभावमागुत्तिरलु तद्वृत्त्यभावमप्पुदरिदं । तत्सामर्थ्योपेतत्वदिदं क्रियावंतनप्पात्मनिदं प्रेर्य्यमाणंगळप्प पुद्गलंगळु वाक्त्वदिदं परिणमिसुवर्वेदितु द्रव्यवाक्कुं पौद्गलिकमेयक्कुं मेकें दोडे श्रोत्रेंद्रियविषयत्वदिदं इतरेंद्रियविषयमेनु कारणमागदें दोडे तद्ग्रहणायोग्यत्वदिदं घ्राणग्राह्यगंधद्रव्यदोळु रसाद्यनुपलब्धियंते, अमूर्त्तं वाक्कें बेतलानुमें वेयप्पोडे युक्तमल्तेकें दोडे मूर्त्तिमद्ग्रहणावरोधव्याघाताभिभवादिदर्शनदिदं मूर्त्तिमत्त्व सिद्धियप्पुदरिदं ।

मनमुं द्विप्रकारमक्कुं द्रव्यभावभेददिदल्लि भावमनस्सें बुदु लब्ध्युपयोगलक्षणं पुद्गलावलंबनदिदं पौद्गलिकमक्कुं । द्रव्यमनमुं ज्ञानावरणवीर्य्यांतरायक्षयोपशमांगोपांगनामलाभप्रत्ययंगळप्प गुणदोषविचारस्मरणादिप्रणिधानाभिमुखमप्पात्मंगनुग्राहकपुद्गलंगळु मनस्त्वदिदं परिणतंगळें दितु पौद्गलिकमक्कुं । वोय्वंने वपं :—मनं द्रव्यांतरं रूपादिपरिणमनविरहितमणुमात्र-

---

यमाङ्गोपाङ्गनामकर्मलाभनिमित्तत्वात् पौद्गलिकी तदभावे तद्वृत्त्यभावात् । तत्सामर्थ्योपेतत्वेन क्रियावतात्मना प्रेर्यमाणपुद्गलाः वाक्त्वेन परिणमन्तीति द्रव्यवागपि पौद्गलिकैव श्रोत्रेन्द्रियविषयत्वात् । इतरेन्द्रियविषयापि कुतो न स्यात् तद्ग्रहणायोग्यत्वात् घ्राणग्राह्ये गन्धद्रव्ये रसाद्यनुपलब्धिवत् । अमूर्ता वाग् इत्यप्ययुक्तं मूर्तग्रहणावरोधव्याघाताभिभवादिदर्शनात् मूर्तत्वसिद्धेः । मनोऽपि तथा द्वेधा । तत्र भावमनः लब्ध्युपयोगलक्षणं पुद्गलालम्बनात् पौद्गलिकम् । द्रव्यमनोऽपि ज्ञानावरणवीर्यान्तरायक्षयोपशमाङ्गोपाङ्गनामकर्मलाभप्रत्ययगुणदोषविचारस्मरणादिप्रणिधानाभिमुखस्यात्मनोऽनुग्राहकपुद्गलानां तथात्वेन परिणमनात् पौद्गलिकम् । कश्चिदाह—मनः द्रव्यान्तरं रूपादिपरिणमनविरहितमणुमात्रं, पौद्गलिकं न । आचार्य आह—तेन आत्मनः

वरण और श्रुतज्ञानावरणके क्षयोपशम तथा अंगोपांग नामक कर्मके उदयके निमित्तसे होनेसे पौद्गलिक हैं। उसके अभावमें भाववचन—बोलनेकी शक्ति नहीं होती। भाववचनकी शक्तिसे युक्त क्रियावान् आत्माके द्वारा प्रेरित पुद्गल वचन रूप परिणत होते हैं इसलिए द्रव्यवाक् भी पौद्गलिक ही है क्योंकि श्रोत्र इन्द्रियका विषय है।

शंका—जब वचन पौद्गलिक है तो अन्य इन्द्रियोंका भी विषय क्यों नहीं है?

समाधान—वह अन्य इन्द्रियोंसे ग्रहण करनेके अयोग्य है। जैसे घ्राण इन्द्रियसे ग्राह्य सुगन्धित द्रव्यमें रसना आदि इन्द्रियोंकी प्रवृत्ति नहीं होती।

वचन अमूर्तिक है ऐसा कहना भी अयुक्त है क्योंकि मूर्त इन्द्रियके द्वारा शब्दका ग्रहण होता है, मूर्त दीवार आदिसे रोका जाता है, मूर्त पदार्थसे टकराता है तथा बहुत तीव्र शब्दसे मन्द शब्द दब जाता है इससे वचन मूर्तिक सिद्ध होता है। मन भी दो प्रकारका है—भावमन और द्रव्यमन। भावमन लब्धि और उपयोग लक्षणवाला है। वह पुद्गलके अवलम्बनसे होता है। इसलिए पौद्गलिक है। द्रव्यमन भी पौद्गलिक है क्योंकि ज्ञानावरण और वीर्यान्तरायके क्षयोपशम तथा अंगोपांग नामकर्मके उदयसे जब आत्मा गुण-दोषके विचार, स्मरण आदिके अभिमुख होता है तो उसके उपकारी पुद्गल मन रूपसे परिणमन करते हैं इसलिए पौद्गलिक है। किसीका कहना है—मन एक पृथक् द्रव्य है उसमें रूपादि


प्राणापानंगळ्गे प्रतिघातं पडेयल्पट्टुदु, श्लेष्मदिदं मेणु अभिभवं काणल्पट्टुदु। अमूर्त्तक्के मूर्त्तिमत्तुगळिंदभिघातादिगळागवु। अदु कारणदिदमे आत्मास्तित्वसिद्धियक्कुमें तोगळेल्लियानुं प्रतिमाचेष्टितं प्रयोक्तृलिंगास्तित्वमनरिपुगुमंते प्राणापानादिव्यापारमुं क्रियावंतनप्पात्मनं साधिसुगुमिल्लदेयुं .मत्ते केलवुं जीवितमरणसुखदुःखनिर्व्वर्त्तनकारणभूतंगळु पुद्गलंगळप्पुवु। सदसद्वेद्योदयमंतरंगहेतुवुंटागुत्तिरलु बाह्यद्रव्यादिपरिपाकनिमित्तवशदिदमुत्पद्यमानप्रीतिपरितापरूपपरिणामं सुखदुःखमेंदु पेळल्पट्टुवु। भवधारणकारणायुराख्यकर्म्मोदयदिदं भवस्थितियं धरिसिद जीवक्के पूर्व्वोक्तप्राणपानक्रियाविशेषाव्युच्छेदं जीवितमेंदु पेळल्पट्टुदु, तदुच्छेदं मरणमेंदु पेळल्पट्टुदु। ई सुखादिगळु जीवक्के पुद्गलंगळिंदमे संभविसुववु। मूर्त्तिमद्धेतु सन्निधानमागुत्तिरलु तदुत्पत्तियुंटप्पुदरिंदं। केवलं जीवंगळ शरीरादिनिर्व्वर्त्तनकारणभूतंगळु पुद्गलंगळेंबुदिल्ल। पुद्गलक्कं पुद्गलंगळु निर्व्वर्त्तनहेतुगळप्पुवु। कांस्यादिगळ्गे भस्मादिगळिंदं जलादिगळ्गे कतकादिगळिंदं अयःप्रभृतिगळ्गे जलादिगळिंदं उपकारं माडल्पट्टुदु काणल्पडुगुमप्पुदरिंदं। इंतु औदारिकवैक्रियिक आहारकशरीरनामकर्म्मोदयदिदमा मूरुं शरीरंगळु मुच्छ्वासनिश्वासमुमाहारवर्ग्गणेयिनप्पुवु। तैजसशरीरनामकर्म्मोदयदिदं तेजोवर्ग्गणेयिदं तैजसशरीरमक्कुं। कार्म्मणशरीरनाम-

---

प्राणापानयोश्च दुर्गंधपूतिगन्धिप्रतिभयेन हस्ततलपुटादिभिरास्यसंवरणेन श्लेष्मणा वा प्रतिघातदर्शनात्, अमूर्तस्य मूर्तिमद्भिस्तदसंभवाच्च। तत एव प्राणापानादिव्यापारादात्मनोऽस्तित्वसिद्धिः प्रयोक्तुरभावे प्रतिमाचेष्टितस्येव आत्माभावे तदघटनात्। तथा सदसद्वेद्योदयान्तरङ्गहेतौ सति बाह्यद्रव्यादिपरिपाकनिमित्तवशेन उत्पद्यमानप्रीतिपरितापरूपपरिणामौ सुखदुःखे। आयुरुदयेन भवस्थितिं बिभ्रतः प्राणापानक्रियाविशेषाव्युच्छेदो जीवितं, तदुच्छेदो मरणम्। तान्यपि पौद्गलिकानि मूर्तिमद्धेतुसन्निधाने सति तदुत्पत्तिसंभवात्। न केवलं जीवशरीरादीनामेव निर्वर्तनकारणभूताः पुद्गलाः पुद्गलादीनामपि कांस्यादीनां भस्मादीभिः जलादीनां कतकादिभिः अयःप्रभृतीनां जलादिभिश्च उपकारदर्शनात्। एवमौदारिकवैक्रियिकाहारकनामकर्मोदयात् आहारवर्गणायातानि त्रीणि शरीराणि उच्छ्वासनिश्वासौ च। तैजसनामकर्मोदयात् तेजोवर्गणया तैजसशरीरम्।

दुर्गन्ध आदिके भयसे हथेली आदिसे मुखको बन्द कर लेनेसे तथा जुकामसे प्राण अपानका प्रतिघात देखा जाता है। अमूर्तका मूर्तिमानके द्वारा प्रतिघात सम्भव नहीं है। उसी प्राण अपान आदि की क्रियासे आत्माके अस्तित्वकी सिद्धि होती है। जैसे प्रयोक्ताके अभावमें यन्त्रादि मशीनमें क्रिया सम्भव नहीं है। तथा साता-असाता वेदनीयके उदयरूप अन्तरंग कारणके होनेपर बाह्य द्रव्यादिके परिपाकके निमित्तसे जो प्रीतिरूप या सन्तापरूप परिणाम उत्पन्न होता है उसे सुख और दुःख कहते हैं। आयुकर्मके उदयसे भवमें स्थिति करते हुए श्वास-उच्छ्वास आदि क्रिया विशेषका होते रहना जीवन है और उसका छेद होना मरण है। ये भी पौद्गलिक हैं क्योंकि मूर्तिमान् कारणोंके होनेपर सुखादिकी उत्पत्ति होती है। पुद्गल केवल जीवोंके ही शरीरादिकी रचनामें कारण नहीं हैं पुद्गल पुद्गलोंका भी उपकार करते हैं। भस्मसे कांसीके बरतन आदि, निर्मली आदिसे जलादि तथा जलादिसे लोहा आदि स्वच्छ होते हैं। इसी प्रकार औदारिक, वैक्रियिक और आहारक नामकर्मके उदयसे आहारवर्गणाके रूपमें आये तीन शरीर और उच्छ्वास-निश्वास, तैजस नामकर्मके उदयसे

बाह्याभ्यंतरकारणवशर्दिदं स्नेहपर्य्यायाविर्भावदिदं स्निह्यतेऽस्मिन्निति स्निग्धः स्निग्धस्य भावःस्निग्धत्वं। चिक्कणत्वलक्षणपर्य्यायमेंबुदत्थं। तोयाजागोमहिष्युष्ट्रिकाक्षीरघृतंगळोळु स्निग्धगुणमें तु प्रकर्षाप्रकर्षदिदं वत्तिसुगुं। रूक्षणाद्रूक्षस्तस्य भावः रूक्षत्वं। आवुदों दु चिक्कणलक्षणपर्य्यायमदर विपरीतपरिणामं रूक्षत्वमें बुदत्थं। पांसुकणिकाशर्करादिगळोळु रूक्षगुणमें तु काणल्पडुवंते परमाणुगळोळं स्निग्धरूक्षगुणंगळ वृत्तियुं प्रकर्षाप्रकर्षदिदमनुमानिसल्पडुगुं। स्निग्धत्वमुं रूक्षत्वमुं द्व्यणुकादिस्कंधपरिणमनरूपबंधक्के कारणमक्कुं। च शब्ददिदं विश्लेषक्केयुं कारणमक्कुं। स्निग्धगुणपरिणतपरमाणुगळ्गं रूक्षगुणपरिणतपरमाणुगळ्गं परस्परश्लेषलक्षणबंधमागुत्तिरलु द्व्यणुकस्कंधमक्कुमेंबुदत्थमिंतु संख्येयासंख्येयानंतप्रदेशस्कंधं योजिसल्पडुवुदु। अल्लि स्नेहगुणमेकद्वित्रिचतु संख्येयासंख्येयानंतविकल्पमक्कुमा प्रकारदिदमे रूक्षगुणमक्कुं। संदृष्टिः—



बाह्याभ्यन्तरकारणवशात् स्नेहपर्यायाविर्भावेन स्निह्यतेऽस्मिन्निति स्निग्धः, तस्य भावः स्निग्धत्वं चिक्कणत्वमित्यर्थः। रूक्षणात् रूक्षः, तस्य भावो रूक्षत्वं चिक्कणत्वाद्विपरीतत्वमित्यर्थः। स्निग्धत्वं तोयाजागोमहिष्युष्ट्रिकाक्षीरघृतादिषु, रूक्षत्वं च पांसुकणिकाशर्करादिषु प्रकर्षाप्रकर्षभावेन दृश्यते तथा परमाणुष्वपि। ते स्निग्धरूक्षत्वे द्व्यणुकादिस्कंधपरिणमनरूपबन्धस्य चशब्दाद्विश्लेषस्य च कारणे भवतः। स्निग्धगुणपरिणतपरमाणोः रूक्षगुणपरिणतपरमाणोः स्निग्धरूक्षगुणपरिणतपरमाण्वोश्च परस्परश्लेषलक्षणे बन्धे सति द्व्यणुकस्कन्धो भवतीत्यर्थः। एवं संख्येयासंख्येयानन्तप्रदेशस्कन्धोऽपि योज्यः। तत्र स्नेहगुणः एकद्वित्रिचतुःसंख्येयासंख्येयानन्तविकल्पो भवति तथा रूक्षगुणोऽपि ॥६०९॥

बाह्य और अभ्यन्तर कारणके वशसे स्नेह पर्यायके प्रकट होनेसे स्नेहपन होना स्निग्ध है। उसके भावको स्निग्धता कहते हैं जिसका अर्थ चिक्कणता है। रूखापनसे रूक्ष है। उसका भाव रूक्षता है। उसका अर्थ चिक्कणतासे विपरीत होना है। जल तथा बकरी, गाय, भैंस, ऊँटनीके दूध-घी आदिमें स्निग्धता व धूलि, रेत, बजरी आदिमें रूक्षता हीनाधिक रूपसे देखी जाती है। इसी तरह परमाणुओंमें भी होती है। वह स्निग्धता और रूक्षता द्व्यणुक आदि पर्याय परिणमनरूप बन्धका और 'च' शब्दसे बन्धके भेदनका कारण है। स्निग्धगुणरूप परिणत दो परमाणुके रूक्षगुणरूप परिणत दो परमाणुके और एक स्निग्ध तथा एक रूक्षगुणरूप परिणत परमाणुके परस्परमें मिलने रूप बन्धके होनेपर द्व्यणुक स्कन्ध बनता है। इसी प्रकार संख्यात, असंख्यात और अनन्तप्रदेशी स्कन्ध भी जानना। उनमें-से स्नेहगुण एक, दो, तीन, चार, संख्यात, असंख्यात और अनन्त प्रकारका होता है। इसी तरह रूक्षगुण भी होता है ॥६०९॥

१-२. म °गुणं।

णिद्दिट्ठगुणा अहिया होंति परिणामपच्चओ [illegible] ।
[illegible] ॥६१९॥

[illegible] ॥

[illegible]

अनंतरं [illegible] :—

एवं धायइसंडे [illegible] होइ ।
[illegible] ॥६२०॥

[illegible] ॥

[illegible]

अनंतरं [illegible] :—

जाव य [illegible] ।
[illegible] ॥६२१॥

मनुष्यरोळं पंचेंद्रियपर्याप्तरोळं अनंतानुबंध्यन्यतरोदयमिथ्यात्वगुणमनुळ्ळ सासादनरुगळुं पल्यासंख्यातैक-भागमात्रमप्परु प
a a ९

मिच्छा सावयसासणमिस्सा विरदा दुवारणंता य।
पल्लासंखेज्जदिममसंखगुणं संखसंखगुणं ॥६२४॥

मिथ्यादृष्टिश्रावकसासादनमिश्राविरताः द्विकवारानन्तास्च। पल्यासंख्यातैकभागोऽसंख्येयगुणाः संख्येयगुणोऽसंख्येयगुणः ॥

मिथ्यादृष्टिगळुदयकु किंचिदूनसंसारिराशिप्रमितमप्पुदरिंदमनंतानंतप्रमितरप्परु ॥ १३— ॥ देशसंयतरुगळु पदिमूरुकोटि मनुष्यरुगळिंदमधिकमप्प तिर्य्यंचतिगळ पल्यासंख्यातैकभागप्रमितरप्परु प । पन १३ को । सासादनरुगळु मनुष्यगतिय ऐवत्तेरडुकोटिसासादनरिंदमधिकमप्प
a a ४ । ७
इतरगतित्रयसासादनरुगळु देशसंयतरं नोडलु असंख्यातगुणमप्परु प पन ५२ को । ई सासादनर
a a ४
संख्येयं नोडलु मनुष्यगतियमिश्ररुगळु नूरनाल्कु कोटिगळिंदमधिकमप्प त्रिगतिमिश्ररु संख्यात-गुणमप्परु प पन १०४ को । ई मिश्रगुणस्थानवर्त्तिगळं नोडलु मनुष्यगतियोळेळु नूरु
a a
कोटिगळिंदमधिकमप्प त्रिगतिजासंयतरसंख्यातगुणरप्परु प पन ७०० को
a

१— । सासादनगुणा अपि सन्ति अनन्तानुबन्ध्यन्यतमोदयेन प्राप्तमिथ्यात्वगुणत्वात् पल्यासंख्यातैकभागमात्रा भवन्ति च ॥६२३॥
a a ९

मिथ्यादृष्टयः किंचिदूनसंसारिराशिमात्रत्वादनन्तानन्ताः १३— । देशसंयताः त्रयोदशकोटिमनुष्याधिकतिर्यञ्चः पल्यासंख्यातैकभागमात्राः— प पन १३ को । तेभ्यः द्विपञ्चाशत्कोटिमनुष्याधिकशेषत्रिगतिसासादनाः असंख्यात-
a a ४ a
गुणाः प पन ५२ को । तेभ्यः चतुरुत्तरशतकोटिमनुष्याधिकत्रिगतिमिश्राः संख्यातगुणाः प पन १०४ को ।
a a a a a
तेभ्यः सप्तशतकोटिमनुष्याधिकत्रिगत्यसंयता असंख्यातगुणा प पन ७०० को ॥६२४॥
a

सासादनगुणस्थानवाले भी पाते हैं क्योंकि अनन्तानुबन्धी कषायकी चौकड़ीमें-से किसी भी एक क्रोधादिका उदय होनेसे मिथ्यात्वगुणस्थानको प्राप्त होते हैं। उनकी संख्या पल्यके असंख्यातवें भाग है ॥६२३॥

मिथ्यादृष्टि कुछ कम संसारी राशि प्रमाण होनेसे अनन्तानन्त हैं। देश संयत गुणस्थानवाले तेरह कोटि मनुष्य तथा पल्यके असंख्यातवें भागमात्र तिर्यंच हैं। उनसे बावन कोटि मनुष्य तथा शेष तीन गतिके सब सासादनगुणस्थानवाले असंख्यातगुणे हैं। उनसे एक सौ चार कोटि मनुष्य और शेष तीन गतिके सब मिश्र गुणस्थानवाले संख्यातगुणे हैं। उनसे सात सौ कोटि मनुष्य और शेष तीन गतिके अविरत गुणस्थानवाले सब असंख्यातगुणे हैं ॥६२४॥

मनुष्ळ जीवंगळुं पापजीवंगळप्पुवनंतानुबंध्यन्यतरोदयमिथ्यागुणयुतरप्पुवरिनवुं पल्यासंख्यातैकभागप्रमाणमप्पुवु प / a a ४

> मिच्छा सावयसासणमिस्सा विरदा दुवारणंता य ।
> पल्लासंखेज्जदिममसंखगुणं संखगुणमसंखेज्जगुणं ॥६२४॥

मिथ्यादृष्टिश्रावकसासादनमिश्राविरताः द्विकवारानंताश्च। पल्यासंख्यातैकभागोसंख्येयगुणः संख्येयगुणोऽसंख्येयगुणः ॥

मिथ्यादृष्टिजीवंगळु किंचिदूनसंसारिराशिप्रमितमप्पुदरिंदमनंतानंतगळप्पुवु ॥ १३—॥ देशसंयतरुगळु पदिमूरुकोटि मनुष्य देशसंयतरिनधिकमप्प तिर्य्यग्गतिजर पल्यासंख्यातैकभागप्रमितरप्परु प / a । धन १३ को। सासादनरुगळु मनुष्यगतिजद्विपंचाशत्कोटिसासादनरिंदमधिकमप्प a ४। a इतरगतित्रयजसासादनरनितुं देशसंयतरं नोडलुं असंख्यातगुणमप्परु प धन ५२ को ई सासादनर / a a ४ संख्येयं नोडलुं मनुष्यगतिजमिश्ररिंदं नूर नाल्कु कोटिगळिंदमधिकमप्प त्रिगतिजमिश्रर संख्यातगुणमप्परु प धन १०४ को / a a ई मिश्रगुणस्थानवर्त्तिजीवंगळं नोडलु मनुष्यगतिजासंयतरिंदमेळु नूर कोटिगळिंदमधिकमप्प त्रिगतिजासंयतरुमसंख्यातगुणरप्परु प धन ७०० को / a

---

१३– । सासादनगुणा अपि पापाः अनन्तानुबन्ध्यन्यतमोदयेन प्राप्तमिथ्यात्वगुणत्वात् पल्यासंख्यातैकभागमात्रा भवन्ति प / a a ४ ॥६२३॥

मिथ्यादृष्टयः किंचिदूनसंसारित्वादनन्तानन्ताः १३– । देशसंयताः त्रयोदशकोटिमनुष्याधिकतिर्यञ्चः पल्यासंख्यातैकभागमात्राः– प धन १३ को । तेभ्यः द्विपञ्चाशत्कोटिमनुष्याधिकेतरत्रिगतिसासादनाः असंख्यातगुणाः प / a a ४ a धन ५२ को । तेभ्यः चतुरुत्तरशतकोटिमनुष्याधिकत्रिगतिमिश्राः संख्यातगुणाः प धन १०४ को । / a a a तेभ्यः सप्तशतकोटिमनुष्याधिकत्रिगत्यसंयता असंख्यातगुणा प धन ७०० को ॥६२४॥ / a

---

सासादनगुणस्थानवाले भी पापी हैं क्योंकि अनन्तानुबन्धीकषायकी चौकड़ीमें-से किसी भी एक क्रोधादिका उदय होनेसे मिथ्यात्वगुणस्थानको प्राप्त होते हैं। उनकी संख्या पल्यके असंख्यातवें भाग है ॥६२३॥

मिथ्यादृष्टि कुछ कम संसारी राशि प्रमाण होनेसे अनन्तानन्त हैं। देश संयत गुणस्थानवाले तेरह कोटि मनुष्य तथा पल्यके असंख्यातवें भागमात्र तिर्यंच हैं। उनसे बावन कोटि मनुष्य तथा शेष तीन गतिके सब सासादनगुणस्थानवाले असंख्यातगुणे हैं। उनसे एक सौ चार कोटि मनुष्य और शेष तीन गतिके सब मिश्र गुणस्थानवाले संख्यातगुणे हैं। उनसे सात सौ कोटि मनुष्य और शेष तीन गतिके अविरत गुणस्थानवाले सब असंख्यातगुणे हैं ॥६२४॥

उपशमकरोळु षोडशमुं चतुर्विंशतियुं त्रिंशत्तुं षट्त्रिंशत्तियुं द्विचत्वारिंशत्तियुं अष्टचत्वारिंशत्तियुं चतुःपंचाशत्तियुं चतुःपंचाशत्तियुं निरंतराष्टसमयंगळोळप्पुवु । १६ । २४ । ३० । ३६ । ४२ । ४८ । ५४ । ५४ ।

बत्तीसं अडदालं सट्ठी बावत्तरी य चुलसीदी ।
छण्णउदी अट्ठुत्तरसयमट्ठुत्तरसयं च खवगेसु ॥६२८॥

द्वात्रिंशदष्टचत्वारिंशत् षष्टि द्वासप्ततिचतुरशीतिः । षण्णवतिरष्टोत्तरशतमष्टोत्तरशतं क्षपकेषु ॥

क्षपकरोळु निरंतराष्टसमयंगळोळु उपशमकर संख्येयं नोडलु द्विगुणमागि द्वात्रिंशदादिगळप्पुवु । ३२ । ४८ । ६० । ७२ । ८४ । ९६ । १०८ । १०८ ॥ ई संख्येयं निरंतराष्टसमयंगळोळु समीकरणविधानदिदं साधिसुव । आदि ३४ । उत्तरं १२ । गच्छे ८ । पदमेगेन विहीनमित्यादि संकलनसूत्रदिदं तरल्पट्ट सर्व्वधनमिदु अष्टोत्तरषट्शतमप्पुदु । ६०८ ॥ उपशमकर्गे । आदि १७ । उत्तरं ६ । गच्छ ८ । इन्तिदु मा सूत्रदिदं तरल्पट्ट सर्व्वधनमिदु चतुरुत्तरत्रिशतमप्पुदु । ३०४ ॥

अट्ठेव सयसहस्सा अट्ठाणउदी तहा सहस्साणं ।
संखा जोगिजिणाणं पंचसयबिउत्तरं वंदे ॥६२९॥

अष्टैव शतसहस्राणि अष्टानवतिस्तथा सहस्राणां । संख्या योगिजिनानां पंचशतं द्व्युत्तरं वंदे ॥

उपशमके षोडश चतुर्विंशतिः त्रिंशत् षट्त्रिंशत् द्वाचत्वारिंशत् अष्टचत्वारिंशत् चतुःपञ्चाशत् चतुःपञ्चाशत् निरन्तराष्टसमयेषु भवन्ति । १६ । २४ । ३० । ३६ । ४२ । ४८ । ५४ । ५४ ॥६२७॥

क्षपके निरन्तराष्टसमयेषु उपशमकेभ्यो द्विगुणत्वात् द्वात्रिंशत् अष्टचत्वारिंशत् षष्टिः द्वासप्ततिः चतुरशीतिः षण्णवतिः अष्टोत्तरशतं अष्टोत्तरशतं भवन्ति । इमामेव संख्यां निरन्तराष्टसमयेषु समीकरणविधानेन आदिः ३४ उत्तरः १२ गच्छः ८ पदमेगेन विहीनमित्यादिनानीतधनम् । इत्थं अष्टोत्तरषट्शतं भवन्ति । ६०८ । उपशमकानां आदिः १७ उत्तरः ६ गच्छः ८ धनं चतुरुत्तरत्रिशतं ३०४ भवन्ति ॥६२८॥

उपशमश्रेणिपर निरन्तर चढ़नेवाले जीवोंकी आठ समयोंमें संख्या क्रमसे सोलह, चौबीस, तीस, छत्तीस, बयालीस, अड़तालीस, चौवन, चौवन होती है ॥६२७॥

क्षपकश्रेणिकी संख्या उपशमवालोंसे दुगुनी होती है इसलिए निरन्तर आठ समयोंमें क्षपकश्रेणि चढ़नेवालोंकी संख्या क्रमसे बत्तीस, अड़तालीस, साठ, बहत्तर, चौरासी, छियानवे, एक सौ आठ, एक सौ आठ होती है। इसी संख्याको निरन्तर आठ समयोंमें समीकरण विधानके द्वारा बराबर करके पहले समयमें चौंतीस, फिर आठ समयोंमें बारह-बारह अधिक करनेसे आदिधन चौंतीस, उत्तर बारह और गच्छ आठ, इसको 'पदमेगेण विहीणं' इत्यादि सूत्रके अनुसार गच्छ आठमें एक घटानेसे सात रहे, दोका भाग देनेसे साढ़े तीन रहे। उत्तर बारहसे गुणा करनेपर बयालीस हुए। इसमें आदिधन चौंतीस जोड़नेसे छिहत्तर हुए। इसे गच्छ आठसे गुणा करनेसे छह सौ आठ हुए। ये सब क्षपकोंका जोड़ होता है। इसी तरह उपशमश्रेणिवालोंका आदिधन सतरह, उत्तर छह, गच्छ आठका धन उससे आधा तीन सौ चार होता है ॥६२८॥

इंतिदोंदु पक्षांतरमरियल्पडुगु । अनंतरमेक समयदोळु युगपत्संभविसुव [illegible]
संख्येयुमनुपशमकर विशेषसंख्येयुमं गाथात्रयदिदं पेळ्दपर ।

होंति खवा इगिसमये बोहियबुद्धा य पुरिसवेदा य ।
उक्कस्सेणट्ठुत्तरसयप्पमा सग्गदो य चुदा ॥६३०॥

भवंति क्षपकाः एकस्मिन्समये बोधितबुद्धाश्च पुरुषवेदाश्च । [illegible]
स्वर्गांतश्च च्युताः ॥

पत्तेयबुद्धतित्थयरत्थिणउंसयमणोहिणाणजुदा ।
दसछक्कवीसदसवीसट्ठावीसं जहाकमसो ॥६३१॥

प्रत्येकबुद्धतीर्थंकरस्त्रीनपुंसकमनोवधिज्ञानयुताः । दश षट्क [illegible]

मप्पुरु १०८/५४ प्रत्येकबुद्धरु क्षपकरु पत्तुपशमकरय्वरु १०/५ तीर्त्थंकररु क्षपकररुवरुपशमकरु मूवरु ६/३ स्त्रीवेदिक्षपकरुमिप्पत्तुपशमकर्प्पंदिवरु २०/१० नपुंसकवेदिगळु क्षपकरु पदिबरवरर्द्ध-मुपशमकरु १०/५ मनःपर्य्ययज्ञानिगळु क्षपकरुगळिप्पत्तु तदर्द्धमुपशमकरु २०/१० अवधिज्ञानिगळु क्षपकरुगळिप्पत्तेंदुमुपशमकरुगळु तदर्द्धमप्परु २८/१४ उत्कृष्टावगाहनयुतक्षपकरुगळीर्व्वरुपशमक-नोर्व्वने २/१ जघन्यावगाहनयुतक्षपकरु नाल्वरुपशमकरीर्व्वरु ४/२ बहुमध्यमावगाहनयुतक्षपक-रेण्टुवरुपशमकर्न्नाल्वरु ८/४ मितेल्ला क्षपकरु ४३२। उपशमकरु २१६।

अनंतरं अयोगिजिनरसंख्येयं कंठोक्तमागि पेळ्दुविल्लप्पुदरिंदं प्रमत्तगुणस्थानं मोदल्गों्डु अयोगकेवलिभट्टारकावसानमाद समस्तसंयमिगळ संख्येयं पेळ्वडदरोळु सयोगकेवलिपर्य्यंतं कंठोक्त-मागि पेळल्पट्ट संयमिगळ संख्येयं कूडि कळेदोडे शेषमयोगिकेवलिगळ संख्येयक्कुमेंबुदं मनदोळि-रिसि संयमिगळ सर्व्वसंख्येयं पेळ्वपं :—

सत्तादी अट्ठंता छण्णवमज्झा य संजदा सव्वे।
अंजलिमौलियहत्थो तियरणसुद्धे णमंसामि ॥६३३॥

सप्ताद्यष्टांतान् षण्णवमध्यांश्च संयुतान्सर्व्वान्। अंजलिमौलिकहस्तस्त्रिकरणशुद्धया नम-स्यामि ॥

सप्तांकमादियागि अष्टांकमवसानमागि षण्नवांकंगळं मध्यमागुळ्ळ त्रिहीननवकोटिसंयतरु-गळनंजलिमौळिकहस्तनागि मनोवाक्कायशुद्धिगळिंदं वंदिसुवें ॥ एंदितु सर्व्वसंयमिगळ संख्येयो

कास्तदर्धं भवन्ति। पुनः प्रत्येकबुद्धाः तीर्थङ्कराः स्त्रीवेदिनः नपुंसकवेदिनः मनःपर्ययज्ञानिनः अवधिज्ञानिनः उत्कृष्टावगाहाः जघन्यावगाहाः बहुमध्यमावगाहाश्च क्षपकाः क्रमशः दश षट्विंशतिः दश विंशतिः अष्टाविंशतिः द्वौ चत्वारः अष्टौ, उपशमकाः तदर्धं भवन्ति। सर्वे मिलित्वा क्षपकाः ४३२। उपशमकाः २१६ ॥६३०–६३२॥
अथ सर्वसंयमिसंख्यामाह—

. आदौ सप्ताङ्कं अन्तेऽष्टाङ्कं च लिखित्वा तयोर्मध्ये च षट्सु नवाङ्केषु लिखितेषु संजनितत्र्यूननवकोटि-संख्यामात्रान् सर्वसंयतान् अञ्जलिमौलिकहस्तोऽहं मनोवाक्कायशुद्धया नमस्यामि। ८९९९९९९७। अत्र च

होते हैं। और उपशमक इनसे आधे अर्थात् चौवन-चौवन होते हैं। पुनः क्षपकश्रेणीवाले प्रत्येकबुद्ध दस, तीर्थंकर छह, स्त्रीवेदी बीस, नपुंसकवेदी दस, मनःपर्ययज्ञानी बीस, अवधिज्ञानी अट्ठाईस, उत्कृष्ट अवगाहनावाले दो, जघन्य अवगाहनावाले चार, बहुमध्यम अवगाहनावाले आठ एक समयमें उत्कृष्ट रूपसे होते हैं। उपशमक इनसे आधे होते हैं। सो उक्त सब क्षपकोंकी संख्या मिलकर चार सौ बत्तीस होती है और उपशमकोंकी दो सौ सोलह ॥६३०–६३२॥

आगे सब संयमियोंकी संख्या कहते हैं—

सातका अंक आदिमें और अन्तमें आठका अंक लिखकर दोनोंके मध्यमें छह नौके

गुणस्थानदोळ्पेळ्द असंयतसम्यग्दृष्टि सम्यग्मिथ्यादृष्टि सासादनसम्यग्दृष्टिगळ्गे मो मूरुं गुणस्थानंगळ वायुर्केळगु पल्यक्के पोरक भागहारंगळ अ a
मि a a
सा a a ४
युरूपोनावल्यसंख्यातदिदं a-१ । भागिसि भागिसि तंतम्म हारदोळे कूडल्पट्टुवादोडे देवौघदोळु तंतम्म भागहारंगळप्पुवु ।
अ a a
a-१
मि a a a
a-१
सा a a ४ a
a-१
मत्तमो देवसामान्यगुणस्थानत्रयभागहारंगळं रूपोनावल्यसंख्यातदिदं भागिसि भागिसिदेकभागमं तंतम्म हारंगळोळु प्रक्षेपिसुत्तं विरलु सौधर्म्मैशानकल्पद्वयद असंयतमिश्रसासादनरुगळ भागहारंगळप्पुवु । सौधर्म्मकल्पद्वयद असंयतन भागहारंगळु प
a a a
a-१a-१
मिश्रभागहारंगळु प
a a a a
a-१a-१
सासादनर भागहारंगळु प
a a ४ a a
a-१a-१
अनंतरमो सौधर्म्मकल्पद्वयासंयतादि सासादनगुण-

गुणस्थानोक्ताः असंयतसम्यग्मिथ्यादृष्टिसासादनानां ये पल्यासंख्यातत्रिकभागहाराः अ a
मि a a
सा a a ४
एतेषु रूपोनावल्यसंख्यातेन a-१ भक्त्वा एतेष्वेव निक्षिप्तेषु देवौघे स्वस्वभागहारा भवन्ति ।
अ a a
a-१
मि a a a
a-१
सा a a ४ a
a-१
एतान् पुनः रूपोनावल्यसंख्यातेन भक्त्वा एकैकभागे स्वस्वहारे प्रक्षिप्ते सौधर्मैशानासंयत-

---

गुणस्थानोंमें जीवोंकी संख्या कहते हुए पूर्वमें जो असंयत, सम्यग्मिथ्यादृष्टि और सासादनोंके पल्यके भागहार कहे हैं उनमें एक कम आवलीके असंख्यातवें भागसे भाग देनेसे जो प्रमाण आवे उन्हें उन्हीं भागहारोंमें मिलानेसे देवगतिमें अपना-अपना भागहार होता है। इन भागहारोंको पुनः एक कम आवलीके असंख्यातवें भागसे भाग देकर एक-एक भाग अपने-अपने भागहारमें मिलानेपर सौधर्म और ऐशान स्वर्गमें असंयत मिश्र और सासादनोंके भागहार होते हैं।

विशेषार्थ—पहले असंयतगुणस्थानमें भागहारका प्रमाण एक [illegible] संख्यात कहा था। उसे एक कम आवलीके असंख्यातवें भागसे भाग [illegible]
उस भागहारमें मिलानेपर जो प्रमाण हो उतना [illegible]
भागहार जानना। इस भागहारका भाग पल्यमें देनेसे [illegible]
असंयतगुणस्थानवर्ती जीव हैं। मिश्रमें दो [illegible]

सोहम्मादासारं जोइसवणभवणतिरियपुढवीसु ।
अविरदमिस्सेऽसंखं संखासंखगुण सासणे देसे ॥६३७॥

सौधर्म्मादासहस्रारं ज्योतिषिकवानभावनतिर्य्यक्पृथ्वीषु । अविरतमिश्रेऽसंख्ये संख्य असंख्यगुणं सासादने देशसंयते ॥

सौधर्म्मद्वयदत्तणिदं मेळे सानत्कुमारकल्पद्वयं मोदल्गोंडु सहस्रारकल्पपर्य्यंतं कल्पद्वयपंचकदोळं ज्योतिषिकवानभावनतिर्य्यंच प्रथमद्वितीयतृतीयचतुर्थपंचमषष्ठसप्तमपृथ्विर्य्येबी षोडश स्थानदोळमविरतरोळं मिश्ररोळमसंख्यातगुणितक्रममक्कुं । सासादनरोळुसंख्यातगुणमक्कु । तिर्य्यंचदेशसंयतरोळसंख्यातगुणमक्कुमदे ते दोडेमुं पेळ्द सानत्कुमारकल्पद्वयद सासादनहारमं नोडलु ब्रह्मकल्पद्वयासंयतहारमसंख्यातगुण a a a a ४ a a ४ a
a − १a − १
मदं नोडलु मिश्रहारमसंख्यातगुण a a a a ४ a a ४ a a
a − १a − १
मदं नोडलु सासादनर हारं संख्यातं गुणमक्कु a a a a ४ a a ४ a a ४
a − १a − १
मदं नोडलु लांतवकल्पद्वयदऽसंयतहारमसंख्यातगुण a a a a ४ a a ४ । २ । a
a − १a − १
मदं नोडलु मिश्रर हारमसंख्यातगुण a a a a ४ a a ४ । २ । a a
a−१a − १
मदं नोडलु सासादनहारं संख्यातगुणमक्कु a a a a ४ a a ४ । २ । a a ४
a − १a − १
मदं नोडलु शुक्रकल्पद्वयासंयतहारमसंख्यातगुणमक्कु a a a a ४ a a ४ । ३ । a
a − १a − १
मदं नोडलु मिश्रहारमसंख्यातगुणमक्कु a a a a ४ a a ४ । ३ । a a
a − १a − १
मदं नोडलु तत्रत्य सासादनहारं संख्यातगुणमक्कु a a a a ४ a a ४ । ३ a a ४
a − १a − १
मदं नोडलु

सौधर्मद्वयादुपरि सानत्कुमारादिसहस्रारपर्यन्तं पञ्चयुग्मेषु ज्योतिष्कवानभावनतिर्यक्सप्तपृथ्वीषु चेति षोडशस्थानेषु अविरते मिश्रे स्वसंख्येयगुणितक्रमः सासादने संख्यातगुणितक्रमः, तिर्यग्देशसंयते असंख्यातगुणितक्रमश्च भवति । तथाहि—सानत्कुमारद्वयसासादनहाराद् ब्रह्मद्वयस्य असंयतहारोऽसंख्यातगुणः । ततो मिश्रहारोऽसंख्यातगुणः । ततः सासादनहारः संख्यातगुणः । अत्र संख्यातस्य संदृष्टिश्चतुरङ्कः । ततः लान्तवद्वये असंयतहारः असंख्यातगुणः । ततः मिश्रहारः असंख्यातगुणः । ततः सासादनहारः संख्यातगुणः । ततः शुक्रद्वये-

---

सौधर्मसे ऊपर सानत्कुमारसे लेकर सहस्रार पर्यन्त पाँच स्वर्ग युगलोंमें और ज्योतिषी, व्यन्तर, भवनवासी, तिर्यंच, और सात नरक इन सोलह स्थानोंमें अविरत और मिश्रमें असंख्यात गुणितक्रम जानना । सासादनमें संख्यात गुणितक्रम जानना । और तिर्यंच सम्बन्धी देशसंयत गुणस्थानमें असंख्यात गुणितक्रम जानना । इसका स्पष्टीकरण इस प्रकार है—सानत्कुमार, माहेन्द्रमें जो सासादनका भागहार कहा उससे ब्रह्म-ब्रह्मोत्तरमें असंयतका भागहार असंख्यातगुणा है । उससे मिश्रका भागहार असंख्यातगुणा है । उससे सासादनका भागहार संख्यातगुणा है । यहाँ संख्यातकी संदृष्टि चारका अंक ४ है । उससे लान्तव-कापिष्ठमें असंयतका भागहार असंख्यातगुणा है । उससे मिश्रका भागहार असंख्यातगुणा है । उससे सासादनका भागहार संख्यातगुणा है । उससे शुक्र महाशुक्रमें असंयतका भागहार असंख्यातगुणा है । उससे मिश्रका भागहार असंख्यातगुणा है । उससे सासादनका भागहार संख्यातगुणा है । उससे शतारसहस्रारमें असंयतका भागहार

संयतहारमुमसंख्यातगुणमक्कुं ■ a a a ४ a a ४ ९ a प्रथमपृथ्वि = असंयताहार
a – १a – १
a a a a ४ a a ४ । ९ । a मवं नोडलु तन्मिश्रहारमसंख्यातगुणमक्कु a a a a ४ a a ९ । a a
a – १a – १ a – १a – १
मदं नोडलु तत्रत्यसासादनहारं संख्यातगुणमक्कु a a a a ४ a a ४ । ९ a a ४ मदं नोडलु
a – १a – १
द्वितीयपृथ्विय असंयतहारमसंख्यातगुणमक्कु a a a a ४ a a ४ । १० । a । मदं नोडलु
a – १a – १
तन्मिश्रहारमसंख्यातगुणमक्कु a a a a ४ a a ४ । १० । a a मदं नोडलु तत्रत्यसासादन-
a – १a – १
हारं संख्यातगुणमक्कुं a a a a ४ a a ४ । १० । a a ४ । मदं नोडलु तृतीयधराऽसंयत-
a – a१ – १
हारमसंख्यातगुणमक्कु a a a a ४ a a ४ । ११ a । मदं नोडलु तन्मिश्रहारमसंख्यातगुण-
a – १a – १
मक्कु a a a a ४ a a ४ ११ a a मदं नोडलु तत्रत्य सासादनहारं संख्यातगुणमक्कु
a – १a – १
a a a a ४ a a ४ । ११ a a ४ मदं नोडलु चतुर्थभूनारकाऽसंयतहारमसंख्यातगुणमक्कु
a – १a – १
a a a a ४ a a ४ । १२ । a मदं नोडलु तन्मिश्रहारमसंख्यातगुणमक्कु a a a a ४ a a ४ । १२ । a a
a – १a – १ a – १a – १
मदं नोडलु तत्रत्यसासादनहारं संख्यातगुणमक्कु a a a a ४ a a ४ । १२ । a a ४ मदं नोडलु
a – १a – १
पंचमधराऽसंयतहारमसंख्यातगुणमक्कुं a a a a ४ a a ४ । १३ । a मदं नोडलु तन्मिश्रहारम-
a – १a – १
संख्यातगुणमक्कु a a a a ४ a a ४ । १३ । a a मदं नोडलु तत्रत्यसासादनहारं संख्यातगुण-
a – १a – १

यदेवसंयतहारः असंख्यातगुणः । अयमेव प्रथमपृथिव्यसंयतस्यापि हारः । ततः मिश्रहारः असंख्यातगुणः । ततः सासादनहारः संख्यातगुणः । ततः द्वितीयपृथिव्यसंयतहारः असंख्यातगुणः । ततः मिश्रहारः असंख्यात-गुणः । ततः सासादनहारः संख्यातगुणः । ततः तृतीयपृथिव्यसंयतहारः असंख्यातगुणः । ततः मिश्रहारः असंख्यातगुणः । ततः सासादनहारः संख्यातगुणः । ततः चतुर्थपृथिव्यसंयतहारः असंख्यातगुणः । ततः मिश्रहारः असंख्यातगुणः । ततः सासादनहारः संख्यातगुणः । ततः पञ्चमधरासंयतहारः असंख्यातगुणः । ततः मिश्रहारः

है वही भागहार प्रथम नरकमें असंयतका भी है। उससे मिश्रका भागहार असंख्यातगुणा है। उससे सासादनका भागहार संख्यातगुणा है। उससे दूसरे नरकमें असंयतका भागहार असंख्यातगुणा है। उससे मिश्रका भागहार असंख्यातगुणा है। उससे सासादनका भागहार संख्यातगुणा है। उससे तीसरे नरकमें असंयतका भागहार असंख्यातगुणा है। उससे मिश्रका भागहार असंख्यातगुणा है। उससे सासादनका भागहार संख्यातगुणा है। उससे चौथे नरकमें असंयतका भागहार असंख्यातगुणा है। उससे मिश्रका भागहार असंख्यात-गुणा है। उससे सासादनका भागहार संख्यातगुणा है। उससे पंचम नरकमें असंयत भागहार असंख्यातगुणा है। उससे मिश्रका भागहार असंख्यातगुणा है। उससे सासादनका

तत्तो संखेज्जगुणा सासणसम्मा होंति संखगुणा ।
उत्तट्ठाणे कमसो पणछस्सत्तट्ठचदुरसंदिट्ठी ॥६४०॥

ततः संख्येयगुणाः सासादनसम्यग्दृष्टयो भवति संख्यगुणाः । उक्तस्थाने क्रमतः पंचषट्सप्ताष्टचत्वारः संदृष्टिः ॥ गाथा द्वितयं ॥

सम्यग्दृष्टिसासादनसम्यग्दृष्टिय हारंगळु आनतकल्पद्वयमिथ्यादृष्टिगळ्गेनुं आरण अच्युतकल्पद्वयप्रभृतियुपरिमग्रैवेयकपर्य्यंतमाद सम्यग्दृष्टिगळ्गेनुमसंख्यातगुणमप्पु संख्यातगुणमुं यथाक्रमदिं मागियप्पुवदें ते दोडे सम्यग्दृष्टिसासादनसम्यग्दृष्टिय हारमं नोडलु आनतकल्पद्वयमिथ्यादृष्टिहारमसंख्यातगुणमक्कु ० ० ० ० ४ ० ० ४ । १६ ० / ० − १० − १ मदं नोडलु आरणाच्युतकल्पद्वयमिथ्यादृष्टिहारं संख्यातगुणमक्कु ० ० ० ० ४ ० ० ४ । १६ । ० ५ / ० − १० − १ मदं नोडलु अधस्तनाधस्तनग्रैवेयकसम्यग्दृष्टिहारं संख्यातगुणमक्कं ० ० ० ० ४ । ० ० ४ । १६ ० । ५ । ५ / ० − १० − १ मदं नोडलु अधस्तनमध्यमग्रैवेयकसम्यग्दृष्टिहारं संख्यातगुणमक्कुं ० ० ० ० ४ ० ० ४ । १६ ० । ५ । ५ । ५ / ० − १० − १ मदं नोडलुमधस्तनोपरितनग्रैवेयकसम्यग्दृष्टिहारं संख्यातगुणमक्कु ० ० ० ० ४ ० ० ४ । १६ ० । ५ । ५ । ५ । ५ / ० − १० − १ मदं नोडलुमध्यमाधस्तनग्रैवेयकसम्यग्दृष्टिहारं संख्यातगुणमक्कु ० ० ० ० ४ ० ० ४ । १६ ० । ५ । ५ । ५ । ५ । ५ / ० − १० − १ मदं नोडलु मध्यम मध्यमग्रैवेयक सम्यग्दृष्टिहारं संख्यातगुणमक्कु ० ० ० ० ४ ० ० ४ । १६ ० । ५ । ५ । ५ । ५ । ५ । ५ / ० − १० − १ मदं नोडलु मध्यमोपरितनसम्यग्दृष्टिहारं संख्यातगुणमक्कु ० ० ० ० ४ ० ० ४ । १६ ० । ५ । ५ । ५ । ५ । ५ । ५ । ५ / ० − १० − १ मदं नोडलुपरितनाधस्तनग्रैवेयकसम्यग्दृष्टिहारं संख्यातगुणमक्कु ० ० ० ० ४ ० ० ४ । [illegible] । ५ । ५ । ५ । ५ । ५ । ५ । ५ । ५ / ० − १० − १ मदं नोडलुपरितनमध्यमग्रैवेयकसम्यग्दृष्टिहारं संख्यातगुणमक्कु ० ० ० ० ४ ० ० ४ । १६ । ० । ५ । ५ । ५ । ५ । ५ । ५ । ५ । ५ । ५ / ० − १० − १ मदं नोडलुपरितनोपरितनग्रैवेयकसम्यग्दृष्टिहार संख्यातगुणमक्कु ० ० ० ० ४ ० ० ४ । १६ । ० । ५ । ५ । ५ । ५ । ५ । ५ । ५ । ५ । ५ । ५ / ० − १० − १

[illegible] ॥६४०॥

[illegible]

अन्तिम ग्रैवेयक पर्यन्त [illegible] असंख्यातगुणे हैं। यहाँ संख्यातकी संदृष्टि [illegible] है। [illegible] अन्तिम ग्रैवेयक [illegible] भागहारसे भी [illegible] और [illegible] संख्यातगुणे हैं। यहाँ संख्यातकी संदृष्टि [illegible] है। [illegible] भागहारसे [illegible] है। ॥६४०॥

[illegible] अन्तिम ग्रैवेयक

भक्तजगच्छ्रेणिमात्रं वामरुगळप्परु ८ । पंचमपृथ्वियोळु गुणप्रतिपन्नराशित्रयविहीननिज-षष्ठमूलभक्तजगच्छ्रेणिमात्रं वामरुगळप्परु । ६ । षष्ठपृथ्वियोळु गुणप्रतिपन्नराशित्रयविहीननिज-तृतीयमूलभक्तजगच्छ्रेणिमात्रं वामरुगळप्पुरु ३ । सप्तमपृथ्वियोळु गुणप्रतिपन्नराशित्रयविहीन-निजद्वितीयमूलभक्तजगच्छ्रेणिमात्रं वामरुगळप्परु । २ । आनतादिगळोळु कंठोक्तमागि पेळल्पट्टरु । सर्व्वार्त्थसिद्धिविमानाहमिंद्ररु असंयतसम्यग्दृष्टिगळु । 'तिगुणा सत्तगुणा वा सव्वट्ठा माणुसी पमाणादो' एंदितु संख्यातमप्परु ४२=४२=४२०३ । ३ । ७।। मनुष्यगतियोळु देशसंयतादिगळं पेळ्दपं :—

तेरसकोडीदेसे बावण्णं सासणे मुणेदव्वा ।
मिस्सावि य तद्दुगुणा असंजदा सत्तकोडिसया ।।६४२।।

त्रयोदशकोट्यो देशसंयते द्विपंचाशत्कोटयः सासादने ज्ञातव्याः । मिश्राश्चापि तद्द्विगुणा भवंति असंयताः सप्तकोटिशताः ।।

मनुष्यगतियोळु देशसंयतरु पदिमूरु कोटिगळप्परु । १३ को । सासादनरु द्विपंचाशत्कोटि-प्रमितरप्परु । ५२ को । मिश्ररुगळु तद्द्विगुणमप्परु १०४ को । असंयतसम्यग्दृष्टिगळु सप्तकोटिशत-मितरप्परु ७०० को । प्रमत्तादिसंख्ये मुन्नमे पेळल्पट्टुदु ।

नीयु किंचिदूना क्रमशो निजद्वादशदशमाष्टमषष्ठतृतीयमूलभक्तजगच्छ्रेणिः । आनतादिषु कण्ठोक्तपोक्त । सर्वार्थसिद्धावहमिन्द्रा असंयता एव । ते च मानुषीप्रमाणात्त्रिगुणाः सप्तगुणा वा भवन्ति ।।६४१।। मनुष्यगतावाह—

देशसंयते त्रयोदशकोट्यो मनुष्याः । १३ को । सासादने द्विपञ्चाशत् कोट्यः ५२ को । मिश्रे ततो द्विगुणाः १०४ को । असंयते सप्त शतकोट्यः ७०० को । प्रमत्तादीनां संख्या तु प्रागुक्ता ।।६४२।।

नवें, आठवें, छठे, तीसरे और दूसरे वर्गमूलका भाग जगतश्रेणिमें देनेसे जो-जो प्रमाण आवे उसमें कुछ-कुछ कम मिथ्यादृष्टियोंका प्रमाण है। यहाँ जो अपनी-अपनी समस्त राशि-में कुछ कम किया है सो दूसरे आदि गुणस्थानवाले जीवोंके प्रमाणको घटानेके लिए किया है क्योंकि मिथ्यादृष्टियोंकी तुलनामें उनका परिमाण बहुत अल्प है। आनतादिमें मिथ्यादृष्टियोंका प्रमाण पहले कहा ही है। सर्वार्थसिद्धिमें अहमिन्द्र असंयत सम्यग्दृष्टि ही हैं। मानुषियोंके प्रमाणसे उनका प्रमाण तिगुना और किन्हींके मतसे सात गुणा कहा है ।।६४१।।

मनुष्यगतिमें कहते हैं—

मनुष्य देशसंयत गुणस्थानमें तेरह कोटि जानना। सासादनमें बावन कोटि जानना। मिश्रमें उससे दुगुने अर्थात् एक सौ चार कोटि जानना। असंयतमें सात सौ कोटि जानना। प्रमत्त आदिकी संख्या पहले कही है ।।६४२।।

आस्रवद्रव्यमुं संवरद्रव्यमुं प्रत्येकं समयप्रबद्धमक्कुं निर्जराद्रव्यमुं तु मत्ते समयप्रबद्ध-मनोडलुमसंख्यातगुणितमुत्कृष्टमक्कुं नियमदिदं ।

> बंधो समयपबद्धो किंचूणदिवड्ढमेत्तगुणहाणी ।
> मोक्खो य होदि एवं सद्दहिदव्वा दु तच्चट्ठा ॥६४८॥

बंधः समयप्रबद्धः किंचिदूनद्व्यर्धमात्रगुणहानिर्मोक्षश्च भवत्येवं श्रद्धातव्यास्तु तत्वार्थाः ॥

तु मत्ते बंधमुं समयप्रबद्धमेयक्कुं । मोक्षद्रव्यं किंचिदूनद्व्यर्धगुणहानिमात्रसमयप्रबद्धंगळप्पु-वेंदितु तत्वार्थंगळु श्रद्धातव्यंगळप्पुवु ।

अनंतरं सम्यक्त्वभेदमं पेळ्दपं :—

> खीणे दंसणमोहे जं सद्दहणं सुणिम्मलं होई ।
> तक्खाइयसम्मत्तं णिच्चं कम्मक्खवणहेदू ॥६४६॥

क्षीणे दर्शनमोहे यच्छ्रद्धानं भवति सुनिर्म्मलं । तत्क्षायिकसम्यक्त्वं नित्यं कर्म्मक्षपणहेतुः ॥

मिथ्यात्वसम्यग्मिथ्यात्वसम्यक्त्वप्रकृतिगळुमनंतानुबंधिचतुष्टयमुं करणलब्धिपरिणाम-सामर्थ्यदिदं क्षीणमागुत्तं विरलु आवुदोंदु श्रद्धानं सुनिर्म्मलमक्कुमदु क्षायिकसम्यग्दर्शनमें बुदक्कुमा क्षायिकसम्यग्दर्शनं नित्यं नित्यमक्कुमेकें दोडे प्रतिपक्षकर्म्मप्रक्षयदिदं पुट्टिदात्मगुणविशुद्धिरूप-सम्यग्दर्शनमक्षयमप्पुददिदं प्रतिसमयं गुणश्रेणिकर्म्मनिर्ज्जराकारणमक्कुमंते पेळल्पट्टुदु ।

> दंसणमोहक्खविदे सिज्झदि एक्केव तदियतुरियभवे ।
> णादिक्कदि तुरिय भवं ण विणस्सदि सेस सम्मं व ॥

आस्रवद्रव्यं संवरद्रव्यं च समयप्रबद्धः । निर्जराद्रव्यं तु पुनः उत्कृष्टं समयप्रबद्धान्नियमेनासंख्यातगुणं भवति ॥६४७॥

तु—पुनः बन्धोऽपि समयप्रबद्ध एव । मोक्षद्रव्यं किंचिदूनद्व्यर्धगुणहानिमात्रसमयप्रबद्धं भवतीति एवं तत्त्वार्थाः श्रद्धातव्याः ॥६४५॥ अथ सम्यक्त्वभेदमाह—

मिथ्यात्वसम्यग्मिथ्यात्वसम्यक्त्वप्रकृतित्रये अनन्तानुबन्धिचतुष्के च करणलब्धिपरिणामसामर्थ्यात् क्षीणे सति यच्छ्रद्धानं सुनिर्मलं भवति तत्क्षायिकसम्यग्दर्शनं नाम । तच्च नित्यं स्यात् प्रतिपक्षप्रक्षयोत्थात्म-गुणत्वात् । पुनः प्रतिसमयं गुणश्रेणिनिर्जराकारणं भवति । तथा चोक्तं—

आस्रवद्रव्य और संवरद्रव्य प्रबद्ध प्रमाण है। किन्तु उत्कृष्ट निर्जराद्रव्य समयप्रबद्धसे नियमसे असंख्यातगुणा होता है ॥६४८॥

बन्धद्रव्य भी समयप्रबद्ध प्रमाण ही है। और मोक्षद्रव्य किंचित् हीन डेढ़ गुण हानिसे गुणित समयप्रबद्ध प्रमाण होता है। इस प्रकार तत्वार्थोंका श्रद्धान करना चाहिए ॥६४५॥

आगे सम्यक्त्वके भेद कहते हैं—

करणलब्धि रूप परिणामोंकी सामर्थ्यसे मिथ्यात्व, सम्यग्मिथ्यात्व और सम्यक्त्व प्रकृति इन तीन दर्शनमोहके तथा अनन्तानुबन्धी क्रोध मान माया लोभके क्षय होनेपर जो अत्यन्त निर्मल श्रद्धान होता है उसका नाम क्षायिक सम्यग्दर्शन है। यह नित्य है; क्योंकि प्रतिपक्षी कर्मोंके क्षयसे उत्पन्न होनेके साथ आत्माका गुण है। तथा प्रतिसमय गुणश्रेणि

ण य मिच्छत्तं पत्तो सम्मत्तादो य जो य परिवडिदो ।
सो सासणोत्ति णेयो पंचमभावेण संजुत्तो ॥६५४॥

न च मिथ्यात्वं प्राप्तः सम्यक्त्वतश्च यश्च परिपतितः । सासादन इति ज्ञेयः पंचमभावेन संयुक्तः ॥

आवनोर्व्वं जीवनु सम्यक्त्वदिदं बळिचि मिथ्यात्वमं पोर्द्दवन्नेवरमिप्पं्वन्नेवरमा जीवं सासादननें दितरियल्पडुवं । दर्शनमोहनीयोदयोपशमादिनिरपेक्षापेक्षेयिदं पारिणामिकभावदोळ्कूडिदनुमप्पनेकें दोडे चारित्रमोहनीयापेक्षेयिनातंगौदयिकभावमप्पुदरिदं ।

सद्दहणासद्दहणं जस्स य जीवस्स होइ तच्चेसु ।
विरयाविरयेण समो सम्मामिच्छोत्ति णायव्वो ॥६५५॥

श्रद्धानाश्रद्धानं यस्य च जीवस्य भवति तत्त्वेषु । विरताविरतेन समः सम्यग्मिथ्यादृष्टिरिति ज्ञातव्यः ।

जीवादिपदार्थंगळोळु आवनोर्व्वंजीवंगे श्रद्धानमुमश्रद्धानमुमोम्मों दलोळे संयतासंयतंगं तु संयममुमसंयममुमोम्मों दलोळेयक्कुमंते । मिश्रनोळु तत्वार्थश्रद्धानमुमतत्वार्थश्रद्धानमुमोम्मों दलोळेयक्कुमप्पुदरिंना जीवं सम्यग्मिथ्यादृष्टियें दितरियल्पडुवं ।

मिच्छाइट्ठी जीवो उवइट्ठं पवयणं ण सद्दहदि ।
सद्दहदि असब्भावं उवइट्ठं वा अणुवइट्ठं ॥६५६॥

मिथ्यादृष्टिर्जीवः उपदिष्टं प्रवचनं न श्रद्दधाति । श्रद्दधात्यसद्भावमुपदिष्टं वाऽनुपदिष्टं ॥

मिथ्यादृष्टिजीवं उपदेशं गेय्यल्पट्टाप्तागमपदार्थंगळं नंबुवनल्लं । उपदेशं गेयल्पट्टुमनुपदेशं गेय्यल्पडदुमनसद्भावमनताप्तागमपदार्थंगळं नंबुवं ।

यो जीवः सम्यक्त्वात्पतितो मिथ्यात्वं यावन्न प्राप्तः तावत् सासादन इति ज्ञेयं स च दर्शनमोहनीयस्यैवापेक्षया पारिणामिकभावेन सहितः, चारित्रमोहनीयापेक्षया तस्यौदयिकभावसद्भावात् ॥६५४॥

जीवादिपदार्थेषु यस्य जीवस्य श्रद्धानमश्रद्धानं च युगपदेव देशसंयमस्य संयमासंयमवद्भवति स जीवः सम्यग्मिथ्यादृष्टिरिति ज्ञातव्यः ॥६५५॥

मिथ्यादृष्टिर्जीवः उपदिष्टान् आप्तागमपदार्थान् न श्रद्दधाति । उपदिष्टान् अनुपदिष्टांश्च असद्भावान् अनाप्तागमपदार्थान् श्रद्दधाति ॥६५६॥ अथ सम्यक्त्वमार्गणायां जीवसंख्यां गाथात्रयेणाह—

जो जीव सम्यक्त्वसे गिरकर जबतक मिथ्यात्वको प्राप्त नहीं होता तबतक उसे सासादन जानना। वह दर्शन मोहनीयकी अपेक्षा ही पारिणामिक भाववाला होता है। चारित्र मोहनीयकी अपेक्षा तो अनन्तानुबन्धीका उदय होनेसे औदयिक भाववाला है॥६५४॥

जैसे देशसंयमीके एक साथ संयम और असंयम दोनों होते हैं वैसे ही जिस जीवके जीवादि पदार्थोंमें श्रद्धान और अश्रद्धान दोनों ही एक साथ होते हैं वह जीव सम्यग्मिथ्यादृष्टि जानना ॥६५५॥

मिथ्यादृष्टि जीव जिन भगवान्‌के द्वारा कहे गये आप्त, आगम और पदार्थोंका श्रद्धान नहीं करता। किन्तु कुदेवोंके द्वारा उपदिष्ट और अनुपदिष्ट असमीचीन मिथ्या आप्त, मिथ्या आगम और मिथ्या पदार्थोंका श्रद्धान करता है ॥६५६॥

पल्लासंखेज्जदिमा सासणमिच्छा य संखगुणिदा हु ।
मिस्सा तेहि विहीणो संसारी वामपरिमाणं ॥६५९॥

पल्यासंख्यातेकभागाः सासादनमिथ्यादृष्टयश्च संख्यातगुणिताः खलु । मिश्राः तैर्विहीनः संसारी वामपरिमाणं ॥

पल्यासंख्यातेकभागप्रमितरु सासादनमिथ्यारुचिगळप्परु प/ a a ४ मा सासादनरं नोडलु सम्यग्मिथ्यादृष्टिगळु संख्यातगुणितमात्ररप्पुरु प/ a a स्फुटमागि ई राशिपंचकविहीनसंसारिराशि-वामरुगळ प्रमाणमक्कुं । प १३– ।

नवपदार्थंगळ प्रमाणं पेळल्पडुगुं । जीवंगळु । १६ अजीवंगळु पुद्गलंगळु सर्व्वजीवराशियं नोडलनंतगुणमक्कुं । १६ ख । धर्म्मद्रव्यमोंदु १ । अधर्म्मद्रव्यमोंदु १ । आकाशद्रव्यमोंदु १ । काल-द्रव्यं जगच्छ्रेणिघनप्रमितमक्कु ≡ मितजीवंगळुं साधिकपुद्गलराशिप्रमितमक्कुं ३ ≡ १६ ख पुण्यजीवं-गळु असंयतरुं देशसंयतरुं कूडि प्रमत्ताद्युपरितनगुणस्थानवर्त्तिगळं संख्यातविवं साधिकरप्परु प a a ४ / a a a ४ अजीवपुण्यं द्व्यर्द्धगुणहानिसंख्यातेकभागमक्कु स a –१२·१ / १ पापजीवंगळु साधिकसिद्धराशिविहीन संसारिराशिप्रमाणमप्परु १३ । अजीवपापं द्व्यर्द्धगुणहानिसंख्यातबहु-

पल्यासंख्यातैकभागमात्राः सासादनमिथ्यादृष्टयः प/ a a ४ तेभ्यः सम्यग्मिथ्यादृष्टयः संख्यातगुणाः प/ a a स्फुटं एतद्राशिपञ्चकोनसंसारराशिर्वामपरिमाणं भवति वा १३—नवपदार्थप्रमाणमुच्यते—

जीवाः १६ अजीवेषु पुद्गलाः सर्वजीवराशितोऽनन्तगुणाः १६ ख । धर्मद्रव्यमेकं । अधर्मद्रव्यमेकं । आकाशद्रव्यमेकं । कालद्रव्यं जगच्छ्रेणिघनमात्रं । ≡ । एवमजीवपदार्थो मिलित्वा साधिकपुद्गलराशिमात्रः ३ ≡ १६ ख । पुण्यजीवा असंयतदेशसंयतान्मेलयित्वा तत्र प्रमत्तादीना संख्याते युते एतावन्तः प a a ४ / a a a ४ अजीव-पुण्यं द्व्यर्धगुणहानिसंख्यातैकभागः स a १२–१ / १ पापजीवाः साधिकपुण्यजीवसिद्धराशिविहीनसंसारिराशिः १३– ।

पल्यके असंख्यातवें भाग सासादन होते हैं जिनकी रुचि मिथ्या होती है। उनसे सम्यग्मिथ्यादृष्टि संख्यातगुणे हैं। संसारी जीवोंकी राशिमेंसे क्षायिकसम्यग्दृष्टि, वेदक-सम्यग्दृष्टि, उपशमसम्यग्दृष्टि, सासादन और मिश्र इन पाँचकी राशियोंको घटानेपर मिथ्या-दृष्टियोंका परिमाण होता है। अब नौ पदार्थोंका परिमाण कहते हैं—जीव अनन्त हैं। अजीवोंमें पुद्गल समस्त जीवराशिसे अनन्तगुणा है। धर्मद्रव्य एक है। अधर्मद्रव्य एक है। आकाशद्रव्य एक है। कालद्रव्य जगतश्रेणिके घन अर्थात् लोकप्रमाण है। इस प्रकार अजीव पदार्थ सब मिलकर साधिक पुद्गलराशिप्रमाण है। असंयत और देशसंयतोंके प्रमाणको प्रमत्त आदिके प्रमाणमें मिलानेपर पुण्य जीवोंका प्रमाण होता है। डेढ़ गुण-हानि प्रमाण

इंतु भगवदर्हत्परमेश्वर चारुचरणारविंदद्वंद्ववंदनानंदितपुण्यपुंजायमान श्रीमद्रायराजगुरुमंडलाचार्यमहावादवादीश्वररायवादिपितामहसकलविद्वज्जनचक्रवर्त्ति श्रीमदभयसूरिसिद्धांतचक्रवर्त्ति श्रीपादपंकजरजोरंजितललाटपट्टं श्रीमत्केशवण्णविरचितगोम्मटसारकर्णाटवृत्तिजीवतत्त्वप्रदीपिकेयोळ् जीवकांडविंशतिप्ररूपणंगळोळु सप्तदशं सम्यक्त्वमार्गणामहाधिकारं व्याख्यातमाय्तु ॥

इत्याचार्यश्रीनेमिचन्द्रसिद्धान्तचक्रवर्तिविरचितायां गोम्मटसारापरनामपञ्चसंग्रहवृत्तौ जीवतत्त्वप्रदीपिकाख्यायां जीवकाण्डे विंशतिप्ररूपणासु सम्यक्त्वमार्गणाप्ररूपणानाम सप्तदशोऽधिकारः ॥१७॥

इस प्रकार आचार्य श्री नेमिचन्द्र विरचित गोम्मटसार अपर नाम पंचसंग्रहकी भगवान् अर्हन्त देव परमेश्वरके सुन्दर चरणकमलोंकी वन्दनासे प्राप्त पुण्यके पुंजस्वरूप राजगुरु मण्डलाचार्य महावादी श्री अभयनन्दी सिद्धान्त चक्रवर्तीके चरणकमलोंकी धूलिसे शोभित ललाटवाले श्री केशववर्णीके द्वारा रचित गोम्मटसार कर्णाटवृत्ति जीवतत्त्व प्रदीपिकाकी अनुसारिणी संस्कृतटीका तथा उसकी अनुसारिणी पं. टोडरमलरचित सम्यग्ज्ञानचन्द्रिका नामक भाषाटीकाकी अनुसारिणी हिन्दी भाषा टीकामें जीवकाण्डकी बीस प्ररूपणाओंमें-से सम्यक्त्वमार्गणा प्ररूपणा नामक सत्रहवाँ अधिकार सम्पूर्ण हुआ ॥१७॥

आहारमारणंतियदुगं पि णियमेण एगदिसिगं तु।
दसदिसिगदा हु सेसा पंचसमुग्घादया होंति ॥६६९॥

आहारमारणान्तिकसमुद्घातद्वयमेकदिशिकं तु। दशदिग्गताः खलु शेषाः पंचसमुद्घाता भवंति ॥

आहारकसमुद्घातमुं मारणांतिकसमुद्घातमुमेंबेरडुं समुद्घातंगळेकदिशिगंगळप्पुवु। शेषवेदनासमुद्घातादिपंचसमुद्घातंगळु दशदिग्गतंगळप्पुवु।

आहारानाहारकालमं पेळ्दपं :—

अंगुलअसंखभागो कालो आहारयस्स उक्कस्सो।
कम्मम्मि अणाहारो उक्कस्सं तिण्णि समया हु ॥६७०॥

अंगुलासंख्यातभागः काल आहारस्योत्कृष्टः। कार्म्मणे अनाहारः उत्कृष्टास्त्रयः समयाः खलु ॥

सूच्यंगुलासंख्यातैकभागमात्रकालमाहारकनुत्कृष्टमक्कुं। त्रिसमयोनोच्छ्वासाष्टादशैकभागमात्रकालं जघन्यमक्कुं। कार्म्मणकायदोळु अनाहारकनुत्कृष्टकालं मूरु समयंगळप्पुवु। जघन्यकालमेकसमयमक्कु आहार अनाहार

उ सू २ जघ (१—३ / १८) उत्कृष्ट सम ३ ज— स १

अनंतरमाहारमार्गणेयोळु जीवसंख्येयं पेळ्दपं।

कम्मइयकायजोगी होदि अणाहारयाण परिमाणं।
तव्विरहिदसंसारी सव्वो आहारपरिमाणं ॥६७१॥

कार्म्मणकाययोगिनो भवत्यनाहारकाणां परिमाणं। तद्विरहितसंसारी सर्व्वः आहारकपरिमाणं ॥

आहारमारणान्तिकसमुद्घातद्वयमेव एकदिग्गतं भवति तु— पुनः शेषाः पंचसमुद्घाताः दशदिग्गता भवन्ति ॥६६९॥ आहारानाहारकालमाह—

आहारकालः उत्कृष्टः सूच्यङ्गुलासंख्यातैकभागः २/a। जघन्यः त्रिसमयोनोच्छ्वासाष्टादशैकभागः। अनाहारकालः कार्मणकाये उत्कृष्टः त्रिसमयः। जघन्यः एकसमयः। खलु—स्फुटं ॥६७०॥ अथात्र जीवसंख्यामाह—

आहारक और मारणान्तिक ये दो समुद्घात ही एक दिशामें गमन करते हैं। किन्तु शेष पाँच समुद्घात दसों दिशाओंमें गमन करते हैं ॥६६९॥

आगे आहार और अनाहारका काल कहते हैं—

आहारका उत्कृष्टकाल सूच्यंगुलके असंख्यातवें भाग है। जघन्यकाल तीन समय कम उच्छ्वासका अठारहवाँ भाग है। अनाहारका काल कार्मणकायमें उत्कृष्ट तीन समय और जघन्य एक समय है ॥६७०॥

इनमें जीवोंकी संख्या कहते हैं—

आहारमारणंतियदुगं पि णियमेण एगदिसिगं तु ।
दसदिसिगदा हु सेसा पंचसमुग्घादया होंति ॥६६९॥

आहारमारणांतिकसमुद्घातद्वयमेकदिशिकं तु । दशदिग्गताः खलु शेषाः पंचसमुद्घाता भवंति ॥

आहारकसमुद्घातमुं मारणांतिकसमुद्घातमुमें बेरडुं समुद्घातंगळेकदिशिगतंगळप्पुवु । शेष-वेदनादिसमुद्घातंगळु दशदिग्गतंगळप्पुवु ।

आहारानाहारकालमं पेळदपं :—

अंगुलअसंखभागो कालो आहारयस्स उक्कस्सो ।
कम्मम्मि अणाहारो उक्कस्सं तिण्णि समया हु ॥६७०॥

अंगुलासंख्यातभागः काल आहारकस्योत्कृष्टः । कार्मणे अनाहारः उत्कृष्टस्त्रयः समयाः खलु ॥

सूच्यंगुलासंख्यातैकभागमात्रमाहारकोत्कृष्टकालमक्कुं । [illegible]-मात्रकालं जघन्यमक्कुं । कार्मणकायदोळु अनाहारकोत्कृष्टकालं मूरु समयंगळप्पुवु । जघन्यकाल-मेकसमयमक्कु आहार अनाहार

[illegible]

अनंतरमनाहारकाहारकजीवसंख्येयं पेळदपं :—

कम्मइयकायजोगी होदि अणाहारयाण परिमाणं ।
तव्विरहिदसंसारी सव्वो आहारपरिमाणं ॥६७१॥

कार्मणकाययोगिगळु अनाहारकर परिमाणं । तद्विरहितसंसारिगळु सर्व्वरुं आहारक-परिमाणं ॥

[illegible]

आहारक और मारणान्तिक ये दो समुद्घात [illegible] एक दिशा में गमन करते हैं । किन्तु शेष पाँच समुद्घात दसों दिशाओंमें गमन करते हैं ॥६६९॥

आगे आहार और अनाहारका काल कहते हैं—

[illegible]

इंतु श्रीमदर्हत्परमेश्वरचारुचरणारविंदद्वंद्ववंदनानंदितपुण्यपुंजायमान श्रीमद्रायराजगुरुमंडलाचार्य्यमहावादवादीश्वररायवादिपितामहसकलविद्वज्जनचक्रवर्त्ति श्रीमदभयसूरिसिद्धांतचक्रवर्त्तिश्रीपादपंकजरजोरंजितललाटपट्टं श्रीमत्केशवण्णविरचितमप्प गोम्मटसारकर्णाटकवृत्तिजीवतत्वप्रदीपिकेयोळु जीवकांडविंशति प्ररूपणंगळोळु एकान्नविंशति माहारमार्गणाधिकारं निरूपितमाय्तु ।

इत्याचार्यश्रीनेमिचन्द्रसिद्धान्तचक्रवर्तिविरचितायां गोम्मटसारापरनामपञ्चसंग्रहवृत्तौ तत्त्वप्रदीपिकाख्यायां जीवकाण्डे विंशतिप्ररूपणासु आहारमार्गणाप्ररूपणानामैकोनविंशोऽधिकारः ॥१९॥

इस प्रकार आचार्य श्री नेमिचन्द्र विरचित गोम्मटसार अपर नाम पंचसंग्रहकी भगवान् अर्हन्त देव परमेश्वरके सुन्दर चरणकमलोंकी वन्दनासे प्राप्त पुण्यके पुंजस्वरूप राजगुरु मण्डलाचार्य महावादी श्री अभयनन्दी सिद्धान्त चक्रवर्तीके चरणकमलोंकी धूलिसे शोभित ललाटवाले श्री केशववर्णीके द्वारा रचित गोम्मटसार कर्णाटवृत्ति जीवतत्त्व प्रदीपिकाकी अनुसारिणी संस्कृतटीका तथा उसकी अनुसारिणी पं. टोडरमलरचित सम्यग्ज्ञानचन्द्रिका नामक भाषाटीकाकी अनुसारिणी हिन्दी भाषा टीकामें जीवकाण्डकी बीस प्ररूपणाओंमें-से आहारमार्गणा प्ररूपणा नामक उन्नीसवाँ अधिकार सम्पूर्ण हुआ ॥१९॥

साकारोपयोगे द्रष्टव्यम्। अतो जीवाः सर्वेऽपि तल्लक्षणे ज्ञानदर्शनोपयोगलक्षणत्वेऽप्यनु- [illegible] इति अव्याप्त्यतिव्याप्त्यसम्भवदोषरहितं लक्षणं द्रष्टव्यम् ।

मदिसुदओहिमणेहि य सगसगविसये विसेसविण्णाणं ।

अंतोमुहुत्तकालो उवजोगो सो दु सायारो ॥६७४॥

मतिश्रुतावधिमनोभिश्च स्वकस्वकविषये विशेषविज्ञानमन्तर्मुहूर्तकाल उपयोगः स तु साकारः ॥

मतिश्रुतावधिमनःपर्ययज्ञानैः स्वकस्वकविषये विशेषविज्ञानमन्तर्मुहूर्तकालार्थग्रहणव्यापाररूपो [illegible] स तु साकारोपयोगो द्रष्टव्यः ।

इंदियमणोहिणा वा अत्थे अविसेसिदूण जं गहणं ।

अंतोमुहुत्तकालो उवजोगो सो अणायारो ॥६७५॥

इन्द्रियमनोऽवधिना वा अर्थे अविशेष्य यद्ग्रहणमन्तर्मुहूर्तकाल उपयोगः सोऽनाकारः ॥

चक्षुरिन्द्रियेण [illegible] अचक्षुर्दर्शनेन वा अवधिदर्शनेन वा [illegible] अविशेष्य [illegible] निर्विकल्पं यद्ग्रहणं [illegible] अनाकारोपयोगो द्रष्टव्यः ॥

अथ उपयोगाधिकारे जीवसंख्यां प्ररूपयति—

णाणुवजोगजुदाणं परिमाणं णाणमग्गणं व हवे ।

दंसणुवजोगियाणं दंसणमग्गण व उत्तकमो ॥६७६॥

ज्ञानोपयोगयुक्तानां परिमाणं ज्ञानमार्गणावद्भवेत् । दर्शनोपयोगिनां दर्शनमार्गणावदुक्तक्रमः ॥

[illegible] दर्शनं अनाकारोपयोगः । अतो जीवाः ज्ञानदर्शनोपयोगलक्षणा एव [illegible] ॥६७३॥

मतिश्रुतावधिमनःपर्ययैः स्वस्वविषये विशेषविज्ञानं अन्तर्मुहूर्तकालं अर्थग्रहणव्यापाररूपं उपयोगः, स तु साकारोपयोगो नाम ॥६७४॥

चक्षुर्दर्शनेन वा [illegible] अचक्षुर्दर्शनेन वा अवधिदर्शनेन वा [illegible] अविशेष्य [illegible] अनाकारोपयोगो नाम ॥६७५॥ अथात्र जीवसंख्यामाह—

दर्शन बिना साकार उपयोग है। चक्षुदर्शन, अचक्षुदर्शन, अवधिदर्शन और केवलदर्शन ये अनाकार उपयोग हैं। अतः जीव ज्ञानदर्शनोपयोग लक्षणवाले हैं। जीवके इस लक्षणमें अव्याप्ति, अतिव्याप्ति और असम्भव दोष नहीं है ॥६७३॥

मति, श्रुत, अवधि और मनःपर्ययज्ञानोंके द्वारा अपने-अपने विषयमें जो विशेष ज्ञान होता है। अन्तर्मुहूर्तकालको लिये हुए अर्थको ग्रहण करने रूप व्यापार जिसका लक्षण है वह उपयोग साकार उपयोग है ॥६७४॥

चक्षुदर्शन अथवा शेष इन्द्रिय और मनरूप अचक्षुदर्शन, अथवा अवधि दर्शनके द्वारा जीवादि पदार्थोंका विशेष न करके जो निर्विकल्प रूपसे ग्रहण होता है वह अनाकार उपयोग है। उसका काल भी अन्तर्मुहूर्त है ॥६७५॥

इनमें जीव संख्या कहते हैं—

---

१. °म व चं । मु.।

राशि शक्ति चक्षुर्द्दर्शनिगळु = २/४।८ व्यक्ति चक्षुर्द्दर्शनिजीवंगळु । प्र १ फ = ४/५ इ । २ लब्ध = २/४४/५

अचक्षुर्द्दर्शनिगळु १३— अवधिदर्शनिगळु प ० / ० ० केवलदर्शनिगळु ३–॥

इंतु भगवदर्हत्परमेश्वरचारुचरणारविंदद्वंद्ववंदनानंदितपुण्यपुंजायमानश्रीमद्रायराजगुरुभूमंडलाचार्य्यवर्य्यमहावादवादीश्वरराय वादिपितामहसकलविद्वज्जनचक्रवर्त्तिश्रीमदभयसूरिसिद्धांतचक्रवर्त्तिश्रीपादपंकजरजोरंजितललाटपट्टं श्रीमत्केशवण्णविरचितमप्प गोम्मटसारकर्णाटकवृत्ति जीवतत्व प्रदीपिकेयोळु विंशमुपयोगाधिकारं निगदितमाददु ॥

---

४ । फ = । इ च । चं । २ । इति त्रैराशिकलब्धमात्राः = २/४/० = व्यक्तिचक्षुर्दर्शनिनः प्र — ४ । फ = इ २/४/५ ।

इति त्रैराशिकलब्धमात्राः = २/४ ५ ४ – अचक्षुर्दर्शनिनः १३– अवधिदर्शनिनः प ० / ० ० केवलिदर्शनिनः सि ३ ॥६७६॥

इत्याचार्यश्रीनेमिचन्द्रसिद्धान्तचक्रवर्तिविरचितायां गोम्मटसारापरनामपञ्चसंग्रहवृत्तौ तत्त्वप्रदीपिकाख्यायां जीवकाण्डे विंशतिप्ररूपणासु उपयोगमार्गणाप्ररूपणा नाम विंशोऽधिकारः ॥२०॥

---

४८७ की टीकामें कहा है। अवधिदर्शनवालोंका परिमाण अवधिज्ञानियोंके समान और केवलदर्शनियोंका परिमाण केवलज्ञानियोंके समान जानना। एकेन्द्रियसे लेकर क्षीणकषाय गुणस्थान पर्यन्त अनन्तानन्त जीवराशि प्रमाण अचक्षुदर्शनी हैं ॥६७६॥

इस प्रकार आचार्य श्री नेमिचन्द्र विरचित गोम्मटसार अपर नाम पंचसंग्रहकी भगवान् अर्हन्त देव परमेश्वरके सुन्दर चरणकमलोंकी वन्दनासे प्राप्त पुण्यके पुंजस्वरूप राजगुरु मण्डलाचार्य महावादी श्री अभयनन्दी सिद्धान्तचक्रवर्तीके चरणकमलोंकी धूलिसे शोभित ललाटवाले श्री केशववर्णीके द्वारा रचित गोम्मटसार कर्णाटवृत्ति जीवतत्त्व प्रदीपिकाकी अनुसारिणी संस्कृतटीका तथा उसकी अनुसारिणी पं. टोडरमल रचित सम्यग्ज्ञानचन्द्रिका नामक भाषाटीकाकी अनुसारिणी हिन्दी भाषा टीकामें जीवकाण्डके अन्तर्गत बीस प्ररूपणाओंमें-से उपयोगमार्गणा प्ररूपणा नामक बीसवाँ अधिकार सम्पूर्ण हुआ ॥२०॥

चतुर्दशं गुणस्थानंगळिर्दु संभविसुगुं। देवगतियोळु नरकगतियोळेंतंते मिथ्यादृष्टिसासादनमिश्रासंयतगुणस्थानचतुष्टयं संभविसुगुं। इंद्रियमार्गणेयोळु पंचेंद्रियदोळु चतुर्दशगुणस्थानंगळिर्दु संभविसुगुं। कायमार्गणेयोळु त्रसकायदोळु चतुर्दशगुणस्थानंगळिर्दु संभविसुगुं। शेषेंद्रियकायंगळोळु प्रत्येकमोंदोंदु मिथ्यादृष्टिगुणस्थानमक्कुं।

	न	ति	म	दे	ए	द्वि	त्रि	च	पं	पृ	अ	ते	वा	वन	त्र
गुण	४	५	१४	४	१	१	१	१	१४	१	१	१	१	१	१४
जीव	२	१४	२	२	४	२	२	२	४	४	४	४	४	४	१०

नरकगतियोळु संज्ञिपंचेंद्रियपर्याप्तनिर्वृत्यपर्याप्तजीवसमासंगळेरडेयप्पुवु। तिर्यग्गतियोळु एकेंद्रियबादरसूक्ष्मद्वींद्रियत्रींद्रियचतुरिंद्रियासंज्ञिपंचेंद्रियसंज्ञिपंचेंद्रियपर्याप्तापर्याप्तजीवसमासंगळु पदिनाल्कुमप्पुवु। मनुष्यगतियोळु संज्ञिपंचेंद्रियपर्याप्तापर्याप्तजीवसमासंगळेरडेयप्पुवु। देवगतियोळु संज्ञिपंचेंद्रियपर्याप्तनिर्वृत्त्यपर्याप्त जीवसमासंगळेरडेयप्पुवु। इंद्रियमार्गणेयोळेकेंद्रियदोळु बादरसूक्ष्मैकेंद्रियपर्याप्तापर्याप्तजीवसमासंगळु नाल्कप्पुवु। द्वींद्रियदोळु द्वींद्रियपर्याप्तापर्याप्तजीवसमासंगळु येरडेयप्पुवु। त्रींद्रियदोळु त्रींद्रियपर्याप्तापर्याप्तजीवसमासंगळेरडेयप्पुवु। चतुरिंद्रियदोळु चतुरिंद्रियपर्याप्तापर्याप्तजीवसमासंगळेरडेयप्पुवु। पंचेंद्रियदोळु संज्ञ्यसंज्ञिपर्याप्तापर्याप्तजीवसमासंगळु नाल्कप्पुवु। कायमार्गणेयोळु पृथ्वीजलतेजोवायुवनस्पतिकायिकंगळोळु एकेंद्रियबादरसूक्ष्मपर्याप्तापर्याप्तजीवसमासंगळु प्रत्येकं नाल्कुनाल्कप्पुवु। त्रसकायिकंगळोळु द्वींद्रियत्रींद्रियचतुरिंद्रियासंज्ञिपंचेंद्रियसंज्ञिपंचेंद्रियपर्याप्तापर्याप्तजीवसमासंगळु पत्तु संभविसुववु

गतिमार्गणायां	इंद्रिय मार्गणायां	कायमार्गणायां
न । ति । म । दे ।	ए । द्वी । त्री । च । पं ।	पृ । अ । ते । वा । व । त्र ।
४ । ५ । १४ । ४ ।	१ । १ । १ । १ । १४ ।	१ । १ । १ । १ । १ । १४ ।
२ । १४ । २ । २ ।	४ । २ । २ । २ । ४ ।	४ । ४ । ४ । ४ । ४ । १०

पर्याप्तौ द्वौ। देवगतौ नारकवत् द्वौ। इन्द्रियमार्गणायां एकेन्द्रिये बादरसूक्ष्मैकेन्द्रियौ पर्याप्तापर्याप्ताविति चत्वारः। द्वीन्द्रिये त्रीन्द्रिये चतुरिन्द्रिये च स्वस्वपर्याप्तापर्याप्तौ द्वौ द्वौ। पञ्चेन्द्रिये संज्ञ्यसंज्ञिनौ पर्याप्तापर्याप्ताविति चत्वारः। कायमार्गणायां पृथ्व्यादिपञ्चसु एकेन्द्रियवत् चत्वारः चत्वारः, त्रसे शेषा दश ॥६७८॥

एक मिथ्यादृष्टिगुणस्थान होता है। जीवसमास नरकगतिमें संज्ञिपर्याप्त और निर्वृत्यपर्याप्त दो होते हैं। तिर्यंचगतिमें चौदह होते हैं। मनुष्यगतिमें संज्ञिपर्याप्त और अपर्याप्त दो होते हैं। देवगतिमें नरकगतिके समान दो होते हैं। इन्द्रियमार्गणामें एकेन्द्रियमें बादर और सूक्ष्म एकेन्द्रियके पर्याप्त और अपर्याप्त होनेसे चार होते हैं। दो-इन्द्रिय, तेइन्द्रिय और चतुरिन्द्रियमें अपने-अपने पर्याप्त और अपर्याप्त होनेसे दो-दो होते हैं। पंचेन्द्रियमें संज्ञी-असंज्ञीके पर्याप्त-अपर्याप्तके भेदसे चार हैं। कायमार्गणामें पृथिवीकायिक आदि पाँच कायोंमें एकेन्द्रियकी तरह चार-चार जीवसमास होते हैं। त्रसमें शेष दस जीवसमास होते हैं ॥६७८॥

नियमविदमवकुमा नाल्कुमपर्य्याप्तगुणस्थानंगळावुवें दोडे पेळ्दपं :—

मिच्छे सासणसम्मे पुंवेदयदे कवाडजोगिम्मि ।
णरतिरिये वि य दोण्णि वि होंतिचि जिणेहि णिद्दिट्ठं ॥६८१॥

मिथ्यादृष्टौ सासादनसम्यग्दृष्टौ पुंवेदासंयते कवाटयोगिनि नरतिरश्चि च द्वावपि भवत इति जिनैर्निर्दिष्टं ॥

मिथ्यादृष्टिगुणस्थानदोळं सासादनसम्यग्दृष्टिगुणस्थानदोळं पुंवेदोदयासंयतसम्यग्दृष्टिगुणस्थानदोळं कवाटसमुद्घातसयोगकेवलिगुणस्थानदोळमितु मनुष्यरोळं तिर्य्यंचरोळमा यरडुमौदारिककाययोगमुं तन्मिश्रकाययोगमुमप्पुवें दितु वीतरागसर्व्वज्ञरिंदं पेळल्पट्टुवु । मसमौदारिकमिश्रकाययोगदोळु एकेंद्रियबादरसूक्ष्मद्वित्रिचतुरिंद्रियासंज्ञिपंचेंद्रियसंज्ञिपंचेंद्रियापर्य्याप्तजीवसमाससप्तकमुं सयोगिकेवलियोळु कवाटसमुद्घातदोळु औदारिकमिश्रयोगमप्पुदुं कूडि जीवसमासाष्टकमक्कुं

औ	मिश्र
१३	४
७	८

वेगुव्वं पज्जत्ते इदरे खलु होदि तस्स मिस्सं तु ।
सुरणिरयचउट्ठाणे मिस्से ण हि मिस्सजोगो दु ॥६८२॥

वैगुर्व्वः पर्याप्ते इतरस्मिन् खलु भवति तस्य मिश्रस्तु । सुरनारकचतुःस्थाने मिश्रे न हि मिश्रयोगस्तु ॥

वैक्रियिककाययोग पंचेंद्रियपर्य्याप्तदेवनारकमिथ्यादृष्टिसासादनमिश्रासंयतगुणस्थानचतुष्टयदोळक्कुं । तन्मिश्रयोगं देवनारकमिथ्यादृष्टिसासादनासंयतगुणस्थानत्रयदोळमक्कुं । वैक्रियिक-

---

तन्मिश्रयोगः अपर्याप्तचतुर्गुणस्थानेष्वेव नियमेन ॥६८०॥ तेषु केषु ? इति चेदाह—

मिथ्यादृष्टौ सासादने पुंवेदोदयासंयते कपाटसमुद्घातसयोगे, चैतेषु अपर्याप्तचतुर्गुणस्थानेषु स औदारिकमिश्रयोगः स्यादित्यर्थः । तौ योगौ द्वावपि नरतिरश्चोरेवेति सर्वज्ञैरुक्तम् । जीवसमासाः औदारिकयोगे पर्याप्ताः सप्त । तेन मिश्रयोगे अपर्याप्ताः सप्त । सयोगस्य चैकः एवमष्टौ ॥६८१॥

वैक्रियिककाययोगः पर्याप्तदेवनारकमिथ्यादृष्ट्यादिचतुर्गुणस्थानेषु भवति खलु स्फुटम् । तु—पुनः

चार गुणस्थानोंमें होता है ॥६८०॥

किन गुणस्थानोंमें होता है यह कहते हैं—

मिथ्यादृष्टिमें, सासादनमें, पुरुषवेदके उदय सहित असंयतमें और कपाट समुद्घात सहित सयोगकेवलीमें इन चार अपर्याप्त अवस्था सहित गुणस्थानोंमें औदारिकमिश्रयोग होता है। औदारिक और औदारिकमिश्र ये दोनों भी योग मनुष्य और तिर्यंचोंमें ही सर्वज्ञदेवने कहे हैं। औदारिक योगमें सात पर्याप्त जीवसमास होते हैं। अतः औदारिक मिश्र योगमें सात अपर्याप्त जीवसमास होते हैं और सयोगकेवलीके एक जीवसमास होता है इस तरह आठ जीवसमास होते हैं ॥६८१॥

वैक्रियिक काययोग पर्याप्त देव नारकियोंके मिथ्यादृष्टि आदि चार गुणस्थानोंमें होता है। वैक्रियिक मिश्रकाय योग मिश्रगुणस्थानमें तो नहीं होता, अतः देवनारकियोंके

स्थानचतुष्टयमुं एकेंद्रियबादरसूक्ष्मद्वित्रिचतुरिंद्रियासंज्ञिपंचेंद्रियसंज्ञिपंचेंद्रियजीवंगळु उत्तरभवशरीरग्रहणार्त्थं स्वस्वयोग्यचतुर्ग्गतिगळ्गे पोपुदं विग्रहगतियेंबुदा विग्रहगतियोळप्प अपर्य्याप्तजीवसमासिगळेंळुं प्रतरसमुद्घातलोकपूरणसमुद्घातसमयप्रवर्त्तिसयोगिभट्टारकन कार्म्मणकाययोगाऽपर्य्याप्तजीवसमासेगूडि कार्म्मणकाययोगदोळें दु जीवसमासेगळप्पुवु का ≈
गु ४
जी ८

थावरकायप्पहुडी संढो सेसा असण्णिआदी य।
अणियट्टिस्सय पढमो भागोत्ति जिणेहि णिद्दिट्ठं ॥६८५॥

स्थावरकायप्रभृति षंढः शेषाः असंज्ञ्यादयश्च। अनिवृत्तेः प्रथमभागपर्य्यंतं जिनैर्न्निर्द्दिष्टं॥

वेदमार्ग्गणेयोळु स्थावरकायदोळु मिथ्यादृष्टिप्रभृतियागि षंढवेदिगळनिवृत्तिकरणगुणस्थानपंचभागंगळोळु प्रथमसवेदभागपर्य्यंतमो भत्तुं गुणस्थानं गळोळप्पवु। अदु कारणमागि नपुंसकवेददोळु गुणस्थाननवकमुं एकेंद्रियबादरसूक्ष्मद्वित्रिचतुःपंचेंद्रियसंज्ञ्यसंज्ञिपर्य्याप्तजीवसमासेगळु पदिनाल्कुमप्पुवु। शेषस्त्रीवेदिगळुं पुंवेदिगळुं संज्ञ्यसंज्ञिमिथ्यादृष्टिगुणस्थानं मोदलोंडऽनिवृत्तिकरणगुणस्थानद तंतम्म सवेदभागपर्य्यंतमो भत्तु गुणस्थानंगळोळप्पवु। अदु कारणमागि स्त्रीवेददोळं पुंवेददोळमोंभत्तुमभो भत्तु गुणस्थानंगळं। संज्ञ्यसंज्ञिपंचेंद्रियपर्य्याप्तापर्य्याप्तजीवसमासेगळु नाल्कु नाल्कुमप्पुवु न। स्त्री। पुं
९। ९। ९।
१४ ४ ४

थावरकायप्पहुडी अणियट्टीबितिचउत्थभागोत्ति।
कोहतियं लोहो पुण सुहुमसरागोत्ति विण्णेयो ॥६८६॥

स्थावरकायप्रभृत्यनिवृत्तिद्वित्रिचतुर्थभागपर्य्यंतं। क्रोधत्रयं भवति लोभः पुनः सूक्ष्मसरागपर्य्यंतं विज्ञेयः॥

पूरणकाले च भवति तेन तत्र गुणस्थानानि जीवसमासाश्च यद्वत् चत्वारि अष्टौ भवन्ति ॥६८४॥

वेदमार्गणायां षण्ढवेदः स्थावरकायमिथ्यादृष्ट्याद्यनिवृत्तिकरणप्रथमसवेदभागपर्यन्तं भवति तेन तत्र गुणस्थानानि नव। जीवसमासाश्चतुर्दश। शेषस्त्रीपुंवेदौ संज्ञ्यसंज्ञिमिथ्यादृष्ट्याद्यनिवृत्तिकरणस्वस्वसवेदभागपर्यन्तं भवतः तेन तयोर्गुणस्थानानि नव नव। जीवसमासाः संज्ञ्यसंज्ञिनौ पर्याप्तापर्याप्ताविति चत्वारः इति जिनैरुक्तम् ॥६८५॥

कालमें होता है। इससे उसमें गुणस्थान और जीवसमास उसीकी तरह क्रमसे चार और आठ होते हैं ॥६८४॥

वेदमार्गणामें नपुंसकवेद स्थावरकायसम्बन्धी मिथ्यादृष्टिसे लेकर अनिवृत्तिकरणके प्रथम सवेदभागपर्यन्त होता है। अतः उसमें नौ गुणस्थान होते हैं। जीवसमास चौदह होते हैं। शेष स्त्रीवेद और पुरुषवेद संज्ञी-असंज्ञी मिथ्यादृष्टिसे लेकर अनिवृत्तिकरणके अपने-अपने सवेद भागपर्यन्त होते हैं। इससे उनमें नौ-नौ गुणस्थान होते हैं। तथा जीवसमास संज्ञी, असंज्ञी, पर्याप्त, अपर्याप्त चार होते हैं ऐसा जिनदेवने कहा है ॥६८५॥

सण्णाणतियं अविरदसम्मादी छट्ठगादि मणपज्जो ।
खीणकसायं जाव दु केवलणाणं जिणे सिद्धे ॥६८८॥

सज्ज्ञानत्रिकमसंयतसम्यग्दृष्ट्यादि षष्ठकादि मनःपर्य्यायः क्षीणकषायं यावत् केवलज्ञानं जिनेसिद्धे ॥

मतिश्रुतावधि सम्यग्ज्ञानत्रितयमसंयतसम्यग्दृष्ट्यादिक्षीणकषायगुणस्थानपर्य्यंतं मों भत्तु गुणस्थानंगळोळप्पुवु। संज्ञिपंचेंद्रियपर्य्याप्ताऽपर्य्याप्तजीवसमासेगळेरडेरडप्पुवु। मनःपर्य्यायज्ञानं षष्ठगुणस्थानवर्त्ति प्रमत्तसंयतनादियागि क्षीणकषायपर्य्यंतमेळु गुणस्थानदोळप्पुवु। संज्ञिपंचेंद्रियपर्य्याप्तजीवसमासमो वेयक्कुं। केवलज्ञानं सयोगिकेवलियोळमयोगिकेवलियोळं सिद्धरोळमक्कुमल्लि संज्ञिपंचेंद्रियपर्य्याप्तजीवसमासमुं समुद्घातजिननल्लि औदारिकमिश्रमुं कार्म्मणकाययोगमुमुळ्ळवरिंदमपर्य्याप्तजीवसमासमुं कूडि जीवसमासद्वयं संभविसुगुं—

कु	कु	वि	म	श्रु	अ	म	के
२	२	२	९	९	९	७	२
१४	१४	१	२	२	२	१	२

अयदोत्ति हु अविरमणं देसे देसो पमत्तइदरे य ।
परिहारो सामाइयच्छेदो छट्ठादि थूलोत्ति ॥६८९॥

असंयतपर्य्यंतमविरमणं देशे देशः प्रमत्ते इतरस्मिन्नुभय। परिहारः सामायिकच्छेदोपस्थापनौ षष्ठादिस्थूलपर्य्यंतं ॥

सुहुमो सुहुमकसाए संते खीणे जिणे जहक्खादं ।
संजमसग्गणभेदा सिद्धे णत्थित्ति णिद्दिट्ठं ॥६९०॥

सूक्ष्मः सूक्ष्मकषाये शांते क्षीणे जिने यथाख्यातः। संयममार्ग्गणाभेदाः सिद्धे न संति इति निर्दिष्टं ॥

संयममार्ग्गणेयोळु मिथ्यादृष्टिगुणस्थानं मोदल्गो डसंयतसम्यग्दृष्टिगुणस्थानपर्य्यंतं नाल्कुं गुणस्थानंगळोळविरमणमक्कुमल्लि पदिनाल्कुं जीवसमासंगळुमप्पुवु। देशसंयतगुणस्थानदोळु देश-

मत्यादिसम्यग्ज्ञानत्रयं असंयतादिक्षीणकषायान्तं तेन तत्र गुणस्थानानि नव। जीवसमासौ संज्ञिपर्याप्तापर्याप्तौ द्वौ। मनःपर्ययज्ञानं षष्ठादिक्षीणकषायान्तं तेन तत्र गुणस्थानानि सप्त जीवसमासः संज्ञिपर्याप्त एकैकः। केवलज्ञानं सयोगायोगयोः सिद्धे च। तत्र जीवसमासौ संज्ञिपर्याप्तसयोगापर्याप्तौ द्वौ ॥६८८॥

संयममार्गणाया अविरमणं मिथ्यादृष्ट्याद्यसंयतान्तचतुर्गुणस्थानेषु। तत्र जीवसमासाश्चतुर्दश। देशसंयमः

मति आदि तीन सम्यग्ज्ञान असंयतसे लेकर क्षीणकषाय गुणस्थानपर्यन्त होते हैं इससे उनमें नौ गुणस्थान होते हैं। जीवसमास संज्ञिपर्याप्त अपर्याप्त दो होते हैं। मनःपर्ययज्ञान छठे गुणस्थानसे क्षीणकषाय पर्यन्त होता है अतः उसमें सात गुणस्थान होते हैं और जीवसमास एक संज्ञिपर्याप्त ही होता है। केवलज्ञान सयोगी, अयोगी और सिद्धोंमें होता है। उसमें संज्ञी पर्याप्त तथा समुद्घातगत सयोगीकी अपेक्षा संज्ञी अपर्याप्त ये दो जीवसमास होते हैं ॥६८८॥

संयममार्गणामें असंयम मिथ्यादृष्टिसे लेकर असंयतपर्यन्त चार गुणस्थानोंमें होता

दर्शनमार्गणेयोळु चक्षुर्द्दर्शनं चतुरिंद्रियमिथ्यादृष्टि मोदल्गोंडु क्षीणकषायगुणस्थानपर्य्यंतं पन्नेरडु गुणस्थानंगळोळप्पुवल्लि चतुरिंद्रियसंज्ञिपंचेंद्रियासंज्ञिपंचेंद्रियपर्य्याप्तापर्य्याप्तजीवसमासेगळारप्पुवु। अचक्षुर्द्दर्शनं स्थावरकायमिथ्यादृष्टिगुणस्थानमादियागि क्षीणकषायगुणस्थानपर्य्यंतं पंनेरडुं गुणस्थानंगळोळप्पुवल्लि पदिनाल्कुं जीवसमासेगळप्पुवु। अवधिदर्शनमसंयतसम्यग्दृष्टि-गुणस्थानमादियागि क्षीणकषायगुणस्थानपर्य्यंतमोंभत्तु गुणस्थानंगळोळप्पुवल्लि संज्ञिपंचेंद्रिय पर्य्याप्तापर्याप्तजीवसमासेगळेरडेयप्पुवु। केवलदर्शनं सयोगिकेवलिययोगिकेवलिगळेंबेरडुं गुण-स्थानंगळोळप्पुवल्लि संज्ञि पंचेंद्रियपर्य्याप्तजीवसमासेयुं समुद्घातकेवलिय अपर्य्याप्तजीवसमासमुमितेरडु जीवसमासेगळप्पुवु—

च। अ। अ। के।
१२। १२। ९। २।
६। १४। २। २।

गुणस्थानातीतरप्प सिद्धरोळं केवलदर्शनमक्कुं॥

थावरकायप्पहुडी अविरदसम्मोत्ति असुहतियलेस्सा।
सण्णीदो अपमत्तो जाव दु सुहतिण्णिलेस्साओ॥६९२॥

स्थावरकायप्रभृत्यविरतसम्यग्दृष्टिपर्य्यंतमशुभत्रयलेश्याः। संज्ञितोऽप्रमत्तं यावत् शुभत्रयलेश्याः॥

लेश्यामार्गणेयोळु अशुभत्रयलेश्येगळु स्थावरकायमिथ्यादृष्टिगुणस्थानमादियागि असंयत-सम्यग्दृष्टिगुणस्थानपर्य्यंतं नाल्कुं गुणस्थानंगळोळु संभविसुववल्लि एकेंद्रियबादरसूक्ष्मद्वित्रिचतुः-पंचेंद्रियसंज्ञ्यसंज्ञिपर्य्याप्तापर्य्याप्तभेदविभिन्नजीवसमासेगळु पदिनाल्कुमप्पुवु। तेजःपद्मलेश्येगळु संज्ञिमिथ्यादृष्टिगुणस्थानमादियागि अप्रमत्तगुणस्थानपर्य्यंतमेळं गुणस्थानंगळोळप्पुवल्लि संज्ञि-पर्य्याप्तापर्य्याप्तजीवसमासेगळेरडेरडप्पुवु।

दर्शनमार्गणायां चक्षुर्दर्शनं चतुरिन्द्रियमिथ्यादृष्ट्यादिक्षीणकषायान्तं। तत्र जीवसमासाः चतुरिन्द्रिय-संज्ञ्यसंज्ञिपर्याप्तापर्याप्ताः षट्। अचक्षुर्दर्शनं स्थावरकायमिथ्यादृष्ट्यादिक्षीणकषायान्तं तत्र जीवसमासाश्चतुर्दश। अवधिदर्शनं असंयतादिक्षीणकषायान्तं तत्र जीवसमासौ संज्ञिपर्याप्तापर्याप्तौ। केवलदर्शनं सयोगायोगगुण-स्थानयोः तत्र जीवसमासौ केवलज्ञानोक्तौ द्वौ। सिद्धेऽपि केवलदर्शनं भवति।

लेश्यामार्गणायां अशुभलेश्यात्रयं स्थावरकायमिथ्यादृष्ट्याद्यसंयतान्तं तत्र जीवसमासाः चतुर्दश। तेजःपद्मलेश्ये संज्ञिमिथ्यादृष्ट्याद्यप्रमत्तान्तं तत्र जीवसमासौ संज्ञिपर्याप्तापर्याप्तौ॥६९२॥

दर्शनमार्गणामें चक्षुदर्शन चतुरिन्द्रिय मिथ्यादृष्टिसे लेकर क्षीणकषाय पर्यन्त होता है। उसमें जीवसमास चौइन्द्रिय, संज्ञी पंचेन्द्रिय, असंज्ञि पंचेन्द्रिय इनके पर्याप्त और अपर्याप्त के भेदसे छह होते हैं। अचक्षुदर्शन स्थावरकाय मिथ्यादृष्टिसे लेकर क्षीणकषाय गुणस्थान पर्यन्त होता है। उसमें जीवसमास चौदह होते हैं। अवधिदर्शन असंयतसे लेकर क्षीणकषाय गुणस्थानपर्यन्त होता है। उसमें जीवसमास संज्ञिपर्याप्त और अपर्याप्त होते हैं। केवलदर्शन सयोगी-अयोगी गुणस्थानोंमें होता है। उसमें दो जीवसमास होते हैं जो केवलज्ञानमें होते हैं। सिद्धोंमें भी केवलदर्शन होता है॥६९१॥

लेश्यामार्गणामें तीन अशुभ लेश्या स्थावरकाय मिथ्यादृष्टिसे लेकर असंयत गुणस्थान पर्यन्त होती हैं उनमें जीवसमास चौदह हैं। तेजोलेश्या और पद्मलेश्या संज्ञिमिथ्यादृष्टिसे लेकर अप्रमत्त गुणस्थान पर्यन्त होती हैं। उसमें जीवसमास संज्ञिपर्याप्त और संज्ञिअपर्याप्त होते हैं॥६९२॥

सम्यक्त्वमार्गणेयोळु मिथ्यादृष्टियुं सासादननुं मिश्रनुं तंतम्म गुणस्थानदोळेयक्कुमल्लि मिथ्यादृष्टियोळु पदिनाल्कु जीवसमासेगळप्पवु। सासादनोळु येकेंद्रियबादरापर्य्याप्त द्वींद्रियापर्य्याप्त त्रींद्रियापर्य्याप्तचतुरिंद्रियापर्य्याप्तं संज्ञिपंचेंद्रियपर्याप्तापर्याप्त संज्ञिपंचेंद्रियापर्य्याप्तजीवसमासेगळेळप्पुवु । द्वितीयोपशमसम्यक्त्वविराधकनप्प सासादननुमोळने बाचार्य्यापेक्षेयिदं संज्ञिपंचेंद्रियपर्य्याप्तजीवसमासेयुं देवापर्य्याप्तजीवसमासेयुमेरडप्पुवु । मिश्रनोळु संज्ञिपंचेंद्रियपर्य्याप्तजीवसमासेयो देयक्कुं । प्रथमोपशमसम्यक्त्वमु वेदकसम्यक्त्वमुमसंयतसम्यग्दृष्टियादियागप्रमत्तपर्य्यंतं नाल्कुं नाल्कुं गुणस्थानंगळोळप्पुवु । अल्लि प्रथमोपशमसम्यक्त्वदोळु मरणमिल्लप्पुदरिदं संज्ञिपर्य्याप्तपंचेंद्रियजीवसमासेयो देयक्कुं । वेदकसम्यक्त्वदोळु संज्ञिपंचेंद्रियपर्य्याप्तापर्याप्तजीवसमासेगळेरडप्पुवेकेंदोडे घर्म्मेय नारकापर्य्याप्तनुं भवनत्रयवर्ज्जितदेवापर्य्याप्तनुं भोगभूमिजमनुष्यतिर्य्यंचापर्य्याप्तनुं वेदकसम्यग्दृष्टियोळनप्पुदरिदं ।

द्वितीयोपशमसम्यक्त्वक्के पेळ्दपं ।

> बिदियुवसमसम्मत्तं अविरदसम्मादि संतमोहो त्ति ।
> खइगं सम्मं च तहा सिद्धोत्ति जिणेहि णिद्दिट्ठं ॥६९६॥

द्वितीयोपशमसम्यक्त्वमविरतसम्यग्दृष्ट्याद्युपशांतमोहगुणस्थानपर्य्यंतं क्षायिकसम्यक्त्वं च तथा सिद्धपर्य्यंत जिनैर्निर्दिष्टं ॥

सम्यक्त्वमार्गणायां मिथ्यादृष्टिः सासादनः मिश्रश्च स्वस्वगुणस्थाने एव भवति । तत्र मिथ्यादृष्टो जीवसमासाश्चतुर्दश । सासादने बादरैकद्वित्रिचतुरिन्द्रियसंज्ञ्यसंज्ञ्यपर्याप्तसंज्ञिपर्याप्ताः सप्त । द्वितीयोपशमसम्यक्त्वविराधकस्य सासादनत्वप्राप्तिपक्षे च संज्ञिपर्याप्तदेवापर्याप्तावपि द्वौ । मिश्रे संज्ञिपर्याप्तः । प्रथमोपशमवेदकसम्यक्त्वे द्वे असंयताद्यप्रमत्तान्ते स्तः । तत्र जीवसमासः प्रथमोपशमसम्यक्त्वे मरणाभावात् संज्ञिपर्याप्त एकः । वेदकसम्यक्त्वे संज्ञिपर्याप्तापर्याप्तौ द्वौ । घर्मानारकस्य भवनत्रयवर्जितदेवस्य भोगभूमिनरतिरश्चोश्च अपर्याप्तत्वेऽपि तत्संभवात् ॥६९५॥ द्वितीयोपशमसम्यक्त्वस्याह—

सम्यक्त्वमार्गणामें मिथ्यादृष्टि, सासादन, और मिश्र अपने-अपने गुणस्थानमें होते हैं। मिथ्यादृष्टिमें जीवसमास चौदह होते हैं। सासादनमें बादर एकेन्द्रिय, दोइन्द्रिय, तेइन्द्रिय, चौइन्द्रिय, असंज्ञिअपर्याप्त तथा संज्ञिपर्याप्तअपर्याप्त ये सात जीवसमास होते हैं। द्वितीयोपशम सम्यक्त्वकी विराधना करके सासादनको प्राप्त होनेके पक्षमें संज्ञिपर्याप्त और देवअपर्याप्त दो जीवसमास होते हैं। मिश्रगुणस्थानमें संज्ञिपर्याप्त जीवसमास होता है। प्रथमोपशम सम्यक्त्व और वेदकसम्यक्त्व असंयतसे अप्रमत्त गुणस्थान पर्यन्त होते हैं। प्रथमोपशम सम्यक्त्वमें मरणका अभाव होनेसे जीवसमास एक संज्ञिपर्याप्त ही है। वेदक सम्यक्त्वमें संज्ञिपर्याप्त, अपर्याप्त दो होते हैं। क्योंकि घर्मा नामक प्रथम नरकमें भवनत्रिकको छोड़कर देवोंमें और भोगभूमिया मनुष्य तथा तिर्यंचोंमें अपर्याप्त दशामें भी वेदक सम्यक्त्व होता है ॥६९५॥

द्वितीयोपशम सम्यक्त्वको कहते हैं—

१. मु. °सावपि द्वौ ।

दृष्टिगुणस्थानमों देयक्कुमल्लि संज्ञिजीवसंबंधिपर्य्याप्तापर्य्याप्तजीवसमासद्वयमुळियलुळिद द्वादश-जीवसमासेगळनितुमप्पुवु नियमदिदं

सं । अ
१२ । १ ।
२ । १२ ।

थावरकायप्पहुडो सजोगिचरिमोत्ति होदि आहारी ।
कम्मइय अणाहारी अजोगिसिद्धे वि णायव्वो ॥६९८॥

स्थावरकायप्रभृति सयोगिचरमपर्य्यंतं भवत्याहारो। कार्म्मणे अनाहारो अयोगिसिद्धेपि ज्ञातव्यः ॥

आहारमार्गणेयोळु स्थावरकायमिथ्यादृष्टियादियागि सयोगकेवलिपर्य्यंतं पदिमूरुं गुणस्थानंगळोळाहारिगळोळु आहारियक्कुमल्लि सर्व्वमुं जीवसमासेगळु पदिनाल्कुमप्पुवु। विग्रहगति-कार्म्मणकाययोगद मिथ्यादृष्टिसासादनसम्यग्दृष्टि असंयतसम्यग्दृष्टिगुणस्थानत्रयमुं प्रतरलोकपूरण-समुद्घातसयोगिगुणस्थानमुमयोगिगुणस्थानमुमितुगुणस्थानपंचकदोळमनाहारियक्कुमल्लि एकेंद्रिय-बादरसूक्ष्मापर्य्याप्तजीवसमासद्वयमुं द्वित्रिचतुरिंद्रियापर्य्याप्तजीवसमासत्रयमुं संज्ञिपंचेंद्रियपर्य्याप्ता-पर्य्याप्तद्वयमुमसंज्ञ्यपर्य्याप्तजीवसमासेयुमितु जीवसमासाष्टकमक्कुं

आ । अ
१३ । ५
१४ । ८

अनंतरं गुणस्थानंगळोळु जीवसमासयं पेळ्दपरु :—

मिच्छे चोद्दसजीवा सासण अयदे पमत्तविरदे य ।
सण्णिदुगं सेसगुणे सण्णी पुण्णो दु खीणोत्ति ॥६९९॥

मिथ्यादृष्टौ चतुर्द्दशजीवाः सासादने अयते प्रमत्तविरते च। संज्ञिद्वयं शेषगुणे संज्ञिपूर्ण्णस्तु क्षीणकषायपर्य्यंतं ॥

द्वौ। तु—पुनः असंज्ञिजीवः स्थावरकायाद्यसंज्ञ्यन्तमिथ्यादृष्टिगुणस्थाने एव स्यान्नियमेन तत्र जीवसमासा द्वादश संज्ञिनो द्वयाभावात् ॥६९७॥

आहारमार्गणायां स्थावरकायमिथ्यादृष्ट्यादिसयोगान्तं आहारो भवति। तत्र जीवसमासाश्चतुर्दश मिथ्यादृष्टिसासादनासंयतसयोगानां कार्मणयोगावसरे अयोगिसिद्धयोश्च अनाहारो ज्ञातव्यः। तत्र जीवसमासा अपर्याप्ताः सप्त। अयोगस्य पंकः ॥६९८॥ अथ गुणस्थानेषु जीवसमासानाह—

असंज्ञी पंचेन्द्रिय पर्यन्त मिथ्यादृष्टि गुणस्थानमें ही होता है। नियमसे उसमें बारह जीव-समास होते हैं क्योंकि संज्ञी सम्बन्धी दो जीवसमास नहीं होते ॥६९७॥

आहारमार्गणामें स्थावरकाय मिथ्यादृष्टिसे लेकर सयोगकेवलिपर्यन्त आहारी होता है। उसमें जीवसमास चौदह होते हैं। मिथ्यादृष्टि, सासादन, असंयत, और सयोगकेवली के कार्मणयोगके समय तथा अयोगी और सिद्धोंमें अनाहारी जानना। उसमें जीवसमास अपर्याप्त सम्बन्धी सात होते हैं और अयोगीके एक पर्याप्त होता है ॥६९८॥

अब गुणस्थानोंमें जीवसमासोंको कहते हैं—

मिथ्यादृष्टिगुणस्थानं मोदल्गोंडु पदिनाल्कुं गुणस्थानंगळोळु पर्य्याप्तिगळुं प्राणंगळुं पृथक्कागि पेळल्पडवेकेंदोडे सुगमंगळप्पुवरिवमदेंतेंदोडे क्षीणकषायगुणस्थानपर्य्यंतं प्रत्येकमारु-पर्य्याप्तिगळं दशप्राणंगळुमप्पुवु। सयोगिकेवलिभट्टारकनोळु भावेंद्रियमिल्ल। द्रव्येंद्रियापेक्षेयिनारुं पर्य्याप्तिगळोळवु वाग्बलप्राणमुमुच्छ्वासनिश्वासप्राणमुमायुःप्राणमुं कायबलप्राणमेंबी नाल्कुं प्राणंगळप्पुवु। उळिदिंद्रिय प्राणंगळय्दुं मनोबलप्राणमुं संभविसवु। आ सयोगकेवलिगे वाग्योगं निल्तिरलु मूरु प्राणंगळप्पुवु। उच्छ्वासनिःश्वासमुपरतमागुत्तिरलुमेरडेप्राणंगळप्पुवु। अयोगि भट्टारकनोळु आयुष्यप्राणमोंदेयक्कुं। पूर्व्वसंचितनोकर्म्मकर्म्मसंचयं प्रतिसमयमेकैकनिषेकस्थिति-गळिसि चरमसमयदोळु किंचिन्न्यूनद्व्यर्द्धगुणहानिमात्रनोकर्म्मसंचयमुं कर्म्मसंचयमुमुबयिसि द्रव्यार्त्थिकनयापेक्षेयिंदमयोगिचरमसमयदोळु कर्म्ममुं नोकर्म्ममुं केट्टवु पर्य्यायार्त्थिकनयापेक्षेयिन-नंतरसमयदोळ्किडुत्तिरलु लोकाग्रनिवासि सिद्धपरमेष्ठियप्पनेंबुदु तात्पर्य्यं।

अनंतर गुणस्थानंगळोळु संज्ञेगळं पेळ्दपरु :—

छट्ठोत्ति पढमसण्णा सकज्ज सेसा य कारणावेक्खा।
पुव्वो पढमणियट्टी सुहुमोत्ति कमेण सेसाओ ॥७०२॥

षष्ठपर्य्यंतं प्रथमसंज्ञा सकार्य्या शेषाश्च कारणापेक्षाः। अपूर्व्वप्रथमानिवृत्ति सूक्ष्मपर्य्यंतं क्रमेण शेषाश्च ॥

मिथ्यादृष्टिगुणस्थानमादियागि प्रमत्तगुणस्थानपर्य्यंतमूरुं गुणस्थानंगळोळु सकार्य्यमप्पा-हारादिचतुःसंज्ञेगळुमप्पुवा षष्ठनल्लि आहारसंज्ञे व्युच्छित्तियाक्कु। उपरितनगुणस्थानदोळऽभावमं

चतुर्दशगुणस्थानेषु पर्याप्तयः प्राणाश्च पृथक् नोच्यन्ते सुगमत्वात्। तथाहि—क्षीणकषायपर्यन्तं षट्पर्याप्तयः दश प्राणाः। सयोगजिने भावेन्द्रियं न, द्रव्येन्द्रियापेक्षया षट्पर्याप्तयः वागुच्छ्वासनिश्वासायुः-कायप्राणाश्चत्वारि भवन्ति। शेषेन्द्रियमनःप्राणाः षट् न सन्ति। तत्रापि वाग्योगे विश्रान्ते त्रयः। पुनः उच्छ्वासनिश्वासे विश्रान्ते द्वौ। अयोगे आयुः प्राण एकः। प्राक्संचितनोकर्मकर्मसंचयः प्रतिसमयमेकैकनिषेकं गलन् किंचिदूनद्व्यर्धगुणहानिमात्रो द्रव्यार्थिकनयेन अयोगिचरमे विनश्यति पर्यायार्थिकनयेन अनन्तरसमये एवेति तात्पर्यम् ॥७०१॥ अथ गुणस्थानेषु संज्ञा आह—

मिथ्यादृष्ट्यादिप्रमत्तान्तं सकार्याः आहारादिचतस्रः संज्ञा भवन्ति। षष्ठगुणस्थाने आहारसंज्ञा

चौदह गुणस्थानोंमें पर्याप्ति और प्राण पृथक् नहीं कहे हैं क्योंकि सुगम है। यथा—क्षीणकषाय गुणस्थान पर्यन्त छह पर्याप्तियाँ और दस प्राण होते हैं। सयोगकेवलीमें भावेन्द्रिय नहीं है। उनके द्रव्येन्द्रियकी अपेक्षा छह पर्याप्तियाँ हैं और वचनबल, उच्छ्वास-निश्वास, आयु और कायबल ये चार प्राण होते हैं। शेष इन्द्रियाँ और मन ये छह प्राण नहीं हैं। उन चार प्राणोंमें-से भी वचनयोगके रुक जानेपर तीन रहते हैं, पुनः उच्छ्वास-निश्वासका निरोध होनेपर दो रहते हैं। अयोगकेवलीके एक आयुप्राण होता है। पूर्व संचित कर्म-नोकर्मका संचय प्रतिसमय एक-एक निषेक गलते-गलते किंचित् न्यून डेढ़ गुणहानि प्रमाण रहता है। सो द्रव्यार्थिक नयसे तो अयोगीके अन्तिम समयमें नष्ट होता है और पर्यायार्थिक नयसे अनन्तर समयमें नष्ट होता है ॥७०१॥

गुणस्थानोंमें संज्ञा कहते हैं—

मिथ्यादृष्टिसे लेकर प्रमत्त गुणस्थान पर्यन्त आहार आदि चारों संज्ञाएँ कार्यरूपमें

निकायमप्पुवु। मिश्रगुणस्थानदोळु पर्य्याप्तपंचेंद्रियत्रसकायिकमेयक्कुं। असंयतगुणस्थानदोळु पर्य्याप्तापर्य्याप्तसंज्ञिपंचेंद्रियत्रसकायिकमेयक्कुं। देशसंयतगुणस्थानदोळु पर्याप्तसंज्ञिपंचेंद्रियत्रसकायिकमेयक्कु। प्रमत्तगुणस्थानदोळु संज्ञिपंचेंद्रियपर्य्याप्तत्रसकायिकमक्कुमल्लियाहारकऋद्धिप्राप्तनोळु आहारकशरीरपंचेंद्रियपर्याप्तापर्य्याप्तत्रसकायिकमक्कु। अप्रमत्तगुणस्थानं मोदल्गोंडु क्षीणकषायगुणस्थानपर्य्यंतमाद गुणस्थानंगळोळु प्रत्येकं पर्य्याप्तपंचेंद्रियत्रसकायिकमेयक्कुं। सयोगकेवलिगुणस्थानदोळु पर्य्याप्तसंज्ञिपंचेंद्रियत्रसकायिकमक्कुमल्लि समुद्घातसयोगकेवलि भट्टारकनोळु औदारिकमिश्रयोगमुं कार्म्मणकाययोगमुमुळ्ळुदरिंदमपर्य्याप्तपंचेंद्रियत्रसकायिकमुमक्कुं। अयोगिकेवलिभट्टारकनोळुपर्य्याप्तपंचेंद्रियत्रसकायिकमयक्कुं—

मि	सा	मि	अ	दे	प्र	अ	अ	अ	सू	उ	क्षी	स	अ
६	६	१	२	१	१	१	१	१	२	१	१	१	१

पुद्गलविपाकिशरीरांगोपांगनामकर्म्मोदयंगळिदं मनोवचनकाययुक्तमप्प जीवक्के कर्म्मनोकर्म्मागमनकारणमप्पुदावुदो दु शक्ति जीवप्रदेशपरिस्पंदसंभूतमदु योगमें बुदक्कुमदु मनोवचनकायप्रवृत्तिभेददिं त्रिविधमक्कुमल्लि वीर्य्यांतरायनोइंद्रियावरणक्षयोपशमदिदमंगोपांगनामकर्म्मोदयदिदं मनःपर्य्याप्तियुक्तंगे मनोवर्ग्गणायातपुद्गलस्कंधंगळो अष्टच्छदारविंदाकारदिदं हृदयदोळु निर्म्माणनामकर्म्मोदयसंपादितद्रव्यमनः पद्मपत्रंगळोळु नोइंद्रियक्षयोपशमजीवप्रदेशप्रचयदोळु लब्ध्युपयोगलक्षणभावेंद्रियं मनमें बुदक्कुमा मनोव्यापारमं मनोयोगमें बुदा मनोयोगमुं सत्याद्यर्थ

पर्याप्ताः संज्ञित्रसकायः उभयश्चेति षड्जीवनिकायाः। मिश्रे संज्ञिपञ्चेन्द्रियत्रसकायपर्याप्त एव। असंयते उभयः, देशसंयते पर्याप्त एव। प्रमत्ते पर्याप्तः। आहारकर्धिस्तूभयः। अप्रमत्तादिक्षीणकषायान्तेषु पर्याप्त एव। सयोगे पर्याप्तः। ससमुद्घाते तूभयः। अयोगे पर्याप्त एव।

पुद्गलविपाकिशरीराङ्गोपाङ्गनामकर्मोदयैः मनोवचनकाययुक्तजीवस्य कर्मनोकर्मागमकारणा या शक्तिः तज्जनितजीवप्रदेशपरिस्पन्दनं वा योगः स च मनोवचनकायवृत्तिभेदात्त्रेधा। तत्र वीर्यान्तरायनोइन्द्रियावरणक्षयोपशमेन अङ्गोपाङ्गनामोदयेन च मनःपर्याप्तियुक्तजीवस्य मनोवर्गणायातपुद्गलस्कन्धानां अष्टच्छदारविन्दाकारेण हृदये निर्माणनामोदयसंपादितं द्रव्यमनः। तत्पत्राग्रेषु नोइन्द्रियावरणक्षयोपशमयुक्तजीवप्रदेशप्रचये

इन्द्रिय, चतुरिन्द्रिय और असंज्ञी पंचेन्द्रिय त्रसकाय अपर्याप्त होते हैं। संज्ञी पंचेन्द्रिय सकाय दोनों होते हैं। इस प्रकार इस गुणस्थानमें छहों जीवनिकाय होते हैं। मिश्रमें संज्ञी चेन्द्रिय त्रसकाय पर्याप्त ही है। असंयतमें दोनों हैं। देशसंयतमें पर्याप्त ही है। प्रमत्तमें प्ति है। आहारक ऋद्धि सहित दोनों है। अप्रमत्तसे क्षीणकषायपर्यन्त दोनों हैं। सयोगीमें प्ति है। समुद्घातमें दोनों हैं। अयोगीमें पर्याप्त ही हैं।

पुद्गलविपाकी शरीर और अंगोपांग नामकर्मके उदयके साथ मन-वचन-कायसे युक्त विके कर्म-नोकर्मके आनेमें कारण जो शक्ति है अथवा उसके द्वारा होनेवाला जो जीवके शोंका चलन है वह योग है। यह मन-वचन-कायकी प्रवृत्तिके भेदसे तीन प्रकारका है। न्तराय और नोइन्द्रियावरणके क्षयोपशमसे तथा अंगोपांगनाम कर्मके उदयसे मनःप्तिसे युक्त जीवके मनोवर्गणारूपसे आये हुए पुद्गल स्कन्धोंका आठ पाँखुड़ीके कमलके रसे हृदयमें निर्माणनाम कर्मके उदयसे रचा गया द्रव्यमन है। उन पाँखुड़ीके अग्रभागोंमें

गुणस्थानषट्कदोळु प्रत्येकमों दे शुक्ल लेश्येयक्कुमयोगिकेवलिभट्टारकगुणस्थानदोळु योगमिल्लप्पुदरिं लेश्येयुमिल्ल

मि	सा	मि	अ	दे	प्र	अ	अ	अ	सू	उ	क्षी	स	अ
६	६	६	६	३	३	३	१	१	१	१	१	१	०

सामग्री-विशेषंगळिंद सम्यग्दर्शनज्ञानचारित्रंगळिंदमनंतज्ञानानंतदर्शन अनंतवीर्य्यानंतसुखस्वरूपनागि परिणमिसल्के योग्यमप्पजीवं भव्यनें बनक्कुमदरविपरीतमभव्यनें बनक्कुमितु भव्याभव्यभेददिं जीवराशि द्विविधमक्कुं। मिथ्यादृष्टिगुणस्थानदोळं भव्यजीवंगळुमभव्यजीवंगळुमप्पुववरोळु अभव्यजीवंगळेल्ल कूडि परीतानंतजघन्यराशियं विरळिसि तद्राशियने रूपं प्रतिकोट्टु वर्गितसंवर्गं माडि पुट्टिद राशि युक्तानंतजघन्यमक्कुम। राशिप्रमाणमभव्यजीवराशिप्रमाणमक्कुमुळिद मिथ्यादृष्टिगळनितुं भव्यजीवजातिगळक्कुमादोडं आसन्नभव्यरुं दूरभव्यरुमभव्यसमभव्यरुमप्परु। सासादनगुणस्थानं मोदल्गों डु क्षीणकषायगुणस्थानपर्य्यंतं यथोंदु गुणस्थानंगळोळु भव्यजीवंगळेयप्पुवु। सयोगकेवलिभट्टारक अयोगकेवलिभट्टारकरुं भव्यरुमभव्यरुमल्लतु :—

मि	सा	मि	अ	दे	प्र	अ	अ	अ	सू	उ	क्षी
२	१	१	१	१	१	१	१	१	१	१	१

क्षयोपशमलब्धिमोदलागि करणलब्धिपर्य्यंतमाद परिणामपरिणतनागि अनिवृत्तिकरणपरिणामचरमसमयदोळु अनादिमिथ्यादृष्टियाद पक्षदोळु अनंतानुबंधिचतुःकषायंगळुमं दर्शनमोहनीयमिथ्यात्वकर्म्मप्रकृतियुमनुपशमिसि तदनंतर समयदोळु मिथ्यात्वकर्म्मप्रकृत्यंतरायामांतर्म्मुहूर्त्तकालप्रथमसमयदोळु प्रथमोपशमसम्यक्त्वमं स्वीकररिसि असंयतनक्कुं। मेण प्रथमोपशमसम्यक्त्वमुमं देशव्रतमुमं युगपत्स्वीकरिसि देशसंयतनक्कुमथवा प्रथमोपशमसम्यक्त्वमुमं महाव्रतमुमं युगपत्स्वीकरिसि अप्रमत्तसंयतनक्कुमिवर्गळु प्रथमोपशमसम्यक्त्वग्रहणप्रथमसमयं मोदल्गों डु गुणसंक्रमविधानदिंदं मिथ्यात्वप्रकृतिद्रव्यमुदयदके बारदंतुपशमिसिदुदुं गुणसंक्रमण भागहारदिदमपकर्षिसिकों डु

मिथ्यादृष्टौ द्वौ। तत्र अभव्यराशिः जघन्ययुक्तानन्तमात्रः तेनोनः सर्वसंसारी भव्यराशिः। स च आसन्नभव्यः दूरभव्यः अभव्यसमभव्यश्चेति त्रेधा। सासादनादाक्षीणकषायान्तं भव्य एव। सयोगायोगयोर्भव्याभव्यव्यपदेशो नास्ति।

क्षयोपशमादिपञ्चलब्धिपरिणामपरिणतः अनिवृत्तिकरणचरमसमये अनादिमिथ्यादृष्टिः अनन्तानुबन्धिनो मिथ्यात्वं चोपशमय्य तदनन्तरसमये मिथ्यात्वान्तरायामान्तर्मुहूर्तप्रथमसमये प्रथमोपशमसम्यक्त्वं प्राप्य असंयतो भवति। अथवा प्रथमोपशमसम्यक्त्वदेशव्रते युगपत्प्राप्य देशसंयतो भवति। अथवा प्रथमोपशमसम्यक्त्वमहाव्रते

हो वह भव्य है। उससे विपरीत अभव्य है। मिथ्यादृष्टि गुणस्थानमें दोनों होते हैं। अभव्यराशि युक्तानन्त प्रमाण है। उससे हीन सब संसारी भव्यराशि है। भव्यके तीन भेद हैं— आसन्नभव्य, दूरभव्य, और अभव्यके समान भव्य। सासादनसे क्षीणकषाय पर्यन्त भव्य ही होते हैं। सयोगी और अयोगी न भव्य हैं, न अभव्य। क्षयोपशम आदि पाँच लब्धिरूप परिणामोंसे परिणत हुआ अनादिमिथ्यादृष्टि अनिवृत्तिकरणरूप परिणामोंके अन्तिम समयमें अनन्तानुबन्धी और मिथ्यात्वका उपशम करके उससे अनन्तर समयमें मिथ्यात्वके अन्तरायाम सम्बन्धी अन्तर्मुहूर्तके प्रथम समयमें प्रथमोपशम सम्यक्त्वको

है। मिथ्यात्वके ऊपर और नीचेके निषेकोंको छोड़कर

निषेकोंका अभाव करनेको अन्तर कहते हैं। यह

अथवा प्रथमोपशम सम्यक्त्व और देशव्रत एक साथ

सम्यग्दृष्टियागिक्कुं मात्कुमपवा केळगे देशसंयमगुणस्थानमं पोर्द्दि द्वितीयोपशमसम्यग्दृष्टियागिक्कुं-मथवा, असंयतगुणस्थानमं पोर्द्दि असंयतसम्यग्दृष्टियागिक्कुमथवा मरणमावोडे देवाऽसंयतनक्कुं। मेणु मिश्रप्रकृत्युदयदिदं मिश्रनक्कु। मनंतानुबंधिकषायोदयदिदं द्वितीयोपशमसम्यक्त्वविराधकं सासादननुमोळनें याचार्य्यंपक्षदोळु सासादननुमक्कुमथवा मिथ्यात्वकर्म्मोदयदिदं मिथ्यादृष्टियु-मक्कुमें बी विशेषं द्वितीयोपशमसम्यक्त्वदोळरियल्पडुगुं। क्षायिकसम्यक्त्वमसंयतादिचतुर्गुण-स्थानवर्त्तिगळु वेदकसम्यग्दृष्टिगळ्कर्म्मभूमि जरुमप्परवर्गळ्गक्कुमवर्गळुं केवलि श्रुतकेवलिद्वय श्रीपादपाद्मंदोळु सप्तप्रकृतिगळं निरवशेषं कोडिसि क्षायिकसम्यग्दृष्टिगळप्परु। मानुषियरसं-यतसम्यग्दृष्टिगळु देशयतिकेयरुपचारमहाव्रतिकेयरु केवलिद्वयपादमूलदोळु सप्तप्रकृतिगळं क्षपिसिदिसि क्षायिकसम्यग्दृष्टिगळप्परु। मितु सम्यक्त्वं सामान्यदिदमोंदु विशेषदिदं मिथ्यात्व सासादनमिश्रउपशमवेदकक्षायिकमें दितु षड्विधमक्कुं। मिथ्यादृष्टिगुणस्थानदोळु मिथ्यारुचियक्कुं। सासादननोळमा सासादनरुचियक्कुं। मिश्रगुणस्थानदोळु मिश्ररुचियक्कुं। असंयतगुणस्थानमादि-यागिअप्रमत्तगुणस्थानपर्य्यंतं प्रत्येकमुपशमवेदकक्षायिकंगळमूरुं सम्यक्त्वंगळप्पुवु।

अपूर्व्वकरणगुणस्थानं मोदलागि उपशांतकषायगुणस्थानपर्य्यंतमुपशमश्रेणियोळु नाल्कुं गुण-स्थानंगळोळु प्रत्येकमुपशमसम्यक्त्वमुं क्षायिकसम्यक्त्वमुमेरडुं संभविसुवुवु। क्षपकश्रेणियोळु

मिथ्यादृष्टिर्भवति। द्वितीयोपशमसम्यक्त्वे विशेषः। स कः ? उपशमश्रेण्यारोहणार्थं सातिशयाप्रमत्तवेदक-सम्यग्दृष्टिः करणत्रयपरिणामसामर्थ्यात् अनन्तानुबन्धिनो प्रशस्तोपशमं विना अप्रशस्तोपशमेन अधोनिषेकानु-त्कृष्य वा विसंयोज्य क्षपयित्वा दर्शनमोहत्रयस्य अन्तरकरणेन अन्तरं कृत्वा उपशमविधानेन उपशमय्य अनन्तरप्रथमसमये द्वितीयोपशमसम्यग्दृष्टिर्भूत्वा उपशमश्रेणिमारुह्य उपशान्तकषायं गत्वा अन्तर्मुहूर्तं स्थित्वा क्रमेण अवतीर्य अप्रमत्तगुणस्थानं प्राप्य प्रमत्ताप्रमत्तपरावृत्तिसहस्राणि करोति। वा अधः देशसंयतो भूत्वा आस्ते। वा असंयतो भूत्वा आस्ते। वा मरणे देवासंयतः स्यात् वा मिश्रप्रकृत्युदये मिश्रः स्यात्। अनन्तानु-बन्ध्यन्यतमोदये द्वितीयोपशमसम्यक्त्वं विराधयतीत्याचार्यपक्षे सासादनः स्यात् वा मिथ्यात्वोदये मिथ्यादृष्टिः स्यात् इति। क्षायिकसम्यक्त्वं तु असंयतादिचतुर्गुणस्थानमनुष्याणां असंयतदेशसंयतोपचारमहाव्रतमानुषीणां

मिथ्यात्वका उदय होनेपर मिथ्यादृष्टि हो जाते हैं। द्वितीयोपशम सम्यक्त्वमें विशेष कथन है। उपशम श्रेणीपर आरोहण करनेके लिए सातिशय अप्रमत्तवेदक सम्यग्दृष्टि तीन करणरूप परिणामोंकी सामर्थ्यसे अनन्तानुबन्धी कषायोंका प्रशस्त उपशमके बिना अप्रशस्त उपशमके द्वारा नीचेके निषेकोंको उत्कर्षणके द्वारा ऊपरके निषेकोंमें स्थापित करता है अथवा विसंयो-जन द्वारा अन्य प्रकृतिरूप परिणमाता है। इस तरह उनका क्षपण करके दर्शनमोहकी तीन प्रकृतियोंका अन्तरकरणके द्वारा अन्तर करके उपशम विधानके द्वारा उपशम करता है। तदनन्तर प्रथम समयमें द्वितीयोपशम सम्यग्दृष्टी होकर उपशम श्रेणीपर चढ़ता है। और उपशान्त कषाय तक जाकर वहाँ अन्तर्मुहूर्त तक ठहरकर क्रमसे उतरता हुआ अप्रमत्त गुणस्थानको प्राप्त करके हजारों बार सातवेंसे छठेमें और छठेसे सातवेंमें आता-जाता है। अथवा नीचे उतरकर देशसंयमी या असंयमी हो जाता है। अथवा मरणकाल आनेपर असंयतदेव हो जाता है अथवा मिश्र प्रकृतिके उदयमें मिश्रगुणस्थानवर्ती हो जाता है। जिन आचार्योंका मत है कि अनन्तानुबन्धीका उदय होनेपर द्वितीयोपशम सम्यक्त्वकी विरा-धना करता है उनके मतसे सासादन हो जाता है। अथवा मिथ्यात्वके उदयमें मिथ्यादृष्टि

---

१. म जरुगळक्कुमर्गुळु।

स्थानंगळोळं आहारमो देयक्कुं। अयोगिकेवलिभट्टारकरोळं गुणस्थानातीतरप्प सिद्धपरमेष्ठिगळोळमनाहारमेयक्कुं :—

मि	सा	मि	अ	दे	प्र	अ	अ	अ	सू	उ	क्षी	स	अ	सि
२	२	१	२	१	१	१	१	१	१	१	१	२	१	१

अनंतरं गुणस्थानंगळोळुपयोगमं पेळ्दपं :—

दोण्हं पंच य छच्चेव दोसु मिस्सम्मि होंति वामिस्सा।
सत्तुवजोगा सत्तसु दो चेव जिणे य सिद्धे य ॥७०५॥

द्वयोः पंच च षट् चैव द्वयोः मिश्रे भवंति व्यामिश्राः। सप्तोपयोगाः सप्तसु द्वावेव जिनयोः सिद्धे च ॥

गुणपर्य्ययवद्वस्तुग्रहणव्यापारमुपयोगमें बुदक्कुं। ज्ञानमं वस्तु पुट्टिसुवल्लुमंते पेळल्पट्टुदु।

स्वहेतुजनितोप्यर्थः परिच्छेद्यः स्वतो यथा।
तथा ज्ञानं स्वहेत्वर्थं परिच्छेद्यात्मकं स्वतः ॥ [ ]

'नार्थालोकौ कारणं परिच्छेद्यत्वात्तमोवत्'। [परी० मु०] एंदितु अंतप्पुपयोगं ज्ञानोपयोगमें दुं दर्शनोपयोगमें दुं द्विविधमक्कुमल्लि कुमति कुश्रुत विभंग मतिश्रुतावधिमनःपर्य्ययकेवलज्ञानमें दु ज्ञानोपयोगमें दु तेरनक्कक्कुं। चक्षुरचक्षुरवधिकेवलदर्शनमें दु दर्शनोपयोगं नाल्कु तेरनक्कुं। मिथ्यादृष्टिगुणस्थानदोळु कुमतिकुश्रुतविभंगमें ब मूरुं ज्ञानोपयोगंगळु चक्षुरचक्षुर्द्दर्शनमें बेरडुं दर्शनोपयोगंगळुमितु अय्दुमुपयोगंगळप्पुवु। सासादनगुणस्थानदोळमंते अय्दुमुपयोगंगळप्पुवु। मिश्रगुणस्थानदोळु मतिश्रुतावधिचक्षुरचक्षुरवधिगळ वारु मिश्रोपयोगंगळप्पुवु। असंयतसम्यग्दृष्टि-

सयोगे अयोगे सिद्धे च अनाहारः। तेन मिथ्यादृष्टिसासादनासंयतसयोगेषु तौ द्वौ शेषनवस्वाहारः। अयोगिसिद्धे वा अनाहारः ॥७०४॥ गुणस्थानेषु उपयोगमाह—

गुणपर्ययवद्वस्तु तद्ग्रहणव्यापार उपयोगः। ज्ञानं न वस्तूत्थं तथा चोक्तं—

स्वहेतुजनितोऽप्यर्थः परिच्छेद्यः स्वतो यथा।
तथा ज्ञानं स्वहेतूत्थं परिच्छेदात्मकं स्वतः ॥१॥

"नार्थालोकौ कारणं परिच्छेद्यत्वात् तमोवत् इति"। स उपयोगः ज्ञानदर्शनभेदाद्द्वेधा। तत्र ज्ञानोपयोगः—कुमतिकुश्रुतविभंगमतिश्रुतावधिमनःपर्ययकेवलज्ञानभेदादष्टधा। दर्शनोपयोगः चक्षुरचक्षुरवधि-

शरीर और अंगोपांग नामकर्मसे उत्पन्न शरीर वचन और मनके योग्य नोकर्म वर्गणाओंके ग्रहणको आहार कहते हैं। विग्रहगतिमें प्रतर और लोकपूरण समुद्घात सहित सयोगीमें, अयोगी और सिद्ध अनाहारक हैं। अतः मिथ्यादृष्टि, सासादन, असंयत और सयोगकेवलीमें प्रतर लोकपूरणवाले अनाहारक हैं। शेष नौ गुणस्थानोंमें आहार है। अयोगकेवली और सिद्ध अनाहारक हैं ॥७०४॥

गुणस्थानोंमें उपयोग कहते हैं—

गुणपर्यायसे जो युक्त है वह वस्तु है। उसको ग्रहण करनेरूप व्यापारका नाम उपयोग है। ज्ञान वस्तुसे उत्पन्न नहीं होता। कहा है—जैसे अर्थ अपने कारणसे उत्पन्न होता है, आप स्वतः ही ज्ञानका विषय होनेके योग्य होता है। उसी प्रकार ज्ञान अपने कारणसे उत्पन्न होता है और स्वतः अर्थको जाननेरूप होता है॥ और कहा है—अर्थ और प्रकाश ज्ञानके कारण नहीं

आलापाधिकारः ॥२२॥

अनंतरमालापाधिकारमं पेळलुपक्रमिसुत्तमिष्टदेवतानमस्काररूपपरममंगलमनंगीकरिसुत्तं गुणस्थानदोळं मार्गणास्थानदोळं विंशतिभेदंगळ्गे प्राग्योजितंगळप्पाळापत्रयमं पेळ्दपेनेंदाचार्यं प्रतिज्ञेयं माडिदपं :—

गोदमथेरं पणमिय ओघादेसेसु वीसभेदाणं ।
जोजणिकाणालावं वोच्छामि जहाकमं सुणुह ॥७०६॥

गौतमस्थविरं प्रणम्य ओघादेशेषु विंशतिभेदानां । योजितानामालापं वक्ष्यामि यथाक्रमं शृणुत ॥

विशिष्टा गौर्भूमिर्गौतमा अष्टमपृथ्वी सा स्थविरा नित्या यस्य सिद्धपरमेष्ठिसमूहस्य स गौतमस्थविरः गौतमस्थविरः गौतमस्थविर एव गौतमस्थविरस्तं । अथवा गौतमो गौतमस्वामी स्थविरो यस्यासौ गौतमस्थविरः श्रीवीरवर्द्धमानस्वामी तं । अथवा विशिष्टा गौर्वाणी[१] गौतम सर्व्वज्ञभारती तां वेत्ति अधीते वा गौतमः । स चासौ स्थविरश्च गौतमस्थविरः गौतमस्वामी तं प्रणम्येत्यर्थः । सिद्धपरमेष्ठिसमूहमं श्रीवीरवर्द्धमानस्वामियुमं मेणु गौतमगणधरस्वामियुमं नमस्कारमं माडि गुणस्थानमार्ग्गणास्थानंगळोळु मुंनं योजिसल्पट्ट विंशतिप्रकारंगळ्गाळापमं सामान्यपर्य्याप्तापर्य्याप्तमें ब त्रिप्रकाराळापमं यथाक्रमदिंदं पेळ्दपे केळिमेंदाचार्य्यं शिष्यरं शिक्षिसिदपं । अवें ते दोडे :—

नेमि धर्मरथे नेमिं पूज्यं सर्वनरामरैः ।
वहिरन्तःश्रियोपेतं जिनेन्द्रं तत्क्रिये श्रये ॥२२॥

अथालापाधिकारं स्वेष्टदेवतानमस्कारपूर्वकं वक्तुं प्रतिजानीते—

विशिष्टा गौर्भूमिः गोतमा–अष्टमपृथ्वी सा स्थविरा नित्या यस्य स गोतमस्थविरः सिद्धसमूहः, गोतमस्थविर एव गौतमस्थविरः तं अथवा गौतमः गौतमस्वामी स्थविरो यस्यासौ गौतमस्थविरः श्रीवर्धमानस्वामी तं । अथवा विशिष्टा गौः वाणी यस्यासौ गोतमः गोतम एव गौतमः स चासौ स्थविरश्च गौतमस्थविरः तं प्रणम्य गुणस्थानमार्गणास्थानयोः प्राग् योजितानां विंशतिप्रकाराणां आलापं यथाक्रमं वक्ष्यामि ॥७०६॥ तद्यथा—

अपने इष्टदेवको नमस्कारपूर्वक आलापाधिकारको कहनेकी प्रतिज्ञा करते हैं—विशिष्ट 'गौ' अर्थात् भूमि गोतमा अर्थात् आठवी पृथ्वी वह जिसकी स्थविर अर्थात् नित्य है वह गोतमस्थविर अर्थात् सिद्ध समूह । अथवा गौतम स्वामी जिसके गणधर हैं वे वर्धमान स्वामी, अथवा जिसकी गौ अर्थात् वाणी विशिष्ट है उन गौतमस्थविरको नमस्कार करके गुणस्थान और मार्गणास्थानोंमें पूर्वयोजित बीस प्रकारके आलापोंको यथाक्रम कहूँगा ॥७०६॥

१. म °र्वाणी यस्यासौ गौतमः । गौतम एव गौतमः स चासौ ।

सामण्णं पज्जत्तमपज्जत्तं चेदि तिण्णि आलावा ।
दुवियप्पमपज्जत्तं लद्धी णिव्वत्तगं चेदि ॥७०९॥

सामान्यपर्य्याप्तमपर्य्याप्तं चेति त्रय एवालापाः । द्विविकल्पमपर्य्याप्तं लब्धिर्न्निर्वृतिश्चेति ॥

सामान्यमें दुं पर्य्याप्तमें दुमपर्य्याप्तमें दितु आळापंगळु मूरप्पुवल्लि अपर्य्याप्तालापं लब्ध्यपर्य्याप्तं निर्वृत्यपर्य्याप्तमेंदितु द्विविकल्पमक्कुं ।

दुविहंपि अपज्जत्तं ओघे मिच्छेव होदि णियमेण ।
सासण अयदपमत्ते णिव्वत्ति अपुण्णगं ¹होदि ॥७१०॥

द्विविधमप्यपर्य्याप्तं ओघे मिथ्यादृष्टावेव भवति नियमेन । सासादनासंयतप्रमत्ते निर्वृत्यपर्य्याप्तं भवति ॥

द्विप्रकारमनुळ्ळऽपर्य्याप्तं ओघदोळु सामान्यदोळु मिथ्यादृष्टियोळेयक्कु नियमदिदं । सासादनसम्यग्दृष्टिगुणस्थानदोळमसंयतसम्यग्दृष्टिगुणस्थानदोळं प्रमत्तसंयतगुणस्थानदोळमी मूरुं गुणस्थानंगळोळु नियमदिदं निर्वृत्यपर्य्याप्तमेयक्कुं ।

जोगं पडि जोगिजिणे होदि हु णियमा अपुण्णगत्तं तु ।
अवसेसणवट्ठाणे पज्जत्तालावगो एक्को ॥७११॥

योगं प्रति योगिजिने भवति खलु नियमादपूर्णकत्वं तु । अवशेष नवस्थाने पर्य्याप्तालापक एकः ॥

योगमं कुरुत्तु सयोगिकेवलिभट्टारकजिननोळु खलु स्फुटमागि अपूर्णकत्वमपर्य्याप्तकत्वमक्कुं । तु मत्ते अवशेष नवगुणस्थानंगळोळु पर्य्याप्तालापमो देयक्कुं ।

अनंतरं चतुर्द्दश मार्ग्गणास्थानंगळोळालापमं पेळलुपक्रमिसि मोदलोळु गतिमार्ग्गणेयोळु पेळ्दपं :—

ते आलापाः सामान्यः पर्याप्तः अपर्याप्तश्चेति त्रयो भवन्ति । तत्रापर्याप्तालापः लब्ध्यपर्याप्तः निर्वृत्त्यपर्याप्तश्चेति द्विविधो भवति ॥७०९॥

द्विविधोऽपि अपर्याप्तालापः सामान्यमिथ्यादृष्टावेव भवति नियमेन । सासादनासंयतप्रमत्तेषु नियमेन निर्वृत्त्यपर्याप्तालाप एव भवति ॥७१०॥

योगमाश्रित्यैव सयोगिजिने नियमेन खलु अपर्याप्तकत्वं भवति । तु—पुनः अवशेषनवगुणस्थानेषु एकः पर्याप्तालापः ॥७११॥ अथ चतुर्दशमार्गणास्थानेषु आह—

इसी अर्थको स्पष्ट करते हैं—

वे आलाप सामान्य, पर्याप्त, अपर्याप्त इस तरह तीन हैं। उनमें-से अपर्याप्त आलापके भेद दो हैं—लब्ध्यपर्याप्त और निर्वृत्त्यपर्याप्त ॥७०९॥

यह दोनों ही प्रकारका अपर्याप्त आलाप नियमसे सामान्य मिथ्यादृष्टिमें ही होता है। सासादन, असंयत और प्रमत्तमें नियमसे निर्वृत्त्यपर्याप्त आलाप ही होता है ॥७१०॥

सयोगी जिनमें नियमसे योगकी अपेक्षा ही अपर्याप्त आलाप होता है। शेष नौ गुणस्थानोंमें एक पर्याप्त आलाप ही होता है ॥७११॥

चौदह मार्गणास्थानोंमें कहते हैं—

१. म चेदि । २. म चेदि ।

तेरिच्छियलद्धियपज्जत्ते एक्को अपुण्ण आलावो ।
मूलोघं मणुसतिये मणुसिणि अयदम्मि पज्जत्तो ॥७१४॥

तिर्य्यग्लब्ध्यपर्य्याप्ते एकोऽपूर्णालापः मूलोघो मनुष्यत्रये मानुष्यसंयते पर्य्याप्तः ॥

तिर्य्यंचलब्ध्यपर्य्याप्तनोळु अपर्य्याप्तालापमो वेयक्कुं । मनुष्यगतियोळ्पविनाल्कुं गुणस्थानंगळोळु सामान्यमनुष्यपर्य्याप्तमनुष्ययोनिमतिमनुष्यमेंबो मनुष्यत्रयद प्रत्येकं पदिनाल्कुं पदिनाल्कुं गुणस्थानंगळोळु मुंपेळ्दाळापं मूलोघमेयक्कुमावोडं योनिमत्यसंयतसम्यग्दृष्टिगुणस्थानदोळु पर्य्याप्तालापमेयक्कुमेकेंदोडे कारणं मुन्नं तिर्य्यग्गतियोळु पेळ्दुदेयक्कुं । मत्तों दु विशेषमुंटदावुदेंदोडे असंयतयोनिमतितिर्य्यंचेयरुमसंयतयोनिमतिमानुषियुं प्रथमोपशमवेदकक्षायिकसम्यग्दृष्टिगळुमोळरप्पुवर्र । भुज्यमानपर्य्याप्तालापमेयक्कुं । योनिमतिमनुष्यरुगळय्दु गुणस्थानंगळंमेल्पुवरिंदमुपशमश्रेण्यवतरणदोळमा द्वितीयोपशमसम्यक्त्वसंभवमिल्ल एकेंदोडवर्गे श्रेण्यारोहणमे घटिसदप्पुदरिंदं ॥

मणुसिणि पमत्तविरदे आहारदुगं तु णत्थि णियमेण ।
अवगदवेदे मणुसिणि सण्णा भूदगदिमासेज्ज ॥७१५॥

मानुषि प्रमत्तविरते आहारद्वयं नास्ति तु नियमेन । अपगतवेदायां मानुष्यां संज्ञा भूतगतिमाश्रित्य ॥

तिर्यग्लब्ध्यपर्याप्तके एकः अपर्याप्तालाप एव । मनुष्यगतौ सामान्यपर्याप्तयोनिमन्मनुष्येषु प्रत्येकं चतुर्दशगुणस्थानेषु गुणस्थानवत् मूलोघः स्यात् तथापि योनिमदसंयते पर्याप्तालाप एव । कारणं प्रागुक्तमेव । पुनरयं विशेषः—असंयततैरश्चां प्रथमोपशमकवेदकसम्यक्त्वद्वयं, असंयतमानुष्यां प्रथमोपशमवेदकक्षायिकसम्यक्त्वत्रयं च संभवति तथापि एको भुज्यमानपर्याप्तालाप एव । योनिमतीनां पञ्चगुणस्थानादुपरि गमनासंभवात् द्वितीयोपशमसम्यक्त्वं नास्ति ॥७१४॥

स्त्री और नपुंसकोंमें उत्पन्न नहीं होता । तथा शेष मिश्र और देश संयत गुणस्थानोंमें भी एक पर्याप्त आलाप ही होता है ॥७१३॥

तिर्यंच लब्ध्यपर्याप्तकमें एक अपर्याप्त आलाप ही होता है । मनुष्यगतिमें सामान्य, पर्याप्त और योनिमत मनुष्योंमें-से प्रत्येकमें चौदह गुणस्थानोंमें गुणस्थानवत् जानना । फिर भी योनिमत मनुष्यके असंयत गुणस्थानमें एक पर्याप्त आलाप ही होता है । कारण पहले कहा ही है । पुनः इतना विशेष और है कि असंयत गुणस्थानमें तिर्यंचोंके प्रथमोपशम और वेदक दो ही सम्यक्त्व होते हैं । और मानुषीके प्रथमोपशम, वेदक तथा क्षायिक तीन सम्यक्त्व होते हैं । तथापि एक भुज्यमान पर्याप्त आलाप ही है । योनिमती पंचम गुण स्थानसे ऊपर नहीं जाती इसलिए उसके द्वितीयोपशम सम्यक्त्व नहीं होता ॥७१४॥

१. म सालापमेयक्कुमुपशमश्रेण्यवतरणदोळु द्वितीयोपशमसम्यक्त्वं योनिमतिगळल्[illegible] गळेयप्पुदरिंदमा द्वितीयोपशमसम्यक्त्वसंभवमिल्ल ।

मनुष्यलब्ध्यपर्य्याप्तकनोळु अपूर्ण्णालापमोंदे यक्कुं। लेश्येगळिदं माडल्पट्ट भेदंगळिदं भिन्नंगळप्प देवर्क्कळ स्थानंगळु सप्तविकल्पंगळप्पुवु। अवेंतेंदोडे :—

तिण्हं दोण्हं दोण्हं छण्हं दोण्हं च तेरसण्हं च।
एत्तो य चोद्दसण्हं लेस्सा भवणादिदेवाणं ॥

त्रयाणां द्वयोर्द्वयोः षण्णां द्वयोश्च त्रयोदशानां इतश्चतुर्द्दशानां लेश्याः भवनादिदेवानां ॥

भवनत्रयदेवर्क्कळुं सौधर्म्मैशानकल्पजरुं सानत्कुमारमाहेंद्रकल्पजरुं ब्रह्मब्रह्मोत्तरलांतवकापिष्टशुक्रमहाशुक्रषट्कल्पजरुं शतारसहस्रारकल्पद्वयजरुं आनतप्राणतारणाच्युतकल्पनवग्रैवेयककल्पातीतजरुं अल्लिदं मेलण अनुदिशानुत्तरचतुर्द्दशविमानसंभूतरुमितु सप्तस्थानंगळ देवर्क्कळो लेश्येगळ्मेळल्पट्टप्पुवु ॥

तेऊ तेऊ तह तेऊ पम्मपम्मा य पम्मसुक्का य।
सुक्का य परमसुक्का लेस्सा भवणादिदेवाणं ॥

तेजस्तेजस्तथा तेजः पद्मे पद्मं च पद्मशुक्ले च। शुक्ला च परमशुक्ला लेश्या भवनादिदेवानां ॥

मुंपेळ्द सप्तस्थानंगळोळु यथासंख्यमागि भवनत्रयादिस्थानंगळोळु तेजोलेश्येयजघन्यांशमुं तेजोलेश्येयमध्यमांशमुं तेजोलेश्येय उत्कृष्टांशमुं पद्मलेश्येय जघन्यांशमेरडुं पद्मलेश्येय मध्यमांशमुं पद्मलेश्येय उत्कृष्टांशमुं शुक्ललेश्येय जघन्यांशमुमेरडुं शुक्ललेश्येय मध्यमांशमुं शुक्ललेश्येयुत्कृष्टांशमुं भवनत्रयादिदेवर्क्कळ लेश्येगळप्पुवु ॥

सव्वसुराणं ओघे मिच्छदुगे अविरदेय तिण्णेव।
णवरि य भवणतिकप्पित्थीणं च य अविरदे पुण्णो ॥७१७॥

सर्व्वसुराणामोघे मिथ्यादृष्टिद्वये अविरते च त्रय एव। नवमस्ति भवनत्रयकल्पस्त्रीणां च चाविरते पूर्ण्णः ॥

तु—पुनः, मनुष्यलब्ध्यपर्याप्ते एकः लब्ध्यपर्याप्तालाप एव। लेश्याभेदविभिन्नदेवस्थानानि सप्तविकल्पानि भवन्ति तद्यथा—

तिण्हं दोण्हं दोण्हं छण्हं दोण्हं च तेरसण्हं च।
एत्तो य चोद्दसण्हं लेस्सा भवणादिदेवाणं ॥१॥
तेऊ तेऊ तेऊ पम्मा पम्मा य पम्मसुक्का य।
सुक्का य परमसुक्का भवणतिया पुण्णगे असुहा ॥२॥

भवनत्रय–सौधर्मद्वय–सानत्कुमारद्वय–ब्रह्मादिषट्क–शतारद्वय–आनतादित्रयोदश–उपरितनचतुर्दशविमानानां क्रमशः तेजोजघन्यांश–तेजोमध्यमांश–तेज उत्कृष्टांश–पद्मजघन्यांश–पद्ममध्यमांश–पद्मोत्कृष्टांश–शुक्लजघन्यांश–शुक्लमध्यमांश–शुक्लोत्कृष्टांशा भवन्ति ॥७१६॥

मनुष्य लब्ध्यपर्याप्तकमें एक लब्ध्यपर्याप्त आलाप ही होता है। लेश्याभेदसे देवोंके सात स्थान होते हैं। भवनत्रिक, सौधर्मयुगल, सनत्कुमार युगल, ब्रह्म आदि छह स्वर्ग, शतार युगल, आनतादि तेरह और ऊपरके चौदह विमानवालोंके क्रमसे तेजोलेश्याका जघन्य अंश, तेजोलेश्याका मध्यम अंश, तेजोलेश्याका उत्कृष्ट अंश और पद्मलेश्याका जघन्य अंश, पद्मलेश्याका मध्यम अंश, पद्मलेश्याका उत्कृष्ट अंश और शुक्लका जघन्य अंश, शुक्लका मध्यम अंश तथा शुक्लका उत्कृष्ट अंश होता है ॥७१६॥

गुणस्थानंगळोळु षष्ठगुणस्थानवर्त्तिप्रमत्तसंयतनोळाहारक आहारकमिश्रमें बाळापद्वयमं पेळ्वुकोळ्ळवेडेकें दोडा गुणस्थानदोळु अशुभवेदोदयमुळ्ळरोळाहारर्द्धि संभविसवप्पदरिदं हत्थपमाणं पसत्थुदयमें वाहारकशरीरदोळु प्रशस्तप्रकृतिगळुदयनियममुंटप्पुदरिदं। वेदमार्ग्गणेयोळनिवृत्तिकरणसवेदभागिपर्य्यंतमो भत्तुं गुणस्थानंगळप्पुवु। मेलण नाल्कुमवेदभागिपर्य्यंतं कषायमार्ग्गणेय क्रोधदो भत्तुं मानदो भत्तुं मायेयो भत्तुं बादरलोभदो भत्तुं मिथ्यादृष्टिगुणस्थानमादियागिद्दं गुणस्थानंगळोळं सूक्ष्मलोभक्के सूक्ष्मसांपरायगुणस्थानदोळं ज्ञानमार्ग्गणेय कुमतिज्ञानदेरडुं कुश्रुतज्ञानदेरडुं विभंगज्ञानदेरडुं मतिज्ञानदो भत्तुं श्रुतज्ञानदो भत्तुं अवधिज्ञानदो भत्तुं मनःपर्य्ययज्ञानदेळुं केवलज्ञानदेरडुं गुणस्थानंगळोळु। संयममार्ग्गणेय असंयमद नाल्कुं देशसंयमदोंदुं सामायिकद नाल्कुं छेदोपस्थापनद नाल्कुं परिहारविशुद्धि संयमदेरडुं सूक्ष्मसांपरायसंयमदोंदुं यथाख्यातसंयमद नाल्कुं गुणस्थानंगळोळं दर्शनमार्ग्गणेय चक्षुर्द्दर्शनद पन्नेरडु गुणस्थानंगळोळमचक्षुर्द्दर्शनद पन्नेरडुं अवधिदर्शनदो भत्तुं केवलदर्शनदेरडुं गुणस्थानंगळोळं लेश्यामार्ग्गणेय कृष्णनीलकपोतंगळनाल्कुं नाल्कुं गुणस्थानंगळोळं तेजःपद्मंगळेळुं गुणस्थानंगळोळं शुक्ललेश्येय पदिमूरुं गुणस्थानंगळोळं भव्यमार्ग्गणेयोळु भव्यन पदिनाल्कुमभव्यनदोंदु गुणस्थानंगळोळं सम्यक्त्वमार्ग्गणेय मिथ्यात्वदोंदुं सासादननतन्नोंदुं मिश्रन तन्नोंदुं द्वितीयोपशमसम्यक्त्वदेंटुं प्रथमोपशमसम्यक्त्वदनाल्कुं वेदकसम्यक्त्वद नाल्कुं क्षायिकसम्यक्त्वद पन्नोंदुं गुणस्थानंगळोळं संज्ञिमार्ग्गणेयोळु संज्ञिय

द्रव्यपुरुषे भावस्त्रीद्रव्यपुरुषे च प्रमत्तसंयते आहारकतन्मिश्रालापौ न। 'हत्थपमाणं पसत्थुदयं' इत्याहारकशरीरे प्रशस्तप्रकृतीनामेवोदयनियमात्। वेदानामनिवृत्तिकरणसवेदभागान्तेषु क्रोधमानमायाबादरलोभानां अवेदचतुर्भागान्तेषु सूक्ष्मलोभस्य सूक्ष्मसांपराये। ज्ञानमार्गणायां कुमतिकुश्रुतविभङ्गानां द्वयोः, मतिश्रुतावधीनां नवसु, मनःपर्ययस्य सप्तसु, केवलज्ञानस्य द्वयोः, असंयमस्य चतुर्षु, देशसंयमस्य एकस्मिन्, सामायिकछेदोपस्थापनयोश्चतुर्षु, परिहारविशुद्धेर्द्वयोः, सूक्ष्मसांपरायस्य एकस्मिन्, यथाख्यातस्य चतुर्षु, चक्षुरचक्षुर्दर्शनयोः द्वादशसु, अवधिदर्शनस्य नवसु, केवलदर्शनस्य द्वयोः, कृष्णनीलकपोतानां चतुर्षु, तेजःपद्मयोः सप्तसु, शुक्लायाः त्रयोदशसु, भव्यमार्गणायां भव्यस्य चतुर्दशसु, अभव्यस्य एकस्मिन्, सम्यक्त्वमार्गणायां मिथ्यात्वसासादनमिश्राणामेकैकस्मिन्, द्वितीयोपशमस्य अष्टसु, प्रथमोपशमवेदकयोश्चतुर्षु, क्षायिकस्य एकादशसु, संज्ञिनो-

स्त्री द्रव्यसे पुरुषके प्रमत्तसंयतमें आहारक-आहारक मिश्र आलाप नहीं होते क्योंकि 'हत्थपमाणं पसत्थुदयं' इस आगम प्रमाणके अनुसार आहारक शरीरमें प्रशस्त प्रकृतियोंके ही उदयका नियम है। वेद अनिवृत्तिकरणके सवेद भाग पर्यन्त होते हैं। क्रोध, मान, माया, बादर लोभ अनिवृत्तिकरणके वेदरहित चार भागपर्यन्त क्रमसे होते हैं। सूक्ष्मलोभ सूक्ष्मसाम्परायमें होता है। ज्ञानमार्गणामें कुमति, कुश्रुत और विभंगके दो गुणस्थान हैं। मतिश्रुत-अवधिके नौ गुणस्थान हैं। मनःपर्ययके सात गुणस्थान हैं। केवलज्ञानके दो गुणस्थान हैं। असंयतके चार गुणस्थान हैं, देशसंयतका एक गुणस्थान है। सामायिक छेदोपस्थापनाके चार गुणस्थान हैं। परिहारविशुद्धिके दो, सूक्ष्मसाम्परायका एक, यथाख्यातके चार, चक्षुदर्शन-अचक्षुदर्शनके बारह, अवधिदर्शनके नौ, केवलदर्शनके दो, कृष्ण-नील-कपोत लेश्याके चार, तेज और पद्मके सात, शुक्ललेश्याके तेरह, भव्यमार्गणामें भव्यके चौदह, अभव्यका एक, सम्यक्त्वमार्गणामें मिथ्यात्व सासादन मिश्रका एक-एक गुणस्थान है। द्वितीयोपशम-सम्यक्त्वके आठ, प्रथमोपसम और वेदकके चार, क्षायिक सम्यक्त्वके ग्यारह, संज्ञीके

स्थानदोळे मिश्रकाय प्राणंगळेरडुं अयोगिकेवलिगुणस्थानदायुष्प्राणमों दुं नाल्कुं संज्ञेगळुं नाल्कु गतिगळुं पंचेंद्रियंगळुं । आरुकायंगळुं पर्य्याप्तयोगंगळ्पनोंदुं । अपर्य्याप्तयोगंगळु नाल्कुं मूरुवेदंगळु नाल्कुं कषायंगळु एंटु ज्ञानंगळु एळु संयमंगळु नाल्कुं दर्शनंगळु आरुं लेश्यगळुं एरडुं भव्यंगळु आरुं सम्यक्त्वंगळु येरडुं संज्ञेगळु यरडुमाहारंगळुं । पन्नेरडुमुपयोगंगळु एंदी समुच्चयं गुणस्थानंगळोळं मार्गणास्थानंगळोळं यथायोग्यंगळागि प्ररूपिसल्पडुवुवल्लि संदृष्टि :—

गु १४ । प अ । जी ६ । ७ प६ । अ७ अ६ । प६ प४ प्राणंगळु १० । ७ । ९ । ७ । ८ । ६ । ७ । ५ । ६ । ४ । ४ । ३ । ४ । स२ । अ १ । संज्ञेगळुनाल्कु ४ । गतिगळु नाल्कु ४ । इंद्रिय ५ । काय ६ । यो ११ । ४ । वे ३ । क । ४ । ज्ञा ८ । सं ७ । द ४ । ले ६ । भ २ । सं ६ । सं २ । आ २ । उ १२ ॥

जीवसमासेयोळु विशेषमं पेळ्दपं :—

ओघे आदेसे वा सण्णी पज्जंतगा हवे जत्थ ।
तत्थ य उणवीसंता इगिबितिगुणिदा हवे ठाणा ॥७२७॥

ओघे आदेशे वा संज्ञिपर्य्यंता भवेयुर्य्यत्र तत्र चैकान्नविंशत्यंता एकद्वित्रिगुणिता भवेयुः स्थानानि ॥

सामान्यदोळं विशेषदोळं संज्ञिपर्य्यंतमाद मूलजीवसमासंगळावेडेयोळु पेळल्पडुवुवल्लि एकान्नविंशतिअंतमाद उत्तरजीवसमासस्थानविकल्पंगळु एकद्वित्रिगुणितमादोडे सर्व्वजीवसमासस्थानविकल्पंगळप्पुवु । सा १ । ग १ । स्था १ । ए १ । वि १ । सं १ । प १ । वि १ । अ १ । सं १ ।

पुनः मिश्रकायायुषी, अयोगस्य आयुर्नामैकः । संज्ञाश्चतस्रः, गतयः चतस्रः, इन्द्रियाणि पञ्च, कायाः षट्, योगाः पर्याप्ता एकादश, अपर्याप्ताश्चत्वारः, वेदाः त्रयः, कषायाश्चत्वारः, ज्ञानानि अष्टौ, संयमाः सप्त, दर्शनानि चत्वारि, लेश्याः षट्, भव्यद्वयं, सम्यक्त्वानि षट्, संज्ञिद्वयं आहारद्वयं उपयोगा द्वादश-एवं सर्वं समुच्चयं गुणस्थानेषु मार्गणास्थानेषु च यथायोग्यं प्ररूपयितव्याः ॥७२५-७२६॥ जीवसमासेषु विशेषमाह—

सामान्ये विशेषे वा संज्ञिपर्यन्ता मूलजीवसमासा यत्र निरूप्यन्ते तत्र एकान्नविंशत्यन्ता उत्तरजीवसमासस्थानविकल्पा एकद्वित्रिगुणिताः सन्तः सर्वजीवसमासस्थानविकल्पा भवन्ति ।

अयोगीके एक आयुप्राण है । संज्ञा चार, गति चार, इन्द्रियाँ पाँच, काय छह, पर्याप्तयोग ग्यारह, अपर्याप्त चार, वेद तीन, कषाय चार, ज्ञान आठ, संयम सात, दर्शन चार, लेश्या छह, भव्य-अभव्य, सम्यक्त्व छह, संज्ञी-असंज्ञी, आहारक-अनाहारक, उपयोग बारह । ये सब गुणस्थानों और मार्गणास्थानोंमें यथायोग्य प्ररूपणीय हैं ॥७२५-७२६॥

जीवसमासोंमें विशेष कहते हैं—

गुणस्थानों या मार्गणाओंमें जहाँ संज्ञीपर्यन्त मूल जीवसमास कहे जावें वहाँ उन्नीस पर्यन्त उत्तर जीवसमास स्थानके विकल्पोंको एक सामान्य, दो पर्याप्त-अपर्याप्त और तीन

१. म मु. प्रो. प ६ । ६ ।
१४ । ७ । ७ । ६ ६ ।

९।१२।१५।१८।२१।२४।२७।३०। ३३।३६।३९। ४२।४५। ४८।५१।५४। ५७॥ गुणकार ३ युति ५७०॥ इंतु गुणस्थानंगळोळं मार्ग्गणास्थानंगळोळं विंशतिविधं गळु योजिसल्पडुगुमदें तें दोडे :—

वीरमुहकमलणिग्गयसयलसुयग्गहणपयडणसमत्थं ।
णमिऊण गोदममहं सिद्धांतालावमणुवोच्छं ॥७२८॥

वीरमुखकमलनिर्गतसकलश्रुतग्रहणप्रतिपादनसमर्थं । नत्वा गौतममहं सिद्धांतालापमनुवक्ष्यामि ॥

सूत्रसूचितंगळप्प विंशतिविधंगळालापनिरूपणे माडल्पडुवल्लि मोदलोळु गुणस्थानदिदं पेळल्पडुगुमदें तें दोडे पदिनाल्कुं गुणस्थानवर्त्तिगळं गुणस्थानातीतरुगळुमोळरु। पदिनाल्कुं जीवसमासंगळनुळ्ळरुमतीतजीवसमासरुगळुमोळरु पट्पर्य्याप्तिगळोळ्कूडिदरं । षट्पर्य्याप्तियुक्तरं पंचपंचपर्य्याप्त्यपर्य्याप्तियुक्तरं। चतुश्चतुःपर्य्याप्त्यपर्य्याप्तियुक्तरुगळुमोळरु। अतीतपर्य्याप्तरुगळुमोळरु। दशप्राण। सप्तप्राण। नवप्राण। नवप्राण। सप्तप्राण। अष्टप्राण। षट्प्राण। सप्तप्राण। पंचप्राण। षट्प्राण। चतुःप्राण। चतुःप्राण। त्रिप्राण। चतुःप्राण। द्विप्राण। एकप्राण। युतरुमतीतप्राणरुगळुमोळरु। चतुर्विधसंज्ञायुक्तरं। क्षीणसंज्ञरुगळुमोळरु। चतुर्गतिजीवंगळुं सिद्धगतिजीवंगळुमोळरु।

एकेंद्रियादिपंचजातियुतजीवंगळु मतीतजातिगळुमोळरु। पृथ्वीकायिकादिषट्कायिकंगळुमतीतकायिकंगळुमोळरु। पंचदशयोगयुक्तरुमयोगरुगळुमोळरु। त्रिवेदिगळुमपगतवेदरुगळुमोळरु।

एकः १। युतिः १९०। २ ४ ६ ८ १० १२ १४ १६ १८ २० २२ २४ २६ २८ ३० ३२ ३४ ३६ ३८ गुणकारः २ युतिः ३८०। ३ ६ ९ १२ १५ १८ २१ २४ २७ ३० ३३ ३६ ३९ ४२ ४५ ४८ ५१ ५४ ५७ गुणकारः ३। युतिः ५७० ॥७२७॥ इतोऽग्रे गुणस्थानेषु मार्गणास्थानेषु च ते गुणजीवपर्याप्तिप्रभृतिभेदा योज्यन्ते तद्यथा—

तत्र गुणस्थानेषु यथा तावच्चतुर्दशगुणस्थानजीवाः तदतीताश्च सन्ति। चतुर्दशजीवसमासास्तदतीताश्च सन्ति। षट् षट् पञ्च पञ्च चतुश्चतुः पर्याप्त्यपर्याप्तिजीवाः तदतीताश्च सन्ति। दशसप्तनवसप्ताष्टषट्सप्तपञ्चषट्चतुश्चतुस्त्रिचतुर्द्व्येकप्राणाः तदतीताश्च सन्ति। चतुःसंज्ञाः तदतीताश्च सन्ति। चतुर्गतिका सिद्धाश्च सन्ति।

होता है। इन्हें दोसे गुणा करनेपर सबका जोड़ २८० होता है और तीनसे गुणा करनेपर सबका जोड़ ५७० होता है ॥७२७॥

यहाँसे आगे गुणस्थानोंमें और मार्गणाओंमें गुणस्थान जीवसमास इत्यादि बीस भेदोंकी योजना करते हैं—

वर्धमान स्वामीके मुखरूपी कमलसे निकले सकलश्रुतको ग्रहण और प्रकट करनेमें समर्थ गौतम स्वामीको नमस्कार करके सिद्धान्तालापको कहूँगा।

गुणस्थानोंमें जैसे चौदह गुणस्थानवर्ती जीव हैं। गुणस्थानसे रहित सिद्ध हैं। चौदह जीवसमाससे युक्त जीव हैं उनसे रहित जीव हैं। छह-छह, पाँच-पाँच, चार-चार पर्याप्ति और अपर्याप्तिसे युक्त जीव हैं और उनसे रहित जीव हैं। दस सात, नौ सात, आठ छह, सात पाँच, छह चार, चार तीन, चार दो और एक प्राणके धारी जीव हैं और उनसे रहित जीव हैं। चार संज्ञावाले और उनसे रहित जीव हैं। चार गतिवाले और गतिरहित सिद्ध

के । सं ४ । अ । सा । छे । यथा । द ४ ले २ क । शु ॥
भा ६

सव्वेंसि सुहुमाणं कावोदं सव्वविग्गहे सुक्का ।
सव्वो मिस्सो देहो कवोदवण्णो हवे णियमा ॥

भ २ । सं ५ । मिश्ररुचिरहित सं २ । आ २ । उ १० । विभंग ज्ञानसहित मिथ्यादृष्टिगुण-
स्थानवर्त्तिगळगे गु १ । जो १४ प ६ । ६ । ५ । ५ । ४ । ४ । प्रा १० । ७ । ९ । ७ । ८ । ६ ।
७ । ५ । ६ । ४ । ४ । ३ । सं ४ । ग ४ । इं ५ । का ६ । यो १३ । आहारकद्वयरहित । वे ३ ।
क ४ । ज्ञा ३ । कु । कु । वि । सं । १ । अ । द २ । ले ६ भ २ । सं १ । मि । सं २ । आ २ ।
भा ६
उ ५ । पर्य्याप्तमिथ्यादृष्टिगळगे । गु १ । मि । जो ७ । प ६ । ५ । ४ । प्रा १० । ९ । ८ ।
७ । ६ । ४ ॥

सं ४ । ग ४ । इं ५ । का ६ । यो १० । वे ३ । क ४ । ज्ञा ३ । कु । कु । वि । सं १ । अ ।
द २ । ले द्र ६ । भा ६ । भ २ । सं १ । मि । सं २ । आ १ । उ ५ ॥ अपर्य्याप्तमिथ्यादृष्टिगळगे
गु १ । मि । जि ७ । पर्य्या । ६ । ५ । ४ । प्रा ७ । ७ । ६ । ५ । ४ । ३ । सं । ४ । ग ४ । इं ५ ।
का ६ । यो ३ । औ मि वै मि । कार्म्म । वे ३ । क ४ । ज्ञा २ । सं १ । अ । द २ । ले २ क ।
भा ६
शु । भ २ । सं १ । मि । सं २ । आ २ । उ ४ ॥

सासादनगुणस्थानवर्त्तिगळगे गु १ । सासा । जो २ । प । अ । प ६ । ६ । प्रा १० । ७ ।
सं ४ । ग ४ । इं १ । का १ । त्र । यो १३ । म ४ । वा ४ । औ २ । वै २ । का १ । वे ३ । क ४ ।
ज्ञा ३ । कु । कु । वि । सं १ । अ । द । २ ले ६ द्र भ १ । सं १ । सा सा । सं १ । आ २ ।
६ भा

सं ४ अ सा छे यथा । द ४ ले २ क शु ।
भा ६

भ २ । स ५ । मिश्रं न हि, सं २ । आ २ उ १० । विभङ्गमनःपर्ययौ नहि, सामान्यमिथ्यादृष्टीनां ।
गु १ । जी १४ । प ६ । ६ ५ ५ ४ ४ । प्रा १० ७ ९ ७ ८ ६ ७ ५ ६ ४ ४ ३ । सं ४ । ग ४ । इं ५ ।
का ६ । यो १३ आहारकद्वयं नहि । वे ३ । क ४ । ज्ञा ३ कु कु वि । सं १ अ । द १ । ले ६ । भ २ स १
भा ६
मि । सं २ । आ २ । उ ५ । तत्पर्याप्तानां गु १ । जी ७ । प । ६ ५ ४ प्रा १० ९ ८ ७ ६ ४ । सं ४ ।
ग ४ । इं ५ । का ६ । यो १० । वे ३ । क ४ । ज्ञा ३ कु कु वि । सं १ । अ । द २ । ले ६ । भ २ ।
भा ६
स १ मि । सं २ । आ १ । उ ५ । तदपर्याप्तानां—गु १ । जी ७ । प ६ ५ ४ । प्रा ७ ७ ६ ५ ४ ३ ।
सं ४ । ग ४ । इं ५ । का ६ । यो ३ । औमि । वैमि । का । वे ३ । क ४ । ज्ञा २ । सं १ अ । द २
ले २ । क । शु । भ २ । स १ मि । सं २ । आ २ । उ ४ । सासादनानां—गु १ सासा । जी २ प । अ ।
भा ६
प ६ । ६ । प्रा । १० ७ । सं ४ । ग ४ । इं १ पं । का १ । यो १३ । म ४ । वा ४ । औ २ । वै २ ।
का १ । वे ३ । क ४ । ज्ञा ३ कु, कु, वि । सं १ अ । द २ ले ६ । भ १ । स १ सासा । सं १ आ २ ।
भा ६

असंयतगुणस्थानवर्त्ति अपर्य्याप्ता संयतसम्यग्दृष्टिगळ्गे । गु १ । अ सं । जी १ । अ । प ।
अ । प्रा ७ । अ । सं ४ । ग ४ । इं १ । पं । का-१ । त्र । यो ३ । ओ मि । वै मि । का ।
। नपुं । क ४ । ज्ञा ३ । म । श्रु । अ । सं १ । अ । द ३ । च । अ । अ ले २ क । शु ।
भा ६
। सं ३ । उ वे । क्षा । सं १ । आ २ । उ ६ ॥

देशसंयतगुणस्थानवर्त्तिगळ्गे गु १ । देश । जी १ । प । प ६ । प । प्रा १० । सं ४ ।
। ति । म । इं १ पं । का १ त्र । यो ९ । म ४ । वा ४ । औ का १ । वे ३ । क ४ । ज्ञा ३ ।
म । श्रु । अ । सं १ । देश । द ३ । च । अ । अ । ले ६ भ १ । सं ३ । उ । वे । क्षा । सं १ ।
भा ३
१ । उ ६ ॥

प्रमत्तगुणस्थानवर्त्तिप्रमत्तंगे । गु १ । प्र । जी २ । प । अ । प ६ । ६ प्रा १० । ७ । सं ४ ।
। म । इं १ । पं । का १ त्र । यो ११ । म ४ । व ४ । औ । का १ । आ २ । वे ३ । क ४ ।
४ । म । श्रु । अ । म ४ । सं ३ । सा । छे । प । द ३ । च । अ । अ ले ६ भ १ । सं ३ ।
वे । क्षा । सं १ । आ १ । उ ७ ॥ भा ३

अप्रमत्तगुणस्थानवर्त्ति अप्रमत्तंगे गु १ । अ प्र जी १ । प । प ६ । प । प्रा १० । सं ३ ।
। मै । प । कारणाभावे कार्य्यस्याप्यभावः एंदु सदसद्वेद्यंगळिगे प्रमत्तनोळुदीरणे व्युच्छित्तियादु-
दुदरिंदमाहारसंज्ञे अप्रमत्तनोळु संभविसदु । ग १ । म । इं १ । पं । का १ । त्र । यो ९ ।
४ । वा ४ । औ का १ । वे ३ । क ४ । ज्ञा ४ । म । श्रु । अ । म । सं ३ । सा । छे । प । द ३ ।
। अ । अ ले ६ भ १ । सं ३ । उ । वे । क्षा । सं १ । आ १ । उ ७ ॥
भा ३

अपूर्वकरणगुणस्थानवर्त्तिगळिगे । गु १ । अ । जी १ । प ६ । प्रा १० । सं ३ । ग १ ।

अ । सं १ अ । द ३ च अ अ । ले ६ । भ १ । स ३ उ वे क्षा । सं १ । आ १ । उ ६ । तदपर्याप्तानां-
भा ६
१ असं । जी १ अ । प ६ अ । प्रा ७ अ । सं ४ । ग ४ । इं १ पं । का १ त्र । यो ३ । औमि वैमि
। वे २ न पुं । क ४ । ज्ञा ३ म श्रु अ । सं १ अ । द ३ च अ अ । ले २ क शु । भ १ । स ३ उ
भा ६
क्षा । सं १ । आ २ । उ ६ । देशसंयतानां—गु १ देश । जी १ प । प ६ प । प्रा १० प । सं ४ । ग २
म । इं १ पं । का १ त्र । यो ९ । म ४, वा ४, औका १ । वे ३ । क ४ । ज्ञा ३ म श्रु अ । सं १ देश ।
३ च अ अ । ले ६ । भ १ । स ३ उ वे क्षा । सं १ । आ १ । उ ६ । प्रमत्तानां—गु १ प्र । जी २
भा ६
अ । प ६ ६ । प्रा १० ७ । सं ४ । ग १ म । इं १ पं । का १ त्र । यो ११ । म ४ । वा ४ । औका १,
२ । वे ३ । क ४ । ज्ञा ४ म श्रु अ म । सं ३ सा छे प । द ३ च अ अ । ले ६ । भ १ । स ३ उ वे
भा ३
। सं १ । आ १ । उ ७ । अप्रमत्तानां—गु १ अप्र । जी १ । प ६ प । प्रा १० । सं ३–भ मै प । कारणा-
वे कार्यस्याप्यभावात् सदसद्वेद्यानुदीरणात् अत्र आहारसंज्ञा नहि । ग १ म । इं १ पं । का १ त्र । यो ९
४ व ४ । औका १ । वे ३ । क ४ । ज्ञा ४ म श्रु अ म । सं ३ सा छे प । द ३ च अ अ । ले ६ ।
भा ३
१ । स ३ उ वे क्षा । सं १ । आ १ । उ ७ । अपूर्वकरणानां—गु १ अपू । जी १ । प ६ । प्रा १० ।

सूक्ष्मसांपरायगुणस्थानवर्त्तिसूक्ष्मसांपरायंगे गु १ । सू । जी १ । प ६ । प्रा १० । सं १ । ग १ । इं १ । का १ । यो ९ । वे ० । कषा १ । ज्ञा ४ ॥ सं १ । सू । द ३ । लेश्ये ले ६ भा १ । भ १ । सं २ । उ । क्षा । सं १ । आ १ । उ ७ ॥

उपशांतकषायगुणस्थानवर्त्तिउपशांतकषायंगे । गु १ । उ प । जी १ । प ६ । प्रा १० । सं ० । ग १ । म । इं १ । का १ । यो ९ । वे ० । क ० । ज्ञा ४ । सं १ । यथा । द ३ । ले ६ भा १ । भ १ । सं २ । उ । क्षा । सं १ । आ १ । उ ७ ॥

क्षीणकषायगुणस्थानवर्त्तिक्षीणकषायंगे । गु १ । क्षी । जी १ । प ६ । प्रा १० । सं ० । ग १ । म । इं १ । का १ । यो ९ । वे ० । क ० । ज्ञा ४ ॥ सं १ । यथा । द ३ । ले ६ भा १ । भ १ । सं १ । क्षा । सं १ । आ १ । उ ७ ॥

सयोगिकेवलिगुणस्थानवर्त्ति सयोगकेवलिभट्टारकंगे गु १ । जी २ । प ६ । ६ । प्रा ४ । २ । सं ० । ० । ग १ । म । इं १ । का १ । यो ७ । म २ । व २ । औ २ । का १ । वे ० । क ० । ज्ञा १ । के । सं १ । यथा । द १ । के ले ६ भा १ । भ १ । सं १ । क्षा । सं । ० । आ २ । उ २ ॥

अयोगिकेवलिगुणस्थानवर्त्ति अयोगकेवलिभट्टारकंगे । गु १ । अयो । जी १ । प ६ । प्रा १ । आयुष्य । सं । ० । ग १ । म १ । इं १ । प ० । का १ । त्र । यो ० । वे ० । क ० । ज्ञा १ । के । सं १ । यथा । द १ के छे ६ भा ० भ १ ॥ स १ । क्षा । सं । ० । आ १ । अनाहार । उ २ ॥

अतीतगुणस्थानसिद्धपरमेष्ठिगळ्गे । गु ० जी ० प ० । प्रा ० सं । ० । ग १ । सिद्धिगति ।

छे । द १ । ले ६ भा १ । भ १ । स २ उ क्षा । सं १ । आ १ । उ ७ । सूक्ष्मसांपरायाणां—गु १ सू । जी १ । प ६ । प्रा १० । सं १ प । ग १ म । इं १ । का १ । यो ९ । वे ० । क १ । ज्ञा ४ । सं १ सू । द ३ । ले ६ भा १ । भ १ । स २ उ क्षा । सं १ । आ १ । उ ७ । उपशान्तकषायाणां—गु १ उ । जी १ । प ६ । प्रा १० । सं ० । ग १ म । इं १ । का १ । यो ९ । वे ० । क ० । ज्ञा ४ । सं १ यथा । द ३ । ले ६ भा १ । भ १ । स २ उ क्षा । सं १ । आ १ । उ ७ । क्षीणकषायाणां—गु १ क्षी । जी १ । प ६ । प्रा १० । सं ० । ग १ म । इं १ । का १ । यो ९ । वे ० । क ० । ज्ञा ४ । सं १ यथा । द ३ । ले ६ भा १ । भ १ । स १ क्षा । सं १ । आ १ । उ ७ । सयोगकेवलिनां—गु १ । जी २ । प ६ ६ । प्रा ४ २ । सं ० ग १ म । इं १ । का १ । यो ७ म २ वा २ औ २ का १ । वे ० । क ० । ज्ञा १ के । सं १ यथा । द १ के । ले ६ भा १ । भ १ । स १ क्षा । सं ० । आ २ । उ २ । अयोगकेवलिनां—गु १ अयो । जी १ । प ६ । प्रा १ आयुष्यं । सं ० । ग १ म । इं १ पं । का १ त्र । यो ० । वे ० । क ० । ज्ञा १ के । सं १ यथा । द १ के । ले ६ भा ० । भ १ । स १ क्षा । सं ० । आ १ अनाहार । उ २ । गुणस्थानातीतसिद्धपरमेष्ठिनां—गु ० जी ० ।

सामान्यनारकपर्य्याप्तमिथ्यादृष्टिगळ्गे । गु १ मि । जी १ । पर्य्या । ६ । प्रा १० । सं ४ । ग १ । न । इं १ । का १ । यो ९ । म ४ । वा ४ । वै । का १ । वे १ । ष ० । क ४ । ज्ञा ३ । कु । कु । वि । सं १ । अ । द २ ले १ कृ भ २ । सं १ । मिथ्यारुचि । सं १ । आ १ । उ ५ ॥
भा ३

सामान्यनारकापर्य्याप्तमिथ्यादृष्टिगळ्गे । गु १ । मि । जी १ । अ । प ६ । अ । प्रा ७ । अ । सं ४ । ग १ नरक । इं १ । का १ । यो २ । वै मि । का । वे १ षं ० । क ४ । ज्ञा २ । कु । कु । सं १ । अ । द २ । ले २ क शु भ २ । सं १ । मिथ्यारुचि । सं १ । आ २ । उ ४ ॥
भा ३ अ शु

सामान्यनारकसासादनसम्यग्दृष्टिगळ्गे । गु १ । सा । जी १ । प । प ६ । प्रा १० । सं ४ । ग १ न । इं १ । का १ । यो ९ । म ४ । व ४ । वै का १ । वे षं ० । क ४ । ज्ञा ३ । कु । कु । वि । सं । १ । अ । द २ ले १ कृ भ १ । सं १ । सासादनरुचि । सं १ । आ १ । उ ५ ॥
भा ३

नारकसामान्यमिश्रंगे । गु १ । जि १ । प ६ । प्रा १० । सं ४ । ग १ । न । इं १ । का १ । यो ९ । वे १ । ष ० । क ४ । ज्ञा ३ । मिश्र । सं १ । अ । द ३ । ले १ कृ भ १ । सं १ ।
भा ३
मिश्र । सं १ । आ १ । उ ६ ॥

नारकसामान्यासंयतंगे । गु १ । जी २ । प । अ । प ६ । ६ । प्रा १० । ७ । सं ४ । ग १ । न । इं १ । का १ । यो ११ । म ४ । व ४ । वै २ का १ । वे १ । ष ० । क ४ । ज्ञा ३ । म । श्रु । अ । सं १ । अ । द ३ । ले ३ । कृ । क । शु । भ १ । सं ३ । उ । वे । क्षा । सं १ । आ २ ।
भा ३ अ शु
उ ६ ॥

मि । सं १ । आ २ । उ ५ । तत्पर्याप्तानां—गु १ मि । जी १ । प ६ । प्रा १० । सं ४ । ग १ न । इं १ । का १ । यो ९ । म ४, वा ४, वैका १ । वे १ षं । क ४ । ज्ञा ३ । कु कु वि । सं १ अ । द २ । ले १ कृ ।
भा ३
भ २ । स १ मिथ्यारुचिः । सं १ । आ १ । उ ५ । तदपर्याप्तानां गु १ मि । जी १ अ । प ६ अ । प्रा ७ अ । सं ४ । ग १ न । इं १ । का १ । यो २ । वै मि का । वे १ षं । क ४ । ज्ञा २ कु कु । सं १ अ । द २ ले २ । कृ शु भ २ । स १ मिथ्यारुचि । सं १ । आ २ । उ ४ । सासादनानां—गु १ सा । जी १ प
भा ३
प ६ । प्रा १० । सं ४ । ग १ न । इं १ । का १ । यो ९ म ४, वा ४, वै का १ । वे १ षं । क ४ । ज्ञा ३ कु कु वि । सं १ अ । द २ । ले १ कृ । भ १ । स १ सासादनरुचि । सं १ । आ १ उ ५ । मिश्राणां—
भा ३
गु १ मिश्र । जी १ । प ६ । प्रा १० । सं ४ । ग १ न । इं १ । का १ । यो ९ । वे १ षं । क ४ । ज्ञा ३ मिश्राणि सं १ अ । द २ । ले १ कृ । भ १ । स १ मिश्र । सं १ । आ १ । उ ५ असंयतानां—गु १ [illegible]
भा ३
जी २ प अ । प ६ ६ । प्रा १० ७ । सं ४ । ग १ । इं १ । का १ । यो ११ । म [illegible] १ ।
वे १ षं । क ४ । ज्ञा ३ म श्रु अ । सं १ अ । द ३ ले ३ कृ क शु भ १ । स [illegible] १ ।

घम्मेंय मिथ्यादृष्टिगळ्गे। गु १। जी २। प ६।६। प्रा १०।७। सं ४। ग १। न। इं १। का १। यो ११। म ४। व ४। वै २। का १। वे १। पं ०। क ४। ज्ञा ३। कु। कु। वि। सं १। च। द २। ले ३ कृ क नु भ २। सं १। मि। सं १। आ २। उ ५॥
भा १ क

घम्मेंय नारकपर्य्याप्तकमिथ्यादृष्टिगळ्गे। गु १। जी १। प ६। प्रा १०। सं ४। ग १। न। इं १। का १। यो ९। म ४। वा ४। वै का १। वे १। प ०। क ४। ज्ञा ३। कु। कु। वि। सं। १। अ। द २। ले १ भ २। सं १। मिथ्यारुचि। सं १। आ १। उ ५॥
भा १ क

घम्मेंयनारकापर्य्याप्तकमिथ्यादृष्टिगळ्गे। गु १। जी १। प ६। अ प्रा ७। अ। सं ४। ग १। इं १। का १। यो २। वै मि। का। वे १। कषा ४। ज्ञा २। कु। कु। सं १। अ। द २। ले
भा १ क
२ क शु। भ २। सं १। सं १। आ २। उ ४। कु। कु। च। अ॥

घम्मेंय पर्य्याप्तसासादनंगे गु १। जी १। प ६। प्रा १०। सं ४। ग १। इं १। का १। यो ९। वे १। क ४। ज्ञा ३। कु। कु। वि। सं १। द २। ले १ कृ भ १। स १। सं। आ
भा १ क
१ उ ५॥ कु। कु। वि। च। अ॥

घम्मेंय मिश्रंगे। गु १। जी १। प ६। प्रा १०। सं ४। ग १। इं १। का १। यो ९। वे १। क ४। ज्ञा ३। सं १। द २ ले १ कृ भ १। सं १। सं १। आ १। उ ५।
भा १ क

घम्मेंय असंयतंगे। गु १। जी २। प ६।६। प्रा १०।७। सं ४। ग १। इं १। का १।

तन्मिथ्यादृशां—गु १ जी २। प ६ ६। प्रा १० ७। सं ४। ग १ न। इं १। का १। यो ११। म ४ वा ४ वै २ का १। वे १ पं। क ४। ज्ञा ३ कु कु वि। सं १ अ। द २। ले ३ कृ क शु। भ २। स १
भा १ क
मि। सं १। आ २। उ ५। तत्पर्याप्तानां—गु १। जी १। प ६। प्रा १०। सं ४। ग १ न। इं १। का १। यो ९। म ४, वा ४। वै का १। वे १ पं। क ४। ज्ञा ३ कु कु वि। सं १ अ। द २। ले १ कृ।
भा १ क
भ २। स १ मिथ्यारुचिः। सं १। आ १। उ ५। तदपर्याप्तानां—गु १। जी १। प ६ अ। प्रा ७ अ। सं ४। ग १ न। इं १। का १। यो २। वैमि का। वे १। क ४। ज्ञा २ कु कु। सं १ अ। द २। ले २ क शु। भ २। स १। सं १। आ २। उ ४ कु कु च अ। सासादनानां—गु १। जी १। प ६।
भा १ क
प्रा १०। सं ४। ग १। इं १। का १। यो ९। वे १। क ४। ज्ञा ३ कु कु वि। सं १। द २। ले १ कृ। भ १। स १। सं १। आ १। उ ५ कु कु वि च अ। मिश्राणां—गु १। जी १। प ६।
भा १ क
प्रा १०। सं ४। ग १। इं १। का १। यो ९। वे १। क ४। ज्ञा ३ [illegible] कु वि। सं १। द २। ले १ कृ। भ १। स १। सं १। आ १। उ ५। असंयतानां—गु १ जी २। प ६ ६। प्रा १० ७।
भा १ क

सा। वे। सं २। आ २। उ ८। भ। ष्। ब। कु। कु। प। ब। ब॥

तिर्य्यंचसामान्यमिथ्यादृष्टिगळ्गे। गु १। जी १४। प ६। ६। ५। ५। ४। ४। प्रा १०। ७। ९। ८। ६। ७। ५। ६। ४। ४। ३। सं ४। ग १। इं ५। का ६। यो ११। वे ३। क ४। ज्ञा ३। कु। [illegible]। वि। सं १। अ। द २। च। अ। ले ६/६ भ २। सं १। मि। सं २। आ २। उ ५। कु। कु। वि। च। अ॥

तिर्य्यंचसामान्यपर्य्याप्तमिथ्यादृष्टिगळ्गे। गु १। जी ७। प ६। ५। ४। प्रा १०। ९। ८। ७। ६। ४। सं ४। ग १ ति। इं ५। का ६। यो ९। वे ३। क ४। ज्ञा ३। कु। कु। वि। सं १। अ। द २। ले ६/६। भ २। सं १। मि। सं २। आ १। उ ५॥

तिर्य्यंचसामान्यापर्य्याप्तमिथ्यादृष्टिगळ्गे। गु १। मि। जी ७। अ। प ६। ५। ४। अ। प्रा ७। ७। ६। ५। ४। ३। सं ४। ग १। ति। इं ५। काय ६। यो २। मि। का। वे ३। क ४। ज्ञा २। कु। कु। सं १। अ। द २। च। अ। ले २ क शु / भा ६ अशु भ २। सं १। मि। सं २। आ २। उ ४। कु। कु। च। अ॥

तिर्य्यंचसामान्यसासादनंगे। गु १। जी २। प ६। ६। प्रा १०। ७॥ सं ४। ग १। ति। इं १। का १। यो ११। वे ३। क ४। ज्ञा ३। सं १। द २। ले ६/६ भ १। सं १। सा। सं १। आ २। उ ५। कु। कु। वि। च। अ॥

तिर्यंचसामान्यसासादनपर्य्याप्तंगे। गु १। जी १। प ६। प्रा १०। सं ४। ग १। ति। इं १। पं। का १। यो ९। वे ३। क ४। ज्ञा ३। सं। १। अ। द २। ले ६/६ भ १। सं १।

द १ च अ व। ले २ क शु / भा ६ अशुभ भ २। स ४ मि सा सा वे। सं २। आ २। उ ८। म श्रु अ कु कु च अ। तन्मिथ्यादृष्टी—गु १। जी १४। प ६ ६ ५ ५ ४ ४ प्रा १०। ९। ७ ८ ६ ७ ५ ६ ४ ४ ३। सं ४। ग १। इं ५। का ६। यो ११। वे ३। क ४। ज्ञा ३ कु कु वि। सं १ अ। द २ च अ। ले ६ / भा ६ भ २। स मि, सं २, आ २, उ ५ कु कु वि च अ। तत्पर्याप्तानां—गु १, जी ७, प ६ ५ ४, प्रा १० ९ ८ ७ ६ ४, सं ४, ग १ ति, इं ५, का ६, यो ९, वे ३। क ४ ज्ञा ३ कु कु वि, सं १ अ, द २, ले ६ भ २, / भा ६ स १ मि, स २, आ १, उ ५, तदपर्याप्तानां—गु १ मि, जी ७ अ, प ६ ५ ४ अ, प्रा ७ ७ ६ ५ ४ ३, सं ४, ग १ ति, इं ५, का ६, यो २ मि का, वे ३, क ४, ज्ञा २ कु कु, सं १ अ, द २ च अ, ले २, क शु / भा ६ अशुभ, भ २, स १ मि, सं २, आ २, उ ४ कु कु च अ, तत्सासादनानां—गु १, जी २, प ६ ६, प्रा १० ७, सं ४, ग १ ति, इं १, का १, यो ११, वे ३, क ४, ज्ञा [illegible] १, [illegible] भ १, स १ सा, सं १, आ २, उ ५ कु कु वि च अ, तत्पर्याप्तानां—गु १, [illegible] ६, [illegible] १, १ १ १ प,

सामान्यतिर्य्यंचदेशसंयतंगे। गु १। जो १। प ६। प्रा १०। सं ४। ग १। इं १। का १। यो ९। वे ३। क ४। ज्ञा ३। म। श्रु। अ। सं १। दे। द ३ ले ६ / भा ३ शुभ भ १। सं २। उ। वे। सं १। आ १। उ। ६। म। श्रु। अ। च। अ। अ॥

पंचेंद्रियतिर्य्यंचर्गे। गु ५। जी ४॥ पंचेंद्रियसंज्ञ्यसंज्ञिपर्य्याप्ताऽपर्य्याप्त॥ प ६। ६। प्रा १०। ७। ९। ७। सं ४। ग १। ति। इं १। पं। का १। त्र। यो ११। वे ३। क ४। ज्ञा ६। म। श्रु। अ। कु। कु। वि। सं २। अ दे। द ३। च। अ। अ। ले ६ / ६। भ २। सं ६। उ। वे। क्षा। मि। सा। मि। सं २। आ २। उ ९। म। श्रु। अ। कु। कु। वि। च। अ। अ॥

पंचेंद्रियतिर्य्यंचपर्य्याप्तकर्गे। गु ५। जी २। प ६। ५। प्रा १०। ९। सं ४। ग १। इं १। का १। यो ९। वे ३। क ४। ज्ञा ६। सं २। अ। दे। द ३। च। अ। अ। ले ६ / ६ भ २। सं ६। उ। वे। क्षा। मि। सा। मि। सं २। आ १। उ ९॥

पंचेंद्रियतिर्य्यंचापर्य्याप्तकर्गे। गु ३। मि। सा। अ। जीव २। प ६। ५। अ। प्रा ७। ७। अ। सं ४। ग १। इं १। का १। यो २। मि। का। वे ३। क ४। ज्ञा ५। म। श्रु। अ। कु। कु। सं १। अ। द ३। च। अ। अ। ले २ कु। शु / भा ३। भ २। सं ४। वे। क्षा। मि। सा। सं २। आ २। उ ८। म। श्रु। अ। कु। कु। च। अ। अ। थ॥

पंचेंद्रियतिर्य्यंग्मिथ्यादृष्टिगळ्गे। गु १। जी ४। संज्ञिपर्य्याप्तापर्य्याप्त। असंज्ञिपर्य्याप्तापर्य्याप्त। प ६। ६। ५। ५। प्रा १०। ७। ९। ७। सं ४। ग १। इं १। का १। यो ११। वे ३। क ४। ज्ञा ३। सं १। अ। द २। ले ६ / ६ भ २। सं १। मि। सं। २। आ २। उ ५॥

म १, स २ वे क्षा, सं १, आ २, उ ६ देशसंयतानां—गु १, जी १, प ६, प्रा १०, सं ४, ग १, इं १, का १, यो ९, वे ३, क ४, ज्ञा ३ म श्रु अ, सं १ दे, द ३, ले ६, / भा ३ शुभ भ १, स २ उ वे, सं १, आ १, उ ६ म श्रु अ च अ अ, पञ्चेन्द्रियतिरश्चां—गु ५, जी ४ संज्ञ्यसंज्ञिपर्याप्तापर्याप्ताः, प ६ ६ ५ ५, प्रा १० ७ ९ ७, सं ४, ग १ ति, इं १ पं, का १ त्र, यो ११, वे ३, क ४, ज्ञा ६ म श्रु अ कु कु वि, सं २ अ दे, द ३ च अ अ, ले ६, / भा ६ भ २, स ६, उ वे क्षा मि सा मि, सं २, आ २, उ ९ म श्रु अ कु कु वि च अ अ, तत्पर्याप्तानां—गु ५, जी २, प ६ ५, प्रा १० ९, सं ४, ग १, इं १, का १, यो ९, वे ३, क ४, ज्ञा ६, सं २ अ दे, द ३ च अ अ, ले ६ / भा ६। भ २, स ६ उ वे क्षा मि सा मि, सं २, आ १, उ ९ म श्रु अ कु कु वि च अ थ, तदपर्याप्तानां—गु ३ मि सा अ, जी २, प ६ ५ अ, प्रा ७ ७ अ, सं ४, ग १, इं १, का १, यो २ मि का, वे ३, क ४, ज्ञा ५ म श्रु अ कु कु, सं १ अ, द ३ च अ अ। ले २ क शु, / भा ३ अ... भ २, स ४ वे क्षा मि सा, सं २, आ २, उ ८ म श्रु अ कु कु च अ अ, मिथ्यादृशां—गु १, ... ५ ५, प्रा १० ७ ९ ७, सं ४, ग १, इं १, का १, यो ११, वे ३, क ४, ज्ञा ३, सं १, ... भ २, स १

मो ९। वे ३। क ४। ला ३। मत्यादिमिश्रज्ञानत्रयं। सं १। अ। द २। च। अ। ले ६ / ६ भ १। स १ मिश्र सं १। आ १। उ ५॥

मत्यादिमिश्रज्ञानदोळ चक्षुरचक्षुः॥ पंचेंद्रियसंज्ञिपर्याप्तासंयतंगे। गु १। जी २। प ६। अ ६। प्रा १०। ७। सं ४। ग ११। इं १। का १। यो ११। वे ३। क ४। ला ३। सम्यग्ज्ञानत्रयं सं १। अ। द ३ ले ६ / ६ भ १। सं ३। सं १। आ २। उ ६।। म। श्रु। अ। च। अ। अ॥

पंचेंद्रियतिर्य्यग्संज्ञिपर्याप्तासंयतंगे। गु १। जी १। प ६। प्रा १०। सं ४। ग १। इं १। का १। यो ९। क ४। ला ३। सं १। अ। द ३। ले ६ / ६ भ १। सं ३। उ। वे। ला। सं १। आ १। उ ६॥

पंचेंद्रियतिर्य्यग्पर्याप्तासंयतंगे। गु १। जी १। अ। प ६। अ। प्रा ७। अ। सं ४। ग १। ति। इं १। पं। का १। त्र। यो २। मिश्र। का। वे १। पुं। क ४। ला ३। म। श्रु। अ। सं १। अ। द ३। च। अ। अ ले २ क शु / भा १ क भ १। सं २। क्षा। वे। सं १। आ २। उ ६। म। श्रु। अ। च। अ। अ॥

पंचेंद्रियतिर्य्यग्देशसंयतंगे। गु १। जी १। प ६। प्रा १०। सं ४। ग १। ति। इं १। पं। का १ त्र। यो ९। वे ३। क ४। ला ३। सं १। देशसंयम। द ३ ले ६ / भा ३ भ १। सं २। उ। वे। सं १। आ १। उ ६। म। श्रु। अ। अ। च। अ। अ॥

पंचेंद्रियतिर्य्यग्पर्याप्तकर्गे पंचेंद्रियतिर्य्यग्गर्गे पेळ्दंते पेळ्दुकोळ्ळ॥

वे ३, क ४, ज्ञा ३ मत्यादित्रिमिश्रज्ञानं, सं १ अ, द २ च अ, ले ६ / भा ६, भ १, स १ मिश्र, सं १, आ १, उ ५,

मत्यादित्रिमिश्रज्ञानं चक्षुरचक्षुष। असंयतानां—गु १, जी २, प ६, अ ६, प्रा १०, अ प्रा ७, सं ४, ग १, इं १, का १, यो ११, वे ३, क ४, ज्ञा ३ म श्रु अ, सं १ अ। द ३। ले ६ / भा ६। भ १। स ३। सं १। आ २। उ ६ म श्रु अ च अ अ। तत्पर्याप्तानां—गु १। जी १। प ६। प्रा १०। सं ४। ग १। इं १। का १। यो ९। वे ३। क ४। ज्ञा ३। सं १ अ। द ३। ले ६ / भा ६ भ १। स ३ उ वे क्षा। सं १। आ १। उ ६। तदपर्याप्तानां—गु १ जी १ अ, प ६ अ, प्रा ७ अ, सं ४। ग १ ति, इं १ पं, का १ त्र, यो २ मि का, वे १ पुं, क ४, ज्ञा ३ म श्रु अ, सं १ अ, द ३ च अ अ, ले २ क शु / भा १ क, भ १ स २ क्षा वे, सं १, आ २, उ ६ म श्रु अ च अ अ, देशसंयतानां—गु १, जी १, प ६, प्रा १० सं ४, ग १ ति, इं १, पं १, का १ त्र, यो ९, वे ३, क ४, ज्ञा ३, सं १ दे, द ३, ले ६ / भा ३ शु भ १, स २ उ वे, सं १, आ १, उ ६ म श्रु अ च अ अ, पञ्चेन्द्रियतिर्यगपर्याप्तानां-पञ्चेन्द्रियतिर्यग्वद्भणितव्यम्।

पंचेंद्रियतिर्य्यग्योनिमतिपर्य्याप्तमिथ्यादृष्टिगळ्गे । गु १ । मि । जी २ । संज्ञिपर्य्याप्तासंज्ञि-पर्य्याप्त । प ६ ॥ संज्ञिपर्य्याप्तिगळु ५ ॥ असंज्ञिपर्य्याप्तिगळु प्रा १० । संज्ञि । ९ । असंज्ञि । सं ४ । ग १ । ति । इं १ । पं । का १ । त्र । यो ९ । वे १ । स्त्री । क ४ । ज्ञा ३ । सं १ । अ । द २ । ले ६/६ भ २ । सं १ । मि । सं २ । आ १ । उ ५ ॥

पंचेंद्रियतिर्य्यग्योनिमत्यपर्य्याप्तमिथ्यादृष्टिगळ्गे । गु १ । मि । जी २ । संज्ञ्यपर्य्याप्तासंज्ञ्य-पर्य्याप्त । प ६ । संज्ञ्यपर्य्याप्तिगळु । ५ । असंज्ञ्यपर्याप्तिगळु प्रा ७ । संज्ञि ७ । असंज्ञि । सं ४ ॥ ग १ । इं १ । पं । का १ । त्र । यो २ । मिश्र । का । वे १ । स्त्री । क ४ । ज्ञा २ । कु । कु । सं १ । अ । द २ । च । अ । ले २ क शु / भा ३ अशु भ २ । सं १ । मि । सं २ । आ २ । उ ४ । कु । कु । च । अ ॥

पंचेंद्रियतिर्य्यग्योनिमतिसासादनंगे । गु १ । सा । जी २ । सं । प । अ । प ६ । ६ । प्रा १० । ७ । सं ४ । ग १ ति । इं १ । पं । का १ । त्र । यो ११ । वे १ । स्त्री । क ४ । ज्ञा ३ । सं १ । अ । द २ । ले ६/६ भ १ । सं १ । सा । सं १ । आ २ । उ ५ ॥ ० ॥

पंचेंद्रियतिर्य्यग्योनिमतिसासादनपर्य्याप्तकंगे । गु १ । जी १ । प ६ । प्रा १० । सं ४ । ग १ । इं १ । का १ । यो ९ । वे १ । स्त्री । क ४ । ज्ञा ३ । सं १ । अ । द २ । ले ६/६ भ १ । सं १ । सं १ । आ १ । उ ५ ॥

पंचेंद्रियतिर्य्यग्योनिमत्यपर्य्याप्तसासादनंगे । गु १ । जी १ । प ६ । प्रा ७ । सं ४ । ग १ । इं १ । का । यो २ । मिश्र । का । वे १ । स्त्री । क ४ । ज्ञा २ । सं १ । द २ ले २ क शु / भा ३ अशुभ भ १ । सं १ । सं १ । आ २ । उ ४ । कु । कु । च । अ ॥

मिथ्यात्वं, सं २, आ २, उ ५ कु कु वि च अ, तत्पर्याप्तानां—गु १ मि, जी २ संज्ञ्यसंज्ञिपर्याप्तौ, प ६ संज्ञि ५ असंज्ञि, प्रा १० सं, ९ असंज्ञि, सं ४, ग १ ति, इं १ पं, का १ त्र, यो ९, वे १ स्त्री, क ४, ज्ञा ३ कु कु वि, सं १ अ, द २, ले ६/६, भ २, स १ मि, सं २, आ १, उ ५, तदपर्याप्तानां—गु १ मि, जी २ संज्ञ्य-संज्ञिपर्याप्तौ, प ६ संज्ञ्यपर्याप्तयः, ५ असंज्ञ्यपर्याप्तयः, प्रा ७ सं, ७ असंज्ञि, सं ४, ग १ ति, इं १ पं, का १ त्र, यो २ मिश्र, का, वे १ स्त्री, क ४, ज्ञा २ कु कु, सं १ अ, द २ च अ, ले २ क शु / भा ३ अशु, भ २, स १ मि, सं २, आ २, उ ४, कु कु च अ, सासादनानां—गु १ सा, जी २ सं प अ, प ६ ६, प्रा १०, ७, सं ४, ग १ ति, इं १ पं, का १ त्र, यो ११, वे १ स्त्री, क ४, ज्ञा ३, स १ अ, द २, ले ६/६, भ १, स १ सा, सं १, आ २, उ ५, तत्पर्याप्तानां—गु १, जी १, प ६, प्रा १०, सं ४, ग १, इं १, का १, यो ९, वे १ स्त्री, क ४, ज्ञा ३, सं १ अ, द २, ले ६/६ भ १, स १, सं १, आ १, उ ५, तदपर्याप्तानां—गु १, जी १। प ६। प्रा ७, सं ४, ग १, इं १, का १, यो २ मि का, वे १ स्त्री, क ४, ज्ञा २, सं १ अ, द २,

का १। यो ११। वे ३। क ४। ज्ञा ८। सं ७। द ४। ले ६ भ २। सं ६। सं १।
६
आ २। उ १२॥

सामान्यमनुष्यापर्य्याप्तकर्गे। गु ५। मि। सा। अ। प्र। स। जो १। प ६। अ। प्रा ७। अ। सं ४। ग १। इं १। का १। यो ३। औदारिकमिश्र आहारकमिश्र कार्म्मण। वे ३। क ४। ज्ञा ६। म भु। अ। के। कु। कु। सं ४। अ। सा। छे। यथाख्यात। द ४। ले क शु भ २।
भा ६
सं ४। मि। सा। वे। क्षा। सं १। आ २। उ १०॥ कु। कु। म। श्रु। अ। के। च। अ। अ। के॥

सामान्यमनुष्यमिथ्यादृष्टिगळ्गे। गु १। जी २। प ६। ६। प्रा १०। ७। सं ४। ग १। इं १। का १। यो ११। म ४। व ४। औ २। का १। वे ३। क ४। ज्ञा ३। सं १। अ। द २। च। अ ले ६ भ २। सं १। मि। सं १। आ २। उ ५॥
६

सामान्यमनुष्यपर्याप्तमिथ्यादृष्टिगळ्गे। गु १। जी १। प ६। प्रा १०। सं ४। ग १। म। इं १। पं। का १। त्र। यो ९। वे ३। क ४। ज्ञा ३। सं १। अ। द २ ले ६ भ २। सं १।
६
मि। सं १। आ १। उ ५॥

सामान्यमनुष्यापर्य्याप्तमिथ्यादृष्टिगळ्गे। गु १। जी १। प ६। अ प्रा ७। अ सं ४। ग १। म। इं। पं। का १। त्र। यो २। औ मि का १। वे ३। क ४। ज्ञा २। सं १। द २ ले २। क। शु। भ २। सं १। मि। सं १। आ २। उ ४॥
भा ३। अशुभ

ग १, इं १, का १, यो १०, वे ३, क ४, ज्ञा ८, सं ७, द ४, ले ६, भ २, सं ६, सं १, आ २, उ १२,
भा ६
तदपर्याप्तानां—गु ५, मि सा अ प्र स, जी १, प ६ अ, प्रा ७ अ, सं ४, ग १, इं १, का १, यो ३, औमि आमि का, वे ३, क ४, ज्ञा ६ म श्रु अ के कु कु, सं ४ अ सा छे यथाख्यात, द ४, ले २ क शु, भ २,
भा ६
स ४ मि सा वे क्षा, सं १ आ २, उ १० कु कु म श्रु अ के च अ अ के, तन्मिथ्यादृशां—गु १, जी २, प ६ ६, प्रा १० ७, सं ४, ग १, इं १, का १, यो ११ म ४ व ४ औ २ का १, वे ३, क ४, ज्ञा ३, सं १ अ, द २ च अ, ले ६, भ २, सं १ मि, सं १, आ २, उ ५, तत्पर्याप्तानां—गु १, जी १, प ६, प्रा १०,
६
सं ४, ग १ म, इं १ पं, का १ त्र, यो ९, वे ३, क ४, ज्ञा ३, सं १ अ, द २, ले ६, भ २, स १ मि.
भा ६
सं १, आ १, उ ५, तदपर्याप्तानां—गु १ जी १, प ६ अ, प्रा ७ अ, सं ४, ग १ म, इं १ पं, का १ त्र, यो २ औमि का, वे ३, क ४, ज्ञा २, सं १, द २, ले २ क शु, भ २, स १ मि, सं १, आ २, उ ४।
भा ३ अशुभ.

सं १। आ १। उ ६। म। भ्यु। अ। घ। अ। अ॥

सामान्यमनुष्यापर्याप्तासंयतंगे। गु १। अ। जी १। प ६। अ। प्रा ७। अ। सं ४। ग १। म। इं १। पं। का १ त्र। यो २। मि। का। वे १। पु। क ४। ज्ञा ३। म। श्रु। अ। सं १। अ। द ३। च। अ। अ। ले २ क शु। भ १। सं २। वेक्षा। सं १। आ २। उ ६॥ भा ६

सामान्यमनुष्यसंयतासंयतंगे गु १। जी १। प ६। प्रा १०। सं ४। ग १। म। इं १। पं। का १ त्र। यो ९। वे ३। क ४। ज्ञा ३। सं १। दे। द ३। ले ६। भ १। सं ३। सं १। भा ३ शुभ आ १। उ ६॥

सामान्यमनुष्यप्रमत्तंगे। गु १। जी २। प ६। ६। प्रा १०। ७। सं ४। ग १। म। इं १। का १। यो ११। म ४। व ४। औ का १। आ २। वे ३। द्रव्यदिंदं पुंवेदो। भावापेक्षे-यिदं स्त्रीपुन्नपुंसक। क ४। ज्ञा ४। सं ३। द ३। ले ६। भ १। सं ३। सं १। आ १। उ ७। भा ३ शुभ म। श्रु। अ। म। च। अ। अ॥

सामान्यमनुष्यप्रमत्तपर्याप्तर्गे। गु १। प्र जी १। प ६। प। प्रा १०। प। सं ४। ग १। म। इं १। पं। का १। त्र। यो १०। म ४। व ४। औ १। आ १। वे ३। क ४। ज्ञा ४। म। श्रु। अ। म। सं ३। सा। छे। प। द ३। च। अ। अ। ले ६ भ १। सं ३। सं १। आ १। उ ७। म। श्रु। अ। म। च। अ। अ॥ भा ३ शु

सामान्यमनुष्यप्रमत्तापर्याप्तकर्गे गु १। १। जी १ अ। प ६। अ। प्रा ७। अ। सं ४।

द १, ले ६, भ १, स १ द वे क्षा, सं १, आ १, उ ६ म श्रु अ च अ अ। तत्पर्याप्तानां—गु १ अ। जी १, प ६ अ। प्रा ७ अ। सं ४। ग १ म। इं १ पं। का १ त्र। यो २ मि का। वे १ पु। क ४। ज्ञा ३ म श्रु अ। सं १ अ। द ३ च अ अ। ले २ क शु, भ १। स २ वे क्षा। सं १। आ २, उ ६। तत्पर्याप्तानां— भा ६ गु १। जी १। प ६। प्रा १०। सं ४। ग १। म। इं १। पं। का १ त्र। यो ९। वे ३। क ४। ज्ञा ३। सं १। द ३। ले ६। भ १। स ३। सं १। आ १। उ ६। प्रमत्तानां—गु १। जी २। प ६ ६। प्रा भा ३ शुभ १० ७। सं ४। ग १ म। इं १ पं। का १ त्र। यो ११ म ४ व ४ औ १ आ २। वे ३। द्रव्यपुंवेदिनः भावापेक्षया त्रिवेदिनः इत्यर्थः। क ४। ज्ञा ४। सं ३। द ३। ले ६। भ १। स ३। सं १। आ १। उ भा ३ शुभ ७ म श्रु अ म च अ अ। तत्पर्याप्तानां—गु १ प्र। जी १ प। प ६ प। प्रा १० प। सं ४। ग १ म। इं १ पं। का १ त्र। यो १० म ४ व ४ औ १ आ १। वे ३। क ४। ज्ञा ४ म श्रु अ म। सं ३ सा छे प। द ३ च अ अ। ले ६। भ १। स ३। सं १। आ १। उ ७ म श्रु अ म च अ अ। [illegible] नाम—गु भा ३ शु

ग १। ई १। का १। यो ९। वे ०। क ३। मा। मा। लो। ज्ञा ४। सं २। छा। छे। द ३। ले ६ भ १। स २। उ। क्षा। सं १। सं १। आ १। उ ७॥
भा १

सामान्यमनुष्यचतुर्थभागानिवृत्तिगे। गु १। जी १। प ६। प्रा १०। सं १। परिग्रह। ग १। इ १। का १। यो ९। वे ०। क २। माया। लो। ज्ञा ४। सं २। द ३। ले ६ भ १।
भा १
सं २। स १। आ १। उ ७॥

सामान्यमनुष्यपंचमभागानिवृत्तिगे। गु १। जी १। प ६। प्रा १०। सं १। ग १। इं १। का १। यो ९। वे ०। क १। लोभ। ज्ञा ४। सं २। द ३। ले ६ भ १। सं २। गे १।
भा १
आ १। उ ७॥

सामान्यमनुष्यसूक्ष्मसांपरायंगे गु १। सू। जी १। प ६। प्रा १०। सं १। परिग्रह। ग १। ई १। का १। यो ९। वे ०। क १। लो। ज्ञा ४। सं १। सू। द ३। ले ६ भ १। सं २। उ। क्षा। सं १। आ १। उ ७॥
भा १

सामान्यमनुष्योपशांतकषायंगे। गु १। उ। जी १। प ६। प्रा १०। सं। ०। ग १। ई १। का १। यो ९। वे ०। क ०। ज्ञा ४। सं १। यथाख्यात। द ३। ले ६ भ १। सं २। उ। क्षा। सं १। आ १। उ ७॥
भा १

सामान्यमनुष्यक्षीणकषायंगे। गु १। जी १। प ६। प्रा १०। सं। ०। ग १। इं १। का १। यो ९। वे ०। क ०। ज्ञा ४। सं १। यथाख्यात। द ३। ले ६ भ १। सं १। क्षा। सं १। आ १। उ ७॥
भा १

गु १। जी १। प ६। प्रा १०। सं १ परिग्रह। ग १। ई १। का १। यो ९। वे ०। क १ मा माया लो। ज्ञा ४। सं २ छा छे। द ३। ले ६। भ १। स २ उ क्षा। सं १। आ १। उ ७। चतुर्थंगळे—
भा १
गु १। जी १। प ६। प्रा १०। सं १ परिग्रह। ग १। इं १। का १। यो ९। वे ०। क १ लोभ। ज्ञा ४। सं २। द ३। ले ६। भ १। स २। सं १। आ १। उ ७। पंचमभागे—गु १। जी १। प ६।
भा १
प्रा १०। सं १। ग १। इ १। का १। यो ९। वे ०। क १ लो। ज्ञा ४। स २। द ३। ले ६। भ १।
भा १
स २। सं १। आ १। उ ७। सूक्ष्मसांपराये—गु १ सू। जी १। प ६। प्रा १०। सं १ परिग्रह। ग १। ई १। का १। यो ९। वे ०। क १ लो। ज्ञा ४। सं १ सू। द ३। ले ६। भ १। स २ उ क्षा। सं १।
भा १
आ १। उ ७। उपशांतकषाये—गु १ उ। जी १। प ६। प्रा १०। सं ०। ग १। इं १। का १। यो ९। वे ०। क ०। ज्ञा ४। सं १ यथाख्यात। द ३। ले ६। भ १। स २ उ क्षा। सं १। आ १। उ ७।
भा १
क्षीणकषाये गु १। जी १। प ६। प्रा १०। सं ०। ग १। इं १। का १। यो ९। वे ०। क ०। ज्ञा ४।

मनःपर्य्ययज्ञानोपयोगं । स्त्रीवेदगळप्प संक्लिष्टरोळु संभविसवप्पुदरिंदं । अपर्य्याप्तमानुषि-यर्ग्गे । गु २ । मि । सा । सयोग । जी १ । प ६ । अ प्रा ७ ॥ अ । सं ४ । ० । संज्ञारहितर । ग १ । इं १ । का १ । यो २ । मि । का । ० । अयोगरं । वे १ । स्त्री । ० । अवेदरं । क ४ । ० । अकषायरं । ज्ञा ३ । कु । कु । के । सं २ । अ । यथाख्यातमुं । द ३ । अ । च । के । ले २ । क । शु

भा ४ अ ३ शु १

भ २ । स ३ । मि । सा । क्षा । सं । १ । ० । संज्ञित्वशून्यरं । आ २ । उ ६ । कु । कु । के । अ । अ । के ॥

मानुषिमिथ्यादृष्टिगळगे । गु १ । जी २ । प ६ । ६ । प्रा १० ७ । सं ४ । ग १ । इं १ । का १ । यो ११ । वे २ । आ २ । शून्यं । वे १ । स्त्री । क ४ । ज्ञा ३ । कु । कु । वि । सं १ । आ । द २ । च । अ । ले ६ । भ २ । सं १ । मि । सं १ । आ २ । उ ५ । कु । कु । वि । च । अ ॥

६

पर्य्याप्तमानुषिमिथ्यादृष्टिगे—गु १ । मि जी १ । प ६ । प्रा १० । सं ४ । ग १ । इं १ । का १ । यो ९ । वे १ । स्त्री । क ४ । ज्ञा ३ । कु । कु । वि । सं १ । अ । द २ । ले ६ भ २ ।

६

सं १ । मि । सं १ । आ १ । उ ५ ॥

अपर्य्याप्तमानुषिमिथ्यादृष्टिगे—गु १ । जी १ । प ६ । प्रा ७ । अ । सं ४ । ग १ । इं १ । का १ । यो २ । मि । का । वे १ । स्त्री । क ४ । ज्ञा २ । सं १ । अ । द २ । ले २ क । शु । भ २ ।

भा ३ अशुभ

सं १ । मि । सं १ । आ २ । उ ४ ॥

मानुषिसासादनंगे—गु १ । सा । जी २ । प ६ । ६ । प्रा १० । ७ । सं ४ । ग १ । इं १ । का १ । यो ११ । वे १ । स्त्री । क ४ । ज्ञा ३ । कु । कु । वि । सं १ । अ । द २ । ले ६ भ १ ।

६

---

१ शून्यं च । आ २ । उ ११ । मनःपर्ययः स्त्रीवेदिषु नहि संक्लिष्टपरिणामित्वात् । तदपर्याप्तानां—गु ३ मि सा सयोगः । जी १ । प ६ अ । प्रा ७ अ । सं ४ शून्यं च । ग १ । इं १ । का १ । यो २ मि का शून्यं च । वे १ स्त्री । शून्यं च । क ४ । शून्यं च । ज्ञा ३ कु कु के । सं २ अ य । द ३ च अ के । ले २ क शु

भा ४ अ शु ३ शु १

भ २ । स ३ मि सा क्षा । सं १ शून्यं च । आ २ । उ ६ कु कु के च अ के । मानुषीमिथ्यादृशां—गु १ । जी २ । प ६ ६ । प्रा १० ७ । सं ४ । ग १ । इं १ । का १ । यो ११ । वैक्रियिकद्वयाहारकद्वयं नहि । वे १ स्त्री । क ४ । ज्ञा ३ कु कु वि । सं १ अ । द २ च अ । ले ६ । भ २ । स १ मि । सं १ । आ २ । उ ५

६

कु कु वि च अ । तत्पर्याप्तानां—गु १ मि । जी १ । प ६ । प्रा १० । सं ४ । ग १ । इं १ । का १ । यो ९ । वे १ स्त्री । क ४ । ज्ञा ३ कु कु वि । सं १ अ । द २ । ले ६ । भ २ । स १ मि । सं १ । आ १ । उ ५ ।

६

तदपर्याप्तानां—गु १ मि । जी १ । प ६ अ । प्रा ७ अ । सं ४ । ग १ । इं १ । का १ यो २ मि का । वे १ स्त्री । क ४ । ज्ञा २ । सं १ अ । द २ । ले २ क शु । भ २ । स १ मि । सं १ । आ २ । उ ४ । सासा-

३ अशुभ

दनानां—गु १ सा । जी २ । प ६ ६ । प्रा १० ७ । सं ४ । ग १ । इं १ । का १ । यो ११ । वे १ स्त्री ।

स्त्रीपुंनपुंसकवेदोदयंगळिवं। आहारद्धिकं मनःपर्य्ययज्ञानं परिहारविशुद्धिसंयममुमिल्ल। सं २। सा छे। व ३। ले ६। भ १। सं ३। उ। वे। क्षा। सं १। आ १। उ ६॥
भा ३

मानुष्यप्रमत्तसंयतग्गें। गु १। जि १। प ६। प्रा १०। सं ३। आहारसंज्ञे शून्यं। ग १। इं १। का १। यो ९। वे १। स्त्री। क १। ज्ञा ३। सं २। व ३। ले ६। भ १। स ३। सं १।
भा ३
आ १। उ ६॥

मानुष्यपूर्व्वकरणग्गें। गु १। जी १। प ६। प्रा १०। सं ३। ग १। इं १। का १। यो ९। ये १। स्त्री। क ४। ज्ञा ३। सं २। सा छे। द ३। च। अ। अ। ले ६। भ १। सं २।
भा १
उ। क्षा। सं १। आ १। उ ६॥

मानुषिप्रथमभागानिवृत्तिगग्गें।। गु १। जी १। प ६। प्रा १०। सं २। मैथु। प। ग १। इं १। का १। यो ९। वे १। स्त्री। क ४। ज्ञा ३। सं २। सा। छे। द ३। ले ६ भ १।
भा १
सं २। उ। क्षा। सं १। आ १। उ ६॥

मानुषिद्वितीयानिवृत्तिगळ्गे। गु १। जी १। प ६। प्रा १०। सं १। ग १। इं १। का १। यो ९। वे ०। क ४। ज्ञा ३। सं २। द ३। ले ६। भ १। सं २। उक्षा। सं १। आ १। उ ६॥
भा १

यो ९। वे १ स्त्री। क ४। ज्ञा ३। सं १ दे। द ३। ले ६ भ १। स ३। सं १। आ १। उ ६।
भा ३ अशु
प्रमत्तस्य—गु १। जी १। प ६। प्रा १०। सं ४। ग १। इं १। का १। यो ९, वे १ स्त्री, क ४, ज्ञा ३, स्त्रीनपुंसकोदये आहारकर्द्धिमनःपर्ययपरिहारविशुद्धयो नहि सं २ सा छे, द ३। ले ६, भ १, स ३
३
उ वे क्षा, सं १, आ १, उ ६, अप्रमत्तस्य—गु १, जी १, प ६, प्रा १०, सं ३ आहारसंज्ञा नहि, ग १, इं १, का १, यो ९, वे १ स्त्री, क ४, ज्ञा ३, सं २, द ३, ले ६। भ १, स ३, सं १, आ १, उ ६, अपूर्व-
भा ३
करणानां—गु १, जी १, प ६, प्रा १०, सं ३, ग १, इं १, का १, यो ९, वे १ स्त्री, क ४, ज्ञा ३, सं २ सा छे, द ३ च अ अ, ले ६। भ १, स २ उ क्षा, सं १, आ १, उ ६, अनिवृत्तेः प्रथमभागे—गु १, जी १,
भा १
प ६, प्रा १०, सं २ मै प, ग १, इं १, का १, यो ९, वे १ स्त्री, क ४, ज्ञा ३, सं २ सा छे, द ३, ले ६।
भा १
भ १, स २ उ क्षा, सं १। आ १। उ ६, द्वितीयभागे—गु १, जी १, प ६, प्रा १०, सं १ परिग्रहः ग १, इं १, का १, यो ९, वे ०, क ४, ज्ञा ३, सं २, द ३, ले ६। भ १, स २ उ क्षा, सं १, आ १, उ ६,
भा १

मानुषिक्षीणकषायंगे। गु १। जो १। प ६। प्रा १०। सं ०। ग १। इं १। का १। यो ९। वे ०। क ०। ज्ञा ३। सं १। यथा। द ३। ले ६। भ १। सं १। क्षा। सं १।
भा १
आ १। उ ६।

मानुषिसयोगकेवलिये। गु १। जी २। प ६। ६। प्रा ४। २। अ। सं ०। ग १। इं १। का १। यो ७। म २। व २। औ २। का १। वे ०। क ०। ज्ञा १। के। सं १। यथा। द १। के ले ६। भ १। सं १। क्षा। सं ०। आ २। उ २। के। के॥
भा १

मानुषिअयोगिकेवलिजिनंगे। गु १। जो १। प ६। प्रा १। आयुष्य। सं ०। ग १। इं। ०। का १। यो ०। वे ०। क ०। ज्ञा १। सं १। द १। ले ६ भ १। सं १। क्षा। सं। ०।
भा ०
आ १। अनाहार। उ २। के॥

मनुष्यलब्ध्यपर्य्याप्तकर्ग्गे। गु १। मि। जी १। अ। प ६। अ। प्रा ७। अ। सं ४। ग १। इं १। का १। यो २। मि। का। वे १। षंढ। क ४। ज्ञा २। कु। कु। सं १। असंयम। द २। च। अ। ले २ क। शु। भ २। सं १। मि। सं १। आ २। उ ४॥
भा ३ अशुभ

इंतु मनुष्यगति समाप्तमादुदु ॥

देवगतियोळु देवर्क्कळो पेळल्पडुवल्लि। गु ४। जी २। प ६। प्रा १०। ७। सं ४। ग १। दे। इं १। का १। त्र। यो ११। म ४। व ४। वै २। का १। वे २। स्त्री। पुं ०। क ४। ज्ञा ६। म श्रु अ। कु। कु। वि। सं १। अ। द ३। च। अ। अ। ले ६ भ २। सं ६। सं १। आ २।
भा ६
उ ९। म। श्रु। अ। कु। कु। वि। च। अ। अ॥

सं १। आ १। उ ६। क्षीणकषायस्य—गु १। जी १। प ६। प्रा १०। सं ०। ग १। इं १। का १ यो ९। वे ०। क ०। ज्ञा ३ सं १ य। द ३ ले ६। भ १। स १ यथा। सं १। आ १। उ ६। संयोगस्य—
भा १
गु १। जी २। प ६। ६। प्रा ४ २। सं ०। ग १। इं १। का १। यो ७ म २ वा २ औ २। का १। वे ०। क ०। ज्ञा १। के। सं १ य। द १ के। ले ६। भ १। स १ क्षा। सं १। आ २। उ २ के के।
भा १
अयोगस्य—गु १। जी १। प ६। प्रा १ आयुः। सं ०। ग १। इं १। का १। यो ०। वे ०। क ०। ज्ञा १ के। सं १। द १ ले ६। भ १। स १ क्षा। सं ०। आ १ अनाहार। उ २ के के। मनुष्यलब्ध्य-
भा ०
पर्याप्तानां—गु १ मि। जी १ अ। प ६ अ। प्रा ७ अ। सं ४। ग १। इं १। का १। यो २ मि का। वे १ षं। क ४। ज्ञा २ कु कु। सं १ अ। द २ च अ। ले २ क शु। भ २। स १ मि। सं १।
भा ३ अशुभ
आ २। उ ४। देवगतौ—गु ४। जी २। प ६ ६। प्रा १० ७। सं ४। ग १ दे। इं १ पं। का १ त्र। यो ११ म ४। वा ४ २। का १ वैं। वे २ स्त्री पुं। क ४। ज्ञा ६ म श्रु अ कु कु वि। सं १ अ। द ३

देवसामान्यसासादनंगे। गु १। सा। जी २। प ६। ६। प्रा १०। ७। सं ४। ग १। इं १। का १। यो ११। वे २। क ४। ज्ञा ३। कु। कु। वि। सं १। अ। द २ ले ६। भ १।
भा ६
सं १। सा। सं १। आ २। उ ५॥

देवसामान्यसासादनपर्य्याप्तकग्गें। गु १। जी १। प ६। प्रा १०। सं ४। ग १। इं १। का १। यो ९। वे २। क ४। ज्ञा ३। सं १। अ। द २। ले ६। भ १। सं १। सा। सं १।
भा ३ शु
आ १। उ ५॥

देवसामान्यसासादनापर्य्याप्तकग्गें। गु १। जी १। प ६। अ। प्रा ७। अ। सं ४। ग १। इं १। का १। यो २। मि। का। वे २। क ४। ज्ञा २। सं १। द २। ले २ क। शु। भ १।
भा ६
सं १। सा। सं १। आ २। उ ४॥

देवसामान्यसम्यग्मिथ्यादृष्टिगळ्गे। गु १। जी १। प ६। प्रा १०। सं ४। ग १। इं १। का १। यो ९। वे २। क ४। ज्ञा ३। सं १। अ। द २। ले ६। भ १। सं १। मिश्र। सं १।
भा ३
आ १। उ ५॥

देवसामान्यासंयतग्गें। गु १। जी २। प ६। ६। प्रा १०। ७। सं ४। ग १। इं १। का १। यो ११। वे २। क ४। ज्ञा ३। म। श्रु। अ। सं। अ। द ३। ले ६ भ १। सं ३।
भा ३
सं १। आ २। उ ६॥

का। वे २। क ४। ज्ञा २। सं १ अ। द २। ले २ क शु। भ २। स १ मि। सं १। आ २। उ ४
भा ६
कुकुच अ। सासादनानां—गु १ सा। जी २। प ६ ६। प्रा १० ७। सं ४। ग १। इं १। का १। यो ११। वे २। क ४। ज्ञा ३ कु कु वि। सं १ अ। द २ ले ६। भ १। स १ सा। सं १। आ २। उ ५।
भा ६
तत्पर्याप्तानां—गु १। जी १। प ६। प्रा १०। सं ४। ग १। इं १। का १। यो ९। वे २। क ४। ज्ञा ३। सं १ अ। द २। ले ६। भ १। स १ सा। सं १। आ १। उ ५। तदपर्याप्तानां गु १ जी १ अ। प ६ अ। प्रा ७ अ। सं ४। ग १। इं १। का १। यो २ मि का। वे २। क ४। ज्ञा २। सं १। द २।
३ शु
ले २ क शु। भ १। स १ सा। सं १। आ २। उ ४। सम्यग्मिथ्यादृष्टां-गु १। जी १। प ६। प्रा १०।
६
सं ४। ग १। इं १। का १। यो ९। वे २। क ४। ज्ञा ३। सं १ अ। द ३। ले ६। भ १। स १
भा ३
मिश्र। सं १। आ १। उ ५। असंयतानां—गु १। जी २। प ६ ६। प्रा १० ७। सं ४। ग १। इं १। का १। यो ११। वे २। क ४। ज्ञा ३ म श्रु अ। सं १ अ। द ३ ले ६। भ १। स ३। सं १। आ २।
३

भवनत्रयमिथ्यादृष्टिगळ्गे। गु १। मि। जी २। प ६। ६। प्रा १०। ७। सं ४। ग १।
इं १। का १। यो ११। वे २। क ४। ज्ञा ३। सं १। द २। ले ६ भ २। सं १। मि। सं १।
भा ४
आ २। उ ५॥

भवनत्रयपर्य्याप्तमिथ्यादृष्टिगळ्गे। गु १। जी १। प ६। प्रा १०। सं ४। ग १। इं १।
का १। यो ९। वे २। क ४। ज्ञा ३। सं १। द २। ले ६ भ २। स १। मि। सं १।
भा १
आ १। उ ५॥

भवनत्रयापर्य्याप्तमिथ्यादृष्टिगळ्गे। गु १। जी १। प ६। अ। प्रा ७। अ। सं ४। ग १।
इं १। का १। यो २। क ४। ज्ञा २। सं १। द २। ले २। क शु भ २। सं १। मि। सं १।
भा ३ अ शु
आ २। उ ४॥

भवनत्रयसासादनंगे गु १। सा। जी २। प ६। ६। प्रा १०। ७। सं ४। ग १। इं १।
का १। यो ११। वे २। क ४। ज्ञा ३। सं १। अ। द २। ले ६ भ १। सं १। सा। सं १।
भा ४
आ २। उ ५॥

भवनत्रयसासादनपर्य्याप्तकर्गे। गु १। जी १। प ६। प्रा १०। सं ४। ग १। इं १।
का १। यो ९। वे २। क ४। ज्ञा ३। सं १। द २। ले ६ भ १। सं १। सा। सं १।
भा १
१
आ २। उ ५॥

भवनत्रयसासादनापर्य्याप्तकर्गे। गु १। जी १। प ६। अ। प्रा ७। अ सं ४। ग १।
इं १। का १। यो २। वे २। क ४। ज्ञा २। सं १। द २। ले २ क शु भ १। सं १। सा।
भा ३ अशुभ
सं १। आ २। उ ४॥

मिथ्यादृशां—गु १ मि, जी २, प ६ ६, प्रा १० ७, सं ४, ग १, इं १, का १, यो ११, वे २, क ४,
ज्ञा ३, सं १, द २, ले ६, भ २, स १ मि, सं १, आ २, उ ५, तत्पर्याप्तानां—गु १ जी १, प ६, प्रा १०,
भा ४
सं ४, ग १, इं १ का १, यो ९, वे २, क ४, ज्ञा ३, सं १, द २ ले ६, भ २, स १ मि, सं १, आ १, उ ५,
१
तदपर्याप्तानां—गु १, जी १, प ६ ७, प्रा १० अ, सं ४, ग १, इं १, का १, यो २ मि का, वे २, क ४,
ज्ञा २, सं १, द २, ले २ क शु भ २, स १ मि, सं १, आ २, उ ४, सासादनानां—गु १ सा, जी २,
भा ३ अशु
प ६ ६, प्रा १० ७, सं ४, ग १, इं १, का १, यो ११, वे २, क ४, ज्ञा ३, सं १ अ, द २, ले ६ भ १,
भा ४
स १ सा, सं १, आ २, उ ५, तत्पर्याप्तानां—गु १, जी १, प ६, प्रा १०, सं ४, ग १, इं १, का १, यो
९, वे २, क ४, ज्ञा ३, सं १, द २, ले ६, भ १, स १ सा, सं १, आ १, उ ५, तदपर्याप्तानां—गु १,
भा १
जी १, प ६ अ, प्रा ७ अ, सं ४, ग १, इं १, का १, यो २, वे २, क ४, ज्ञा २, सं १, द २, ले २,

सौधर्म्मद्वयमिथ्यादृष्टिपर्य्याप्तकर्गे । गु १। जी १। प ६। प्रा १०। सं ४। ग १। इं १। का १। यो ९। वे २। क ४। ज्ञा ३। सं १। द २। ले १ भ २। सं १। मि। सं १।
भा १
आ १। उ ५॥

सौधर्म्मद्वयमिथ्यादृष्टि अपर्य्याप्तकर्गे । गु १। जी १। प ६। अ। प्रा ७। अ। सं ४। ग १। इं १। का १। यो २। वे २। क ४। ज्ञा २। सं १। द २। ले २ भ २। सं १। मि।
भा १
सं १। आ २। उ ४॥

सौधर्म्मद्वयसासादनंगे । गु १। जी २। प ६। ६। प्रा १०। ७। सं ४। ग १। इं १। का १। यो ११। वे २। क ४। ज्ञा ३॥ सं १। द २ ले ३ भ १। सं १। सा। सं १।
भा १
आ २। उ ५॥

सौधर्म्मद्वयपर्य्याप्तसासादनंगे। गु १ सा। जी १। प ६। प्रा १०। सं ४। ग १। इं १। का १। यो ९। वे २। क ४। ज्ञा ३। सं १। द २। ले १ भ १। सं १। सं १। आ १। उ ५॥
भा १

सौधर्म्मद्वयसासादनापर्य्याप्तकर्गे । गु १। जी १। प ६। अ। प्रा ७। अ। सं ४। ग १। इं १। का १। यो २। मि। का। वे २। क ४। ज्ञा २। सं १। द २। ले २ क शु भ १।
भा १
सं १। सा। सं १। आ २। उ ४॥

सौधर्म्मद्वयसम्यग्मिथ्यादृष्टिगळ्गे। गु १। जी १। प ६। प्रा १०। सं ४। ग १। इं १। का १। यो ९। वे २। क ४। ज्ञा ३। सं १। द २ ले १ ते भ १। सं १। मिश्र। सं १।
भा १
आ १। उ ५॥

जी २, प ६ ६, प्रा १०, ७, सं ४, ग १, इं १, का १, यो ११, वे २, क ४, ज्ञा ३, सं १, द २, ले ३,
भा १
भ २, स १ मि, सं १, आ २, उ ५, तत्पर्याप्तानां—गु १, जी १, प ६, प्रा १०, सं ४, ग १, इं १, का १, यो ९, वे २, क ४, ज्ञा ३, सं १, द २, ले १, भ २, स १ मि, सं १, आ १, उ १, तदपर्याप्तानां—
भा १
गु १, जी १, प ६ अ, प्रा ७ अ, सं ४, ग १, इं १, का १, यो २, वे २, क ४, ज्ञा २, सं १, द २, ले २,
भा १
भ २, स १ मि, सं १, आ २, उ ४, सासादनानां—गु १, जी २, प ६, ६, प्रा १० ७, सं ४, ग १, इं १, का १, यो ११, वे २, क ४, ज्ञा ३, सं १, द २, ले ३, भ १, स १ सा,
भा १
गु १ सा, जी १, प ६, प्रा १०, सं ४, ग १, इं १, का १, यो ९, वे २

भ १, स १, सं १, आ १, उ ५, तदपर्याप्तानां—गु १, जी १, प ६ अ, यो २ मि का, वे २, क ४, ज्ञा २, सं १, द २, ले २ क शु, भ

सम्यग्मिथ्यादृशां—गु १, जी १, प ६, प्रा १०, सं

सानत्कुमारमाहेंद्रदेवक्कंळ्गे । गु ४ । जी २ । प ६ । ६ । प्रा १० । ७ । सं ४ । ग १ । इं १ । का १ । यो ११ । वे १ । पुंस्त्रीवेविगळ्गे सौधर्म्मद्वयदोळे उत्पत्तियप्पुदरिदं । क ४ । ज्ञा ६ । सं १ । द ३ । ले ४ ते प क १ शु १ भ २ । सं ६ । उ । वे । क्षा । मि । सा । मि । सं १ । आ २ । उ ९ ॥
भा २ । ते प

सानत्कुमारद्वयदेवपर्य्याप्तरुगें । गु ४ । जी १ । प ६ । प्रा १० । सं ४ । ग १ । इं १ । का १ । यो ९ । वे १ । क ४ । ज्ञा ६ । सं १ । द ३ । ले २ । भ २ । सं ६ । सं १ । आ १ । उ ९ ॥
२

सानत्कुमारद्वयदेवापर्य्याप्तकग्गें । । गु ३ । मि । सा । अ । जी १ । अ । प ६ । अ प्रा ७ । सं ४ । ग १ । इं १ । का १ । त्र । यो २ । वै ० मिश्र १ । का १ । वे १ । पुं ० । क ४ । ज्ञा ५ । कु । कु । म । श्रु । अ । सं १ । अ । द ३ । च । अ । अ । ले २ क शु । भ २ । सं ५ । उ । सा । उ । वे । क्षा । सं १ । आ २ । उ ८ ॥
२

संप्रति मिथ्यादृष्टिप्रभृति यावदसंयतसम्यग्दृष्टि तावच्चतुर्गुणस्थानंगळ्गे सौधर्म्मंपुंवेदभंगंगळ्वक्तव्यमक्कुं । ई प्रकारदिदं मेलेयुं तंतम्मलेश्यानुसारदिदं वक्तव्यमक्कुं । अनुदिशानुत्तरविमानंगळ सम्यग्दृष्टिगळ्गे सम्यक्त्वप्रमाळापं कर्त्तव्यमक्कुमल्लि विशेषमुंटदावुदें दोडे उपशमसम्यक्त्वमं विट्टु मिकालदोळु वेदकक्षायिकसम्यक्त्वद्वयमे वक्तव्यमक्कुं । इंतु देवगति समाप्तमादुदु ॥

सिद्धगतियोळु सिद्धर्गे तंते वक्तव्यमक्कुं । विशेषमुंटावुदें दोडे अस्ति सिद्धगतिस्तत्र केवलज्ञानकेवलदर्शनक्षायिकसम्यक्त्वमनाहारमुपयोगद्वयमुंटु शेषाळापमिल्ल एकें दोडे सिद्धरुगळ्गे एकेंद्रियादिजातिनामकर्म्मोदयाभावमप्पुदरिदं । इंतु गतिमार्ग्गणेयसमाप्तमाय्तु ।

सनत्कुमारमाहेन्द्रदेवानां—गु ४, जी २, प ६ ६, प्रा १० ७, सं ४, ग १, इं १, का १, यो ११, वे १ पुं कल्पस्त्रीणां सौधर्मद्वय एवोत्पत्तेः, क ४, ज्ञा ६, सं १, द ३, ले ४ ते प क शु, भ २, स ६ उ वे क्षा मि सा मि, सं १, आ २, उ ९, तत्पर्याप्तानां—गु ४, जी १, प ६, प्रा १०, सं ४, ग १, इं १, का १, यो ९, वे १, क ४, ज्ञा ६, सं १, द ३, ले २, भ २, स ६, सं १, आ १, उ ९ ।
भा २ ते प २

तदपर्याप्तानां—गु ३ मि सा अ, जी १ अ, प ६ अ, प्रा १० ७ अ, सं ४, ग १ दे, इं १ पं, का १ त्र, यो २ वै मि का, वे १ पु, क ४, ज्ञा ५ कु कु म श्रु अ, सं १ अ, द ३ च अ अ, ले २ क शु, भ २, स ५ सा उ वे क्षा, सं १, आ २, उ ८, मिथ्यादृष्टयाद्यसंयतान्तानां सौधर्मपुंवेदवत्कथ्यं एवमुपर्यपि स्वस्वलेश्यानुसारेण योज्यं, अनुदिशानुत्तरविमानजानामसंयतस्थान एव तथापि विशेषः, पर्याप्तत्वे वेदकक्षायिकसम्यक्त्वद्वयमेव, सिद्धगतौ सिद्धानां यथासम्भवं वक्तव्यं, अस्ति सिद्धगतिस्तत्र केवलज्ञानदर्शनक्षायिकसम्यक्त्वानाहारोपयोगद्वयेभ्यः शेषालापो नास्ति सिद्धानामेकेन्द्रियादिजातिनामोदयाभावात्, गतिमार्गणा गता ।
२

बादरैकेंद्रियापर्य्याप्तकग्गें । गु १ । मि । जो १ । अ । प ४ । अ । प्रा ३ । ए । का । आ । ४ । ग १ । ति । इं १ । का ५ । यो २ । मि । का । वे । १ । प ० । क ४ । ज्ञा २ । सं १ । । द १ । अच ले २ क शु भ २ । सं १ । मि । सं १ । असंज्ञि । आ २ । उ ३ ॥
भा ३ अ

इंतु बादरपर्य्याप्तनामकर्म्मोदयसहितर्गे आलापत्रयं पेळल्पट्टुदपर्य्याप्तनामकर्मोदयसहित ादरैकेंद्रियलब्ध्यपर्य्याप्तकग्गें पेळल्पडुवल्लि बादरैकेंद्रियापर्य्याप्तालापवंतालापमक्कुं ॥

सूक्ष्मैकेंद्रियंगळगे । गु १ । मि । जो २ । प । अ प ४ । ४ । प्रा ४ । ३ । स ४ । ग १ । इं १ । । का ५ । यो ३ । औ २ । का १ । वे १ । पं । क ४ । ज्ञा २ । सं १ । अ । द १ । अच । २ क शु एकें बोळे :—
ा ३ अशु

सव्वेंसिं सुहुमाणं काओदा सव्वविग्गहे सुक्का ।
सव्वो मिस्सो देहो कवोदवण्णो हवे णियमा ॥

एंब नियममुंटप्पुदरिंद । भ २ । सं १ । मि । सं १ । असंज्ञि । आ २ । उ ३ ॥

सूक्ष्मैकेंद्रियपर्य्याप्तकग्गें । गु १ । जी १ । प ४ । प्रा ४ । सं ४ । ग १ । इं १ । का ५ । े १ । औ का । वे १ । प ९ । क ४ । ज्ञा २ । सं १ । अ । द १ । अच । ले ६ क भ २ ।
भा ३
ं १ । मि । सं १ । असंज्ञि । आ १ । उ ३ ॥

, का ५, यो १ औ, वे १ पं, क ४, ज्ञा २ कु कु, सं १ अ, द १ अच, ले ६, भ २, स १ मि, सं १
३ अशु
संज्ञी, आ १, उ ३, तदपर्याप्तानां—गु १ मि, जी १ अ, प ४ अ, प्रा ३ एका आ, सं ४, ग १ ति, इं १ , का ५, यो २ मि का, वे १ पं, क ४, ज्ञा २, सं १ अ, द १ अच, ले २ क शु, भ २, स १ मि, स १
भा ३ अशु
संज्ञी, आ २, उ ३, एवं बादरपर्याप्तनामोदयानामेकेन्द्रियाणामुक्तं, अपर्याप्तनामोदयानां तल्लब्ध्यपर्याप्तानां ; तदपर्याप्तवद्योग्यं,

सूक्ष्माणां—गु १ मि, जी २ प अ, प ४ ४, प्रा ४ ३, सं ४, ग १ ति, इं १ ए, का ५, यो ३ औ २ ा १, वे १ पं, क ४, ज्ञा २, सं १ अ, द १ अच, ले २ क शु

भा ३ अशु—कुतः ?

सर्व्वेसिं सुहुमाणं काओदा सव्वविग्गहे सुक्का ।
सव्वो मिस्सो देहो कवोदवण्णो हवे णियमा ॥१॥
सर्वेषां सूक्ष्माणां कापोता सर्वविग्रहे शुक्ला ।
सर्वो मिश्रो देहः कपोतवर्णो भवेन्नियमात् ॥१॥

भ २, स १ मि, सं १ असंज्ञि, आ २, उ ३, तत्पर्याप्तानां—गु १, जी १, प ४, प्रा ४, सं ४, ग १, इं १, ा ५, यो १ औ, वे १ पं, क ४, ज्ञा २, सं १ अ, द १ अचक्षु, ले १ क, भ २, सं १ मि, सं १ असंज्ञी,
भा ३ अशु

त्रींद्रियपर्य्याप्तकर्ग्ये । गु १ । जी १ । त्री । प । प ५ । प्रा ७ । सं ४ । ग १ । ति । इं १ । त्री । का १ । त्र । यो २ । औ । वा । वे १ । पं । क ४ । ज्ञा २ । सं १ । अ द १ । अच । ले ६ भ २ । सं १ । मि । सं १ । अ । आ १ । उ ३ ॥
भा ३

त्रींद्रियापर्य्याप्तर्गे । गु १ । जी १ । प ५ । अ प्रा ५ । अ । सं ४ । ग १ । इं १ । का १ । यो २ । मि । का । वे १ । पं । क ४ । ज्ञा २ । सं १ । अ द १ । अच । ले २ क शु । भ २ । सं १ ।
भा ३ अशु
मि । सं १ । अ । आ २ । उ ३ ॥

त्रींद्रियलब्ध्यपर्य्याप्तकंगेयुमो प्रकारविदमो देआळापमक्कुं ॥ चतुरिंद्रियंगळ्गे । गु १ । मि । जी २ । प । अ प ५ । ५ । प्रा ८ । ६ । सं ४ । ग १ । ति । इं १ । चतुरिंद्रिय । का १ त्र । यो ४ । औ २ । वा १ । का १ । वे १ । पं । क ४ । ज्ञा २ । सं १ । अ । द २ । च अ । ले ६ भ २ ।
भा ३
सं १ । मि । सं १ । अ । आ २ । उ ४ ॥

चतुरिंद्रियपर्य्याप्तकर्ग्ये । गु । मि । जी १ । च । प ५ । प्रा ८ । च ४ । वा १ । का १ । उ १ । आ १ । सं ४ । ग १ । इं १ । च । का १ । त्र । यो २ । औदारिक का १ । वा १ । वे १ पं । क ४ । ज्ञा २ । सं १ । अ । द २ । च । अ । ले ६ द्रव्य भ २ । सं १ । मि । सं १ । अ सं ।
भा ३ । अ शु
आ १ । ऊ ४ ॥

चतुरिंद्रियापर्य्याप्तकर्ग्गे । गु १ । जी १ । प ५ । अ । प्रा ६ । च ४ । का १ । आ १ । सं ४ । ग १ । इं १ । च । का १ । यो २ । मि । का । वे १ । पं । क ४ । ज्ञा २ । सं १ । अ । द २ । च । अ । ले २ क शु भ २ । सं १ । मि । सं १ । असं । आ २ । ऊ ४ ॥
भा ३ अशु
इंतु आळापत्रयं पेळल्पट्टुवु ॥

स १ मि, सं १ अ, आ २, उ ३ । तत्पर्याप्तानां—गु १ मि, जी १ त्री प, प ५, प्रा ७, सं ४, ग १ ति, इं १ त्रीं, का १ त्र, यो २ औ १ वा १, वे १ पं, क ४, ज्ञा २, सं १ अ, द १ अ च, ले ६, भ २, स १
भा ३
मि, सं १ अ, आ १, उ ३ । तदपर्याप्तानां—गु १, जी १, प ५ अ, प्रा ५ अ, सं ४, ग १, इं १, का १, यो २ मि का, वे १ पं, क ४, ज्ञा २, सं १ अ, द १ अ च, ले २ क शु, भ २, स १ मि, सं १, आ २,
भा ३ अ शु
उ ३ । तल्लब्ध्यपर्याप्तानां तदपर्याप्तवत्, चतुरिन्द्रियाणां—गु १ मि, जी २ प अ, प ५ ५, प्रा ८, ६, सं ४, ग १, इं १ चतुरि, का १ त्र, यो ४ औ २ वा १ का, वे १ पं, क ४, ज्ञा २, सं १ अ, द २ च अ, ले ६,
भा ३
भ २, स १ मि, सं १ अ, आ २, उ ४ । तत्पर्याप्तानां—गु १ मि, जी १ च प, प ५, प्रा ८ च ४ वा १ का १ उ १ आ १, सं ४, ग १ ति, इं १ च, का १ त्र, यो २ औ १ वा १, वे १ पं, क ४, ज्ञा २, सं १ अ, द २ च अ, ले ६, भ २, स १ मि, सं १ अ, आ १, उ ४ । तदपर्याप्तानां—गु १, जी १ अ, प ५ अ,
भा ३
प्रा ६ अ, च ४, का १ आ १, सं ४, ग १, इं १ च, का १, यो २ मि का, वे १ पं, क ४, ज्ञा २, सं १

षट्कषायसामान्यपर्य्याप्तकर्गे । गु १४ । जो १९ । ३७ । १८६ । प ६ । ५ । ४ । प्रा १० । ९ । ८ । ७ । ६ । सयोगि । ४ । ४ । अयोगि १ । सं ४ । ग ४ । इं ५ । का ६ । यो ११ । मिश्रचतुष्कहोनं । वे ३ । क ४ । ज्ञा ८ । सं ७ । द ४ । ले ६ भ २ । सं ६ । सं २ । आ २ । उ १२ ॥
६

षट्कषायसामान्यापर्य्याप्तकर्गे । गु ५ । मि । सा । अ । प्र । सयो । जी ३८ । ६१ । २२० । प ६ । ५ । ४ । प्रा ७ । ७ । ६ । ५ । ४ । ३ । २ । सं ४ । ग ४ । इं ५ । का ६ । यो ४ । मिश्रचतुष्टयं । वे ३ । क ४ । ज्ञा ६ ॥ मनःपर्य्ययविभंगरहितं । सं ४ । अ । सा । छे । यथा । द ४ ले २ क शु भ २ । सं ५ । मि । सा । उ । वे । क्षा । सं २ । आ २ । उ १० । ज्ञा ६ । द ४ ॥
भा ६

मिथ्यादृष्टिप्रभृतिगळ्गे मूलौघभंगमक्कुमल्लि मिथ्यादृष्टि त्रिविधरुगळ्गे कायानुवाददल्लि मूलौघदोळु पेळ्दजीवसमासगळु वक्तव्यंगळप्पुवु । नास्त्यन्यत्र विशेषः ॥

पृथ्वीकायंगळगे । गु १ । जी ४ । बादरपर्य्याप्तापर्य्याप्तसूक्ष्मपर्य्याप्तापर्य्याप्त । प ४ । ४ । प्रा ४ । ३ । सं ४ । ग १ । ति । इं १ । ए । का १ । पृ । यो ३ । औ २ । का १ । वे १ । षं । क ४ । ज्ञा २ । सं १ । अ सं । द १ । अच । ले ६ भ २ । सं १ । मि । सं १ । असं । आ २ । उ ३ ॥
भा ३

पृथ्वीकायपर्य्याप्तकर्गे । गु १ । जी २ । बा । सू । प ४ । प्रा ४ । सं ४ । ग १ ति । इं १ । ए । का १ पृ । यो २ । औ का । वे १ । षं । क ४ । ज्ञा २ । सं १ । अ । द १ । अ च ले ६
भा ३
भ २ । सं १ । मि । सं १ । अ । सं । आ १ । उ ३ ॥

तत्पर्याप्तानां—गु १४ । जो १९ । ३७ । १८६ । प ६ । ५ । ४ । प्रा १० । ९ । ८ । ७ । ६ । ४ । ४ । १ । सं ४ । ग ४ । इं ५ । का ६ । यो ११ । मिश्रचतुष्कार्मणाभावात् । वे ३ । क ४ । ज्ञा ८ । सं ७ । द ४ । ले ६ । भ २ । स ६ । सं २ । आ २ । उ १२ । तदपर्याप्तानां—गु ५ मि सा अ प्र स ।
६
जी ३८ । ६१ । २२० । प ६ ५ ४ । प्रा ७ ७ ६ ५ ४ ३ २ । सं ४ । ग ४ । इं ५ । का ६ । यो ४ त्रयो मिश्राः कार्मणश्च । वे ३ । क ४ । ज्ञा ६ मनःपर्ययविभंगाभावात् । सं ४ अ सा छे यथा । द ४ । ले २ क शु ।
भा ६
भ २ । सं ५ मि सा उ वे क्षा । सं २ । आ २ । उ १० ज्ञा ६ द ४ । मिथ्यादृष्ट्यादीनां मूलौघः किन्तु सामान्यादित्रिविधमिथ्यादृष्टीनामेव कायानुवादमूलौघोक्तजीवसमासा वक्तव्याः । अन्यत्र विशेषो नास्ति ।

पृथ्वीकायिकानां—गु १ । जी ४ बादरसूक्ष्मपर्याप्तापर्याप्ताः । प ४ ४ । प्रा ४ । ३ । सं ४ । ग १ ति । इं १ ए । का १ पृ । यो ३ औ २ का १ । वे १ षं । क ४ । ज्ञा २ । सं १ अ । द १ अच । ले ६
३
भ २ । स १ मि । सं १ असं । आ २ । उ ३ । तत्पर्याप्तानां—गु १ मि । जी २ बा सू । प ४ । प्रा ४ । सं ४ । ग १ ति । इं १ ए । का १ पृ । यो १ औ । वे १ षं । क ४ । ज्ञा २ । सं १ अ । द १ अच ।

कपोतभेदे बादरसंज्ञो पर्याप्तिपोऽन् पीतवर्णभेदे जनवदर्कं। विग्रहगतियोऽन् गुक्लभे। धातवर्णादिदं-गन्नोयुमपर्याप्तकालदोऽन् पोमुत्रमुद्गगाम्यत्तवर्णमक्कुं। वनस्पतिकायिकंगन्नो। गु १। जी १२॥

प्रतिष्ठितप्रत्येक पर्याप्तापर्याप्त अप्रतिष्ठितप्रत्येकपर्याप्तापर्याप्त ४। नित्यनिगोदबादरसूक्ष्म-चतुर्गतिनिगोदबादरसूक्ष्मंगळुं ४ वर्क पर्याप्तापर्याप्तभेदविदमें टुकूडि पन्नेरडु। प ४। ४। प्रा ४। ३। सं ४। ग १ ति। इं १। ए। का १। वन। यो ३। औ। का मि। वे १। षं। क ४। ज्ञा २। सं १। अ। द १। अच। ले ६ भ २। सं १। मि। सं १ अ सं। आ २। उ ३॥
भा ३

वनस्पतिपर्याप्तकंगे। गु १। जी ६। प्र। अ। नित्यनिगोद बादरसूक्ष्मपर्याप्तचतुर्गति-निगोदबादरसूक्ष्मपर्याप्तंगळु प ४। प्रा ४। सं ४। ग १ ति। इं १। ए। का १। वन। यो १। औ। वे १। षं। क ४। ज्ञा २। सं १ अ। द १। अच। ले ६ भ २। सं १ मि। सं १।
भा ३
अ। आ १। उ ३॥

वनस्पतिकायिकापर्याप्तकर्गे। गु १। मि। जी ६। अ। प ४ अ। प्रा ३। अ। सं ४। ग। ति १। इं १। ए। का १ वन। यो २। मि का। वे १ षं। क ४। ज्ञा २। सं १ अ। द १ अच। ले २ कशु भ २। सं १ मि। सं १। असं। आ २। उ ३॥
भा ३ अशु

प्रत्येकवनस्पतिगळगे। गु १ मि। जी ४। प्रति। अप्रति। प। अ। प ४। ४। प्रा ४। ३। सं ४। ग १ ति। इं १ ए। का १ वन। यो ३। औ २। का १। वे १ षं। क ४। ज्ञा २। सं १ अ। द १ अच। ले ६ भ २। सं १ मि। सं १। असं। आ २। उ ३॥
भा ३

पीता। पद्मविग्रहगती शुक्ला। कापोतविकायां अपर्याप्तकाले कपोता। विग्रहगती शुक्ला। पर्याप्तकाले योग्यषड्लेश्या:।

[illegible]—गु १। जी १२ [illegible] पर्याप्ता। प ४ ४। प्रा ४ ३। सं ४। ग १ ति। इं १ ए। का १ व। यो ३ औ २ का १। वे १ षं। क ४। ज्ञा २। सं १ अ। द १ अच। ले ६। भ २। स १ मि। सं १ अ। आ २। उ ३। [illegible]-
३
गु १। जी ६ [illegible] पर्याप्ता:। प ४। प्रा ४। सं ४। ग १ ति। इं १ ए। का १ व। यो १ औ। वे १ षं। क ४। ज्ञा २। सं १ अ। द १ अच। ले ६। भ २।
३
स १ मि। सं १ अ। आ १। उ ३। [illegible]—गु १ मि। जी ६ अ। प ४ अ। प्रा ३। अ। सं ४। ग १ ति। इं १ ए। का १ व। यो २ मि का। वे १ षं। क ४। ज्ञा २। सं १ अ। द १ अच। ले २
३
भ २। स १ मि। सं १ अ। आ २। उ ३। [illegible]—गु १ मि। जी ४ [illegible]। प १
अ २। प ४ ४। प्रा ४ ३। सं ४। ग १ ति। इं १ ए। का १ व। यो ३ औ २ का १। वे १ षं।

[illegible]

[illegible] सा। २। उ। १॥

[illegible]

[illegible]

[illegible]

[illegible] सा। २। उ। १॥

[illegible]

[illegible]

यथा। द ४ ले २ क शु भ २। सं ५। मि। सा उ। वे। क्षा। सं २। आ २। उ १०॥
भा ६

त्रसमिथ्यादृष्टिगळ्गे। गु १। मि।। जी १०। । वि। ति। च। सं। अ। प ६। ६।
२ २ २ २ २
५। ५। प्रा १०। ७। ९। ७। ८। ६। ७। ५। ६। ४। सं ४। ग ४। इं ४। का १ त्र। यो १३।
आहारद्वयवर्जितमागि। वे ३। क ४। ज्ञा ३। कु। कु। वि। सं १। अ। द। २ ले ६ भ २।
६
सं १। मि। सं २। आ २। उ ५॥

त्रसपर्य्याप्तमिथ्यादृष्टिगळ्गे। गु १। मि। जो ५। वि। ति। च। पं। अ प ६। ५।
१ १ १ १ १
प्रा १०। ९। ८। ७। ६। सं ४। ग ४। इं ४। वि। ति। च। पं। का १ त्र। यो १०।
१ १ १ १
म ४। वा ४। औ १। वै १। वे ३। क ४। ज्ञा ३। सं १। अ। द २। ले ६ भ २। सं मि।
६
सं २। आ १ उ ५॥

त्रसाऽपर्य्याप्तमिथ्यादृष्टिगळ्गे। गु १। मि। जी ५। वि। ति। च। सं। अ प ६। ५।
१ १ १ १ १
अ। प्रा ७। ७। ६। ५। ४। सं ४। ग ४। इं ४। वि। ति। च। पं का १। त्र। यो ३।
१ १ १ १
औ मि। वै मि। का। वे ३। क ४। ज्ञा २। सं १। अ। द २। ले २ क शु भ २। सं १।
भा ६
मि। सं २। आ २। उ ४॥

सासादनसम्यग्दृष्टिप्रभृतियागि अयोगिकेवलिपर्य्यंतं मूलौघभंगमक्कुं॥

सं ४ अ सा छे य। द ४। ले २ क शु। भ २। स ५ मि सा उ वे क्षा। सं २। आ २। उ १०।
भा ६
मिथ्यादृशां—गु १ मि। जी १० वि ति च सं असं। प ६ ६। ५ ५। प्रा १० ७, ९, ७, ८, ६, ७, ५,
२ २ २ २ २
६, ४, सं ४, ग ४, इं ४, का १ त्र, यो १३ आहारकद्वयं नहिं। वे ३, क ४, ज्ञा ३ कु कु वि, सं १ अ।
द २, ले ६, भ २, स १ मि, सं २, आ २, उ ५, तत्पर्याप्तानां—गु १ मि। जो ५ वि ति च पं अ।
६ १ १ १ १ १
प ६। ५, प्रा १० ९ ८ ७, ६, सं ४। ग ४, इं ४, वि ति च पं। का १ त्र, यो १० म ४ वा ४ औ १
१ १ १ १
वै १। वे ३. क ४. ज्ञा ३. सं १. अ. द २. ले ६। भ २. स १ मि. सं २. आ १, उ ५. तदपर्याप्तानां—
६
गु १ मि. जी ५ वि ति च सं अ। प ६. ५ अ. प्रा ७. ७. ६. ५. ४. सं ४ ग ४. इं ४ वि ति च पं का १ त्र.
१ १ १ १ १ १ १ १ १
यो ३ औ मि १ वै मि १ का १. वे ३ क ४. ज्ञा २. स १ अ. द २. ले २ क शु। भ २. स १ मि. सं २.
भा ६

मनोयोगिमिश्रदंपे। गु १। मिश्र। जो १। प ६। प्रा १०। सं ४। ग ४। इं १। पं। का १ त्र। यो ४। मनो। वे ३। क ४। ज्ञा ३। सं १। अ। द ३। ले ६/६ भ १। स १ मिश्र। सं १। आ १। उ ५॥

मनोयोगि असंयतंगे गु १। अस। जो १। प ६। प्रा १०। सं ४। ग ४। इं १। का १। यो ४। मनो। वे ३। क ४। ज्ञा ३। म। श्रु। अ। सं १। अ। द ३। च। अ। अ। ले ६/भा ६ भ १। स ३। उ। वे। क्षा। सं १। आ १। उ ६॥

मनोयोगिदेशसंयतंगे। गु १। दे। जो १। प ६। प्रा १०। सं ४। ग २। ति। म। इं १। का १। यो ४। मनो। वे ३। क ४। ज्ञा ३। सं १ देश। द ३ ले ६/भा ३। शु भ १। सं ३। उ। वे। क्षा। सं १। आ १। उ ६॥

मनोयोगिप्रमत्तंगे। गु १ प्र। जो १। प ६। प्रा १०। सं ४। ग १ म। इं १। का १। यो ४। मनोयोग। वे ३। क ४। ज्ञा ४। म। श्रु। अ। म। सं ३। सा। छे। प। द ३। च। अ। अ। ले ६/भा ३ भ १। सं ३। उ। वे। क्षा। सं १। आ १। उ ७॥

मनोयोगि अप्रमत्तप्रभृति सयोगकेवलिपर्य्यंतं मूलोघभंगमक्कुं। सर्व्वत्रमाल्कुं मनोयोगंगळ्ं सत्यमनोयोगमसत्यमनोयोगमुभयमनोयोगमनुभयमनोयोगमुमक्कुं। … मनोयोगि भंगमक्कुमल्लि। विशेषमावुदेंदोडे सत्यमनोयोगमोंदे वक्तव्यमक्कुं। ई प्रकारदिं अनुभयमनोयोगिगळ्गमक्कुं। विशेषमावुदेंदोडे अनुभयमनोयोगमो देयक्कुमेंदुदु॥

द ३, ले ६/६। भ १, स १ मि, सं १, आ १, उ ५। तन्मिश्रस्य—गु १ मिश्र, जी १। प ६, प्रा १०, सं ४, ग ४, इं १ पं, का १ त्र, यो ४ म, वे ३, क ४, ज्ञा ३ मि, सं १ अ, द २, ले ६/६। भ १। स १ मिश्र, सं १, आ १। उ ५। तदसंयतस्य—गु १ अ, जी १, प ६। प्रा १०, सं ४, ग ४, इं १ पं, का १ त्र, यो ४ म, वे ३, क ४, ज्ञा ३ म श्रु अ, सं १ अ, द ३ च अ अ, ले ६/६, भ १, स ३ उ वे क्षा, सं १, आ १, उ ६। तद्देशसंयतस्य—गु १ दे, जी १, प ६, प्रा १०, सं ४, ग २ ति म, इं १ पं, का १ त्र, यो ४ म, वे ३, क ४, ज्ञा ३, सं १ दे, द ३ च अ अ, ले ६/भा ३ शु। भ १। स ३ उ वे क्षा। सं १। आ १। उ ६। तत्प्रमत्तस्य—गु १ प्र, जी १ प, प ६, प्रा १०, सं ४, ग १ म, इं १ पं, का १ त्र, यो ४ म, वे ३, क ४, ज्ञा ४ म श्रु अ म, सं ३ सा छे प, द ३ च अ अ, ले ६/भा ३, भ १, स ३ उ वे क्षा। सं १, आ १। उ ७। तदप्रमत्तादिसयोगांतानां मूलोघः किंतु सर्वत्र मनोयोगाश्चत्वारः सयोगे सत्यानुभयौ द्वौ सत्यानुभयमनोयोगिनां मिथ्यादृष्ट्यादिसयोगांतं मनोयोगिवत् किंतु योगस्थाने स्वस्वनामैकः।

काययोगिपर्य्याप्तकर्गे । गु १३ । जी ७ । प ६ । ५ । ४ । प्रा १० । ९ । ८ । ७ । ६ । ४ । ४ । सं ४ । ग ४ । इं ५ । का ६ । यो ३ । औ । वै । आ । वे ३ । क ४ । ज्ञा ८ । सं ७ । द ४ । ले ६/६ भ २ । सं ६ । सं २ । आ १ । आहारकरु । उ १२ ॥

अपर्य्याप्तकाययोगिगळ्गे । गु ५ । मि । सा । अ । प्र । स । जी ७ । अ । प । ६ । ५ । ४ । प्रा ७ । ७ । ६ । ५ । ४ । ३ । २ । सं ४ । ग ४ । इं ५ । का ६ । यो ४ । औ मि । वै मि । आ मि । का १ । वे ३ । क ४ । ज्ञा ६ । कु । कु । म । श्रु । अ । के । सं ४ । अ १ । सा १ । छे १ । यथा १ । द ४ । ले २ । कशु/भा ६ । भ २ । सं ५ । मि । सा । क्षा । वे । क्षा । सं २ । आ २ । उ १० ॥

काययोगिमिथ्यादृष्टिगळ्गे । गु १ । मि । जी १४ । प ६ । ६ । ५ । ५ । ४ । ४ । प्रा १० । ७ । ९ । ७ । ८ । ६ । ७ । ५ । ६ । ४ । ४ । ३ । सं ४ । ग ४ । इं ५ । का ६ । यो ५ ॥ आहारद्वयरहित । वे ३ । क ४ । ज्ञा ३ । सं १ । अ । द २ । ले ६/६ । भ २ । सं १ । मि । सं २ । आ २ । उ ५ ॥

काययोगिमिथ्यादृष्टिपर्य्याप्तकर्गे । गु १ । जी ७ । प ६ । ५ । ४ । प्रा १० । ९ । ८ । ७ । ६ । ४ । सं ४ । ग ४ । इं ५ । का ६ । यो २ । औ । वै । वे ३ । क ४ । ज्ञा ३ । कु । कु । वि । सं १ । अ । द २ । ले ६/६ । भ २ । सं १ । मि । सं २ । आ १ । उ ५ ॥

काययोगिमिथ्यादृष्ट्यपर्य्याप्तकर्गे । गु १ । जी ७ । प ६ । ५ । ४ । प्रा ७ । ७ । ६ । ५ । ४ । ३ । सं ४ । ग ४ । इं ५ । का ६ । यो ३ । औ । मि । वै । मि । का । वे ३ । क ४ । ज्ञा २ । सं १ अ । द २ । ले २ कशु/भा ६ भ २ । सं १ । मि । सं २ । आ २ । उ ४ ॥

सं २ । आ २ । उ १२ । तत्पर्याप्तानां—गु १३ । जी ७ । प ६ । ५ । ४ । प्रा १० । ९ । ८ । ७ । ६ । ४ । ४ । सं ४ । ग ४ । इं ५ । का ६ । यो ३ औ वै आ । वे ३ । क ४ । ज्ञा ८ सं ७ । द ४ । ले ६/६ । भ २ । स ६ । सं २ । आ १ आहारकः । उ १२ । तदपर्याप्तानां—गु ५ मि सा अ प्र स । जी ७ अ । प ६ ५ ४ । प्रा ७ ७ ६ ५ ४ ३ २ । सं ४ । ग ४ । इं ५ । का ६ । यो ४ औमि वैमि आमि का । वे ३ । क ४ । ज्ञा ६ । कु कु म श्रु अ के । सं ४ अ सा छे य । द ४ । ले २ कशु/भा ६ । भ २ । स ५ मि सा उ वे क्षा । सं २ । आ २ । उ १० । तन्मिथ्यादृशां—गु १ । जी १४ । प ६ ६ ५ ५ ४ ४ । प्रा १० ७ ९ ७ ८ ६ ७ ५ ६ ४ ४ ३ । सं ४, ग ४, इं ५, का ६, यो ५ आहारकद्वयं नहि, वे ३, क ४, ज्ञा ३, सं १ अ, द २, ले ६/६, भ २, स १ मि, सं २, आ २, उ ५ । तत्पर्याप्तानां—गु १ । जी ७ । प ६ ५ ४ । प्रा १० ९ ८ ७ ६ ४ । सं ४ । ग ४ । इं ५ । का ६ । यो २ औ वै । वे ३ । क ४ । ज्ञा ३ कु कु वि । सं १ अ । द २ । ले ६/६ । भ २ । स १ मि । सं २ । आ १ । उ ५ । तदपर्याप्तानां—गु १ । जी ७ । प ६ ५ ४ । प्रा ७ ७ ६ ५ ४ ३ । सं ४ । ग ४ । इं ५ । का ६ । यो ३ औमि वैमि का । वे ३ । क ४ ।

औवारिककाययोगिअसंयतसम्यग्दृष्टिगे । गु १ । अ । जो १ । पंचि । प । प ६ । प्रा १० । सं ४ । ग २ । ति । म । इं १ । पं । का १ त्र । यो १ । औ । वे ३ । क ४ । ज्ञा ३ । सं १ अ । द ३ । ले ६ । भ १ । सं ३ । सं १ । आ १ । उ ६ ॥
६

औवारिककाययोगि वेशव्रतिगळ्गे । गु १ । वे । जो १ । पं प । प ६ । प्रा १० । सं ४ । ग २ । ति । म । इं १ । पं । का १ त्र । यो १ । औ का । वे ३ । क ४ । ज्ञा ३ । सं १ । दे । द ३ । ले ६ । भ १ । सं ३ । सं १ । आ १ । उ ६ ॥
भा ३

प्रमत्तसंयतप्रभृति सयोगिकेवलिपर्य्यंतं काययोगिभंगं वक्तव्यमक्कुं विशेषमावुदें दोडे सर्व्वत्रौवारिककाययोगमों दे वक्तव्यमक्कुं ॥

औवारिकमिश्रकाययोगिगळ्गे । गु ४ । मि । सा । अ । सयो । जो ७ । अ । प ६ । ५ । ४ । प्रा ७ । ७ । ६ । ५ । ४ । ३ । २ । सं ४ । ग २ । म । ति । इं ५ । का ६ । यो १ । औ मि । वे ३ । क ४ । ज्ञा ६ । विभंगमनःपर्य्ययरहितं । सं २ । अ । यथा । द ४ । ले १ क । भ २ ।
भा ६
सं ४ । मि । सा । वे । क्षा । सं २ । आ १ । उ १० ॥

औवारिकमिश्रकाययोगिमिथ्यादृष्टिगळ्गे । गु १ मि । जो ७ । अ । प ६ । ५ । ४ । प्रा ७ । ७ । ६ । ५ । ४ । ३ । सं ४ । ग २ । ति । म । इं ५ । का १ । यो १ । औ मि । वे ३ । क ४ । ज्ञा २ । सं १ । अ । द २ । ले १ क । भ २ । सं १ । मि । सं २ । आ १ । उ ४ ॥
भा ३

औवारिकसासादनमिश्रगें । गु १ । सासा । जो १ । सं । पं । अ । प ६ । प्रा ७ । सं ४ । ग २ । ति । म । इं १ । पं । का १ । त्र । यो १ । औ मि । वे ३ । क ४ । ज्ञा २ । सं १ । अ ।

जो १, प ६, प्रा १०, सं ४, ग २ ति म, इं १, का १ त्र । यो १ औ, वे ३, क ४, ज्ञा ३, सं १ अ, द ३, ले ६ । भ १, स १ मिश्रं, सं १, आ १, उ ५, असंयतानां—गु १ अ, जो १ पं प, प ६, प्रा १०,
६
सं ४, ग २ ति म, इं १ पं, का १ त्र, यो १ औ, वे ३, क ४, ज्ञा ३, सं १ अ, द ३, ले ६ । भ १, स ३,
६
सं १, आ १, उ ६, देशव्रतानां—गु १ दे, जी १ पं प, प ६, प्रा १०, सं ४, ग २ ति म, इं १ पं, का १ त्र, यो १ औ, वे ३, क ४, ज्ञा ३, सं १ दे, द ३ ले ६, भ १, स ३, सं १, आ १, उ ६, प्रमत्तासयोगांतं
३
काययोगिवत् किंतु सर्वत्र औदारिकयोग एव वक्तव्यः ।

औदारिकमिश्रयोगिनां—गु ४ मि सा अ स । जी ७ अ । प ६ । ५ । ४ । प्रा ७ । ७ । ६ । ५ । ४ । ३ । २ । सं ४ । ग २ ति म । इं ५ । का ६ । यो १ औमि । वे ३ । क ४ । ज्ञा ६, विभंगमनःपर्ययाभावात् । सं २ अ य । द ४ । ले १ क । भ २ । स ४ मि सा वे क्षा । सं २ । आ १ । उ १० । तन्मिथ्यादृशां
भा ६
गु १ मि । जी ७ अ । प ६ । ५ । ४ । प्रा ७ । ७ । ६ । ५ । ४ । ३ । सं ४ । ग २ ति म । इं ५ । का ६ । यो १ औमि । वे ३ । क ४ । ज्ञा २ । सं १ अ । द २ । ले १ । भ २ । स १ मि । सं २ । आ १ ।
भा ३
उ ४ । तत्सासादनानां—गु १ सा । जी १ सं अ । प ६ अ । प्रा ७ । सं ४ । ग २ ति म । इं १ पं ।

वैक्रियिककाययोगिसम्यग्मिथ्यादृष्टिगळ्गे । गु १ । मिश्र । जी १ । प ६ । प्रा १० । सं ४ । ग २ न दे । इं १ । पं । का १ त्र । यो १ । वैं । का । वे ३ । क ४ । ज्ञा ३ । कु । कु । वि । सं १ । अ । द २ । ले ६ । भ १ । सं १ । मिश्र । सं १ । आ १ । उ ५ ॥
भा ६

वैक्रियिककाययोगि असंयतसम्यग्दृष्टिगळ्गे । गु १ । अ सं । जी १ । प ६ । प्रा १० । सं ४ । ग २ । न दे । इं १ । पं । का १ त्र । यो १ । वैं का । वे ३ । क ४ । ज्ञा ३ । म श्रु अ । सं १ । अ । द ३ । ले ६ । भ १ । सं ३ । सं १ । आ १ । उ ६ ॥
६

वैक्रियिकमिश्रकाययोगिगळ्गे । गु ३ । मि । सा । अ । जी १ । प ६ । अ । प्राण ७ । अ । सं ४ । ग २ । न दे । इं १ । पं । का १ त्र । यो १ । वैं मि । वे ३ । क ४ । ज्ञा ५ । कु । कु । म । श्रु । अ । सं १ । अ । द ३ । ले १ । भ २ । सं ५ । मि । सा । उ । वे । क्षा । सं १ ।
भा ६
आ १ । उ ८ ॥

वैक्रियिकमिश्रकाययोगिमिथ्यादृष्टिगळ्गे । गु १ । मि । जी १ । अ । प ६ । अ । प्रा ६ । अ । सं ४ । ग २ । न दे । इं १ । पं । का १ त्र । यो १ । वैं मि । वे ३ । क ४ । ज्ञा २ । सं १ । अ द २ । ले १ । भ २ । सं १ । मि । सं १ । आ १ । उ ४ ॥
भा ६

वैक्रियिकमिश्रकाययोगसासादनसम्यग्दृष्टिगळ्गे । गु १ । सासा । जी १ । अ । प ६ । अ । प्रा ७ । अ । सं ४ । ग १ देव । इं १ । पं । का १ । त्र । यो १ । वैं मि । वे २ । क ४ । ज्ञा २ ।

प ६ । प्रा १० । सं ४ । ग २ न दे । इं १ पं । का १ त्र । यो १ वैं । वे ३ । क ४ । ज्ञा ३ कु कु वि । सं १ अ । द २ । ले ६ । भ १ । स १ सा । सं १ । आ १ । उ ५ । तत्सम्यग्मिथ्यादृशां— गु १ मिश्रं ।
६
जी १ । प ६ । प्रा १० । सं ४ । ग २ न दे । इं १ पं । का १ त्र । यो १ वैं । वे ३ । क ४ । ज्ञा ३ कु कु वि । सं १ अ । द २ । ले ६ भ १ । स १ मिश्रं । सं १ । आ १ । उ ५ । तदसंयतानां—गु १ अ ।
६
जी १ । प ६ । प्रा १० । सं ४ । ग २ न दे । इं १ पं । का १ त्र । यो १ वैं । वे ३ । क ४ । ज्ञा ३ म श्रु अ । द ३ । ले ६ । भ १ । स ३ । सं १ । आ १ । उ ६ । तन्मिश्रयोगिनां—गु १ मि
६
सा अ । जी १ । प ६ अ । प्रा ७ अ । सं ४ । ग २ न दे । इं १ पं । का १ त्र, यो १ वैंमि, वे ३, क ४, ज्ञा ५ कु कु म श्रु अ, सं १ अ, द ३, ले १ क, भ २, स ५ मि सा उ वे क्षा, सं १, आ १, उ ८ ।
भा ६
तन्मिथ्यादृशां—गु १ मि, जी १ अ, प ६ अ, प्रा ७ अ, सं ४, ग २ न दे, इं १ पं, का १ त्र, यो १ वैंमि, वे ३, क ४, ज्ञा २, सं १ अ, द २, ले १ । भ २, स १ मि, सं १, आ १, उ ४ । तत्सासादनानां—गु १ सा,
६
जी १ अ, प ६ अ, प्रा ७ अ, स ४, ग १ दे, इं १ पं, का १ त्र, यो १ वैंमि, वे २, क ४, ज्ञा २, सं १ अ,

का। वे १ स्त्री। क ४। ज्ञा २। कु। कु। सं १। अ। द २। च। अ ले २ क शु / भा ३ अ शु भ २।
सं १। मि। सं २। आ २। उ ४॥

स्त्रीवेदिसासादनर्गें। गु १। सासा। जी २। पंचेंद्रियसंज्ञिपर्य्याप्तापर्य्याप्त। प ६। प ६।
प्रा १०। ७। सं ४। ग ३। ति। म। दे। इं १। पं। का १। त्र। यो १३। आहारद्वयरहित।
वे १ स्त्री। क ४। ज्ञा ३। कु। कु। वि। सं १। अ। द २। ले ६/६। भ १। सं १। सासा।
सं १। आ २। उ ५॥

स्त्रीवेदिसासादनपर्य्याप्तकर्गें। गु १। सासा। जी १। संज्ञिपंचेंद्रियपर्य्याप्तक। प ६।
प्रा १०। सं ४। ग ३ ति। म। दे। इं १। पं। का १ त्र। यो १०। म ४। व ४। औ। वै।
वे १। स्त्री। क ४। ज्ञा ३। कु। कु। वि। सं १। अ। द २। च। अ। ले ६/६ भ १। सं १।
सासा। सं १। आ १। उ ५॥

स्त्रीवेदिसासादनापर्य्याप्तकर्गें। गु १। सासा। जी १। स पं अ ० प ६। अ। प्रा ७।
अ। सं ४। ग ३। ति। म। दे। इं १। पं। का १ त्र। यो ३। औ मि। वै मि। का। वे १।
स्त्री। क ४। ज्ञा २। कु। कु। सं १। अ। द २। च। अ। ले २ क शु / भा ३ अ शु। भ १। सं १।
सासा। सं १। आ २। उ ४॥

स्त्रीवेदिसम्यग्मिथ्यादृष्टिगळ्गे। गु १। मिश्र। जी १। प। प ६। प्रा १०। सं ४।
ग ३। ति। म। दे। इं १। पं। का १ त्र। योग १०। म ४। व ४। औ १। वै १। वे १। स्त्री।
क ४। ज्ञा ३। कु। कु। वि। सं १ अ। द २। च। अ। ले ६/६। भ १। सं १। मिश्र।

का। वे १ स्त्री। क ४। ज्ञा २। कु। कु। सं १। अ। द २। च। अ। ले २ क शु / भा ३ अ शु। भ २।
सं १। मि। सं २। आ २। उ ४॥

स्त्रीवेदिसासादनर्गे। गु १। सासा। जी २। पंचेंद्रियसंज्ञिपर्य्याप्तापर्य्याप्त। प ६। प ६।
प्रा १०। ७। सं ४। ग ३। ति। म। दे। इं १। पं। का १। त्र। यो १३। आहारद्वयरहित।
वे १। स्त्री। क ४। ज्ञा ३। कु। कु। वि। सं १। अ। द २। ले ६/६। भ १। स १। सासा।
सं १। आ २। उ ५॥

स्त्रीवेदिसासादनपर्य्याप्तकर्गे। गु १। सासा। जी १। संज्ञिपंचेंद्रियपर्य्याप्तक। प ६।
प्रा १०। सं ४। ग ३ ति। म। दे। इं १। पं। का १ त्र। यो १०। म ४। व ४। औ। वै।
वे १। स्त्री। क ४। ज्ञा ३। कु। कु। वि। सं १। अ। द २। च। अ। ले ६/६। भ १। स १।
सासा। सं १। आ १। उ ५॥

स्त्रीवेदिसासादनापर्य्याप्तकर्गे। गु १। सासा। जी १। स पं अ ० प ६। अ। प्रा ७।
अ। सं ४। ग ३। ति। म। दे। इं १। पं। का १ त्र। यो ३। औ मि। वै मि। का। वे १।
स्त्री। क ४। ज्ञा २। कु। कु। सं १। अ। द २। च। अ। ले २ क शु / भा ३ अशु। भ १। स १।
सासा। सं १। आ २। उ ४॥

स्त्रीवेदिसम्यग्मिथ्यादृष्टिगळ्गे। गु १। मिश्र। जी १। प। प ६। प्रा १०। सं ४।
ग ३। ति। म। दे। इं १। पं। का १ त्र। योग १०। म ४। व ४। औ १। वै १। वे १। स्त्री।
क ४। ज्ञा ३। कु। कु। वि। सं १ अ। द २। च। अ। ले ६/६। भ १। स १। मिश्र।

प ६ ६ अ। प्रा ७ ७। सं ४। ग ३ ति म दे। इं १ पं। का १ त्र। यो ३ औमि वैमि का। वे १ स्त्री।
क ४। ज्ञा २ कु कु। सं १ अ। द २ च अ। ले २ क शु / भा ३ अशु। भ २। स १ मि। सं २। आ २। उ ४।
सासादनानां—गु १ सा। जी २ संज्ञिपर्याप्तापर्याप्तौ। प ६ ६। प्रा १० ७। सं ४। ग ३ ति म दे। इं १
पं। का १ त्र। यो १३ आहारद्वयाभावात्। वे १ स्त्री। क ४। ज्ञा ३ कु कु वि। सं १ अ। द २। ले ६/६।
भ १। स १ सा। सं १। आ २। उ ५। तत्पर्याप्तानां—गु १ सा। जो १ संज्ञिपर्याप्तः। प ६। प्रा १०।
सं ४। ग ३ ति म दे। इं १ पं। का १ त्र। यो १० म ४ व ४ औ १ वै १। वे १ स्त्री। क ४। ज्ञा ३
कु कु वि। सं १ अ, द २ च अ। ले ६/६। भ १। स १ सा। सं १। आ १। उ ५। तदपर्याप्तानां—गु
१ सा। जी १ सं अ, प ६ अ, प्रा ७ अ, सं ४, ग ३ ति म दे, इं १ पं, का १ त्र, यो ३ औमि वैमि का।
वे १ स्त्री। क ४। ज्ञा २ कु कु, सं १ अ, द २ च अ, ले २ क शु / भा ३ अशु, भ १, स १ सा, सं १, आ २, उ ४,
सम्यग्मिथ्यादृशां—गु १ मिश्र, जी १, प ६, प्रा १०, सं ४, ग ३ ति म दे, इं १ पं, का १ त्र, यो १० म
४ व ४ औ वै। वे १ स्त्री, क ४, ज्ञा ३ कु कु वि, सं १ अ, द २ च अ, ले ६/६, भ १, स १ मिश्रं,

ल्ग २। ला छे। द ३। प। व। अ। ले ६। भ १। सं २। उ। क्षा। सं १। भा १। उ ६॥
भा १

इन्तेरडेंदि अनिवृत्तिकरणंगे। गु १। अनि। जी १। प ६। प्रा १०। सं २। मै। प। ग १। इं १। पं। का १ त्र। यो ९। म ४। व ४। औ १। वे १। स्त्री। क ४। ज्ञा ३। म। श्रु। अ। द ३। ल्ग २। ला छे। द ३। प। व। अ। ले ६ भ १। सं २। उ। क्षा। सं १। भा १। उ ६॥
भा १

पुंवेदिगळ्गे। गु ९। जी ४। संज्ञ्यपर्याप्तकापर्याप्तकाः। प ६। ६। ५। ५। प्रा १०। ९। ७। ७। सं ४। ग ३। ति। म। दे। इं १। पं। का १ त्र। यो १५। वे १। पुं। क ४। ज्ञा ७। केवलज्ञानरहित। सं ५। अ। दे। सा। छे। प। द ३। प। व। अ। ले ६ भ २। ६
सं ६। सं २। आ २। उ १०॥

पुंवेदिपर्याप्तंगे। गु ९। जी २। सं। अ। प ६। ५। प्रा १०। ९। सं ४। ग ३ ति। म। दे। इं १। पं। का १ त्र। यो ११। म ४। व ४। औ १। वै १। आ १। वे १। पुं। क ४। ज्ञा ७। सं ५। अ। दे। सा। छे। प। द ३। प। व। अ। ले ६। भ २। सं ६। सं २। ६
आ १। उ १०॥

पुंवेदि अपर्याप्तकंगे। गु ४। मि। सा। अ। प्र। जी २। प ६। ५। प्रा ७। ७। सं ४। ग ३। ति। म। दे। इं १। का १। यो ४। औ मि। वै मि। आ मि। का। वे १। पुं। क ४। ज्ञा ५। कु। कु। म। श्रु। अ। सं। अ। सा। छे। द ३। प। अ। अ। ले २ क शु भ २। भा ६
सं ५। मि सा। उ। वे। क्षा। सं २। आ २। उ ८॥

सं ३, ग १ म, इं १ पं, का १ त्र, यो ९ म ४ व ४ औ १, वे १ स्त्री, क ४, ज्ञा ३ म श्रु अ, सं २ सा छे, द ३ च अ अ, ले ६, भ १, स २ उ क्षा, सं १, आ १, उ ६। अनिवृत्तिकरणानां—गु १ अनि, जी १, १
प ६, प्रा १०, सं २ मै प, ग १ म, इं १ पं, का १ त्र, यो ९ म ४ व ४ औ १, वे १ स्त्री। क ४, ज्ञा ३ म श्रु अ, सं २ सा छे, द ३ च अ अ, ले ६, भ १, स २ उ क्षा, सं १, आ १, उ ६। पुंवेदिनां—गु ९, १
जी ४ संज्ञिपर्याप्तापर्याप्ताः, प ६ ६ ५ ५, प्रा १० ७ ९ ७, सं ४, ग ३ ति म दे, इं १ पं, का १ त्र, यो १५, वे १ पुं, क ४, ज्ञा ७ केवलज्ञानं नहि, सं ५ अ दे सा छे प, द ३ च अ अ, ले ६, भ २, स ६, ६
सं २, आ २, उ १०। पर्याप्तानां—गु ९, जी २ सं अ, प ६ ५, प्रा १० ९। सं ४, ग ३ ति म दे, इं १ पं। का १ त्र, यो ११ म ४ व ४ औ १ वै १ आ १। वे १ पुं। क ४, ज्ञा ७, सं ५ अ दे सा छे प, द ३ च अ अ। ले ६। भ २। स ६, सं २। आ १। उ १०। अपर्याप्तानां—गु ४ मि सा अ प्र, जी २, ६
प ६ ५। प्रा ७ ७। सं ४। ग ३ ति म दे। इं १। का १, यो ४ औमि वैमि आमि का। वे १ पुं, क ४, ज्ञा ५ कु कु म श्रु अ। सं ३ अ सा छे, द ३ च अ अ। ले २ क शु। भ २। स ५ मि सा उ वे क्षा, सं २, भा ६
आ २। उ ८।

क ४। ज्ञा ६। कु। कु। वि। म। श्रु। अ। सं ४। अ। दे। सा। छे। द ३। च। अ। अ ले ६।
६
भ २। सं ६। सं २। आ १। उ ९॥

नपुंसकवेदिअपर्य्याप्तकर्गे। गु ३। मि। सा। अ। जी ७। प ६। ५। ४। प्रा ७। ७। ६। ५। ४। ३। सं ४। ग ३। न। ति। म। इं ५। का ६। यो ३। औमि। वैमि। का।
१ १ १
वे १। पं। क ४। ज्ञा ५। कु। कु। म। श्रु। अ। सं १। अ। द ३। च। अ। अ। ले २ क शु।
भा ३ अशु
भ २ सं। ४। मि। सा। वे। क्षा। सं २। आ २। उ ८॥

नपुंसकवेदिमिथ्यादृष्टिगळ्गे। गु १। मि। जी १४। प ६। ६। ५। ५। ४। ४। प्रा १०। ७। ९। ७। ८। ६। ७। ५। ६। ४। ४। ३। सं ४। ग ३। न। ति। म। इं ५। का ६। यो १३। आहारकद्वयवर्जित। वे १। नपुं। क ४। ज्ञा ३। कु। कु। वि। सं १। अ। द २। ले ६। भ २। सं १। मि। सं २। आ २। उ ५॥
६

नपुंसकवेदिमिथ्यादृष्टिपर्य्याप्तकंगे। गु १। मि। जी ७। प ६। ५। ४। प्रा १०। ९। ८। ७। ६। ४। सं ४। ग ३। न। ति। म। इं ५। का ६। यो १०। म ४। व ४। औ। वै। वे १ पं। क ४ ज्ञा ३। कु। कु। वि। सं १। अ। द २। ले ६। भ २। सं १। मि। सं २।
६
आ १। उ ५॥

नपुंसकमिथ्यादृष्टि अपर्य्याप्तकंगे। गु १। मि। जी ७। प ६। ५। ४। प्रा ७। ७। ६। ५। ४। ३। सं ४। ग ३। न। ति। म। इं ५। का ६। यो ३। औ मि। वै मि। का ४। वे १

---

१० म ४ व ४ औ १ वै १, वे १ पं, क ४, ज्ञा ६ कु कु वि म श्रु अ, सं ४ अ दे सा छे, द ३ च अ अ, ले ६। भ २, स ६, सं २, आ १, उ ९। तदपर्याप्तानां—गु ३ मि सा अ, जी ७, प ६ ५,४ अ, प्रा ७, ७,
६
६, ५, ४, ३। ४, प्रा १०, ९, ८, ७, ६, ४, सं ४। ग ३ न ति म, इं ५, का ६, यो ३ औमि वैमि का, वे. १ पं, क ४, ज्ञा ५ कु कु म श्रु अ, सं १ अ, द ३ अ च अ, ले २ क शु भ २, स ४ मि सा वे क्षा,
भा ३ अशु
सं २, आ २, उ ८। तन्मिथ्यादृशां—गु १ मि, जी १४, प ६, ६, ५, ५, ४, ४, प्रा १०, ७, ९, ७, ८, ६, ७, ५, ६, ४, ४, ३, सं ४, ग ३ न ति म, इं ५, का ६, यो १३ आहारद्वयं नहि, वे १ न, क ४, ज्ञा ३ कु कु वि, सं १ अ, द २, ले ६, भ २, स १ मि, सं २, आ २ उ ५। तत्पर्याप्तानां—गु १ मि, जी
६
७, प ६, ५, ४, प्रा १०, ९, ८ ७ ६, ४, सं ४, ग ३ न ति म, इं ५, का ६, यो १० म ४ व ४ औ वै, वे १ पं, क ४, ज्ञा ३ कु कु वि, सं १ अ, द २। ले ६। भ २, स १ मि, सं २, आ १, उ ५। तद-
६
पर्याप्तानां—गु १ मि, जी ७, प ६, ५, ४, प्रा ७, ७, ६, ५, ४, ३, सं ४, ग ३ न ति म, इं ५, का ६,

क ४। ज्ञा ६। कु। कु। वि। म। श्रु। अ। सं ४। अ। वे। सा। छे। द ३। च। अ। अ ले ६।
६
भ २। सं ६। सं २। आ १। उ ९॥

नपुंसकवेदिअपर्य्याप्तकर्गें। गु ३। मि। सा। अ। जी ७। प ६। ५। ४। प्रा ७। ७।
६। ५। ४। ३। सं ४। ग ३। न। ति। म। इं ५। का ६। यो ३। औमि। वैमि। का।
१ १ १
वे १। पं। क ४। ज्ञा ५। कु। कु। म। श्रु। अ। सं १। अ। द ३। च। अ। अ। ले २ क शु।
भा ३ अशु
भ २ सं। ४। मि। सा। वे। क्षा। सं २। आ २। उ ८॥

नपुंसकवेदिमिथ्यादृष्टिगळ्गे। गु १। मि। जी १४। प ६। ६। ५। ५। ४। ४। प्रा १०। ७। ९। ७। ८। ६। ७। ५। ६। ४। ४। ३। सं ४। ग ३। न। ति। म। इं ५। का ६। यो १३। आहारकद्वयवर्ज्जित। वे १। नपुं। क ४। ज्ञा ३। कु। कु। वि। सं १। अ। द २। ले ६। भ २। सं १। मि। सं २। आ २। उ ५॥
६

नपुंसकवेदिमिथ्यादृष्टिपर्य्याप्तकंगे। गु १। मि। जी ७। प ६। ५। ४। प्रा १०। ९। ८। ७। ६। ४। सं ४। ग ३। न। ति। म। इं ५। का ६। यो १०। म ४। व ४। औ। वै। वे १ पं। क ४ ज्ञा ३। कु। कु। वि। सं १। अ। द २। ले ६। भ २। सं १। मि। सं २।
६
आ १। उ ५॥

नपुंसकमिथ्यादृष्टि अपर्य्याप्तकंगे। गु १। मि। जी ७। प ६। ५। ४। प्रा ७। ७। ६। ५। ४। ३। सं ४। ग ३। न। ति। म। इं ५। का ६। यो ३। औ मि। वै मि। का ४। वे १

---

१० म ४ व ४ औ १ वै १, वे १ पं, क ४, ज्ञा ६ कु कु वि म श्रु अ, सं ४ अ दे सा छे, द ३ च अ अ, ले ६। भ २, स ६, सं २, आ १, उ ९। तदपर्याप्तानां—गु ३ मि सा अ, जी ७, प ६ ५, ४ अ, प्रा ७, ७,
६
६, ५, ४, ३। ४, प्रा १०, ९, ८, ७, ६, ४, सं ४। ग ३ न ति म, इं ५, का ६, यो ३ औमि वैमि का, वे. १ पं, क ४, ज्ञा ५ कु कु म श्रु अ, सं १ अ, द ३ अ च अ, ले २ क शु भ २, स ४ मि सा वे क्षा,
भा ३ अशु
सं २, आ २, उ ८। तन्मिथ्यादृशां—गु १ मि, जी १४, प ६, ६, ५, ५, ४, ४, प्रा १०, ७, ९, ७, ८, ६, ७, ५, ६, ४, ४, ३, सं ४, ग ३ न ति म, इं ५, का ६, यो १३ आहारद्वयं नहि, वे १ न, क ४, ज्ञा ३ कु कु वि, सं १ अ, द २, ले ६, भ २, स १ मि, सं २, आ २ उ ५। तत्पर्याप्तानां—गु १ मि, जी
६
७, प ६, ५, ४, प्रा १०, ९, ८ ७ ६, ४, सं ४, ग ३ न ति म, इं ५, का ६, यो १० म ४ व ४ औ वै, वे १ पं, क ४, ज्ञा ३ कु कु वि, सं १ अ, द २। ले ६। भ २, स १ मि, सं २, आ १, उ ५। तद-
६
पर्याप्तानां—गु १ मि, जी ७, प ६, ५, ४, प्रा ७, ७, ६, ५, ४, ३, सं ४, ग ३ न ति म, इं ५, का ६,

नपुंसकवेदिअसंयतसम्यग्दृष्टिगळ्गे । गु १ । असं । जी २ । प । अ । प ६ । ६ । प्रा १० । ७ । सं ४ । ग ३ । न ति । म । इं १ । का १ । यो १२ । म ४ । व ४ । ओ का १ । वैं का १ । का १ । वे १ नपुं । क ४ । ज्ञा ३ । म । श्रु । अ । सं १ । अ । द ३ । च । अ । अ । ले ६ ६ भ १ । सं ३ । उ । वे । क्षा । सं १ । आ २ । उ ६ ॥

नपुंसकवेदि असंयतपर्य्याप्तकंगे । गु १ । अ । जी १ । प । प ६ । प्रा १० । सं ४ । ग ३ । न । ति । म । इं १ । का १ । यो १० । म ४ । व ४ । औ १ । वै १ । वे १ । नपुं । क ४ । ज्ञा ३ । म । श्रु । अ । सं १ । अ । द ३ । च । अ । अ । ले ६ ६ भ १ । सं ३ । उ । वे । क्षा । सं १ । आ १ । उ ६ ॥

नपुंसकवेदिअपर्य्याप्तासंयतंगे । गु १ । अ । जी १ । अ । प ६ । अ प्रा ७ । अ । सं ४ । ग १ । न । इं १ । का १ । यो २ । वैमि १ । का १ । वे १ । नपुं । क ४ । ज्ञा ३ । सं १ । अ । द ३ । च । अ । अ । ले २ क शु भा १ अ शु । भ १ । सं २ । क्षा । वे । सं १ । आ २ । उ ६ ॥

नपुंसकवेदिदेशव्रतिगळ्गे । गु १ । दे । जो १ । प । प ६ । प्रा १० । सं ४ । ग २ । ति म । इं १ । का १ । यो ९ । म ४ । वा ४ । औ का १ । वे १ नपुं । क ४ । ज्ञा ३ । म । श्रु । अ । सं १ । दे । द ३ । च । अ । अ । ले ६ भा ३ शु । भ १ । सं ३ उ । वे । क्षा । सं १ । आ १ । उ ६ ॥

नपुंसकवेदिप्रमत्तप्रभृतिप्रथमभागानिवृत्तिपर्य्यंतं स्त्रीवेदिगळ भंगमक्कुं विशेषमावुदें दोडे सर्व्वत्र नपुंसकवेदमों दे वक्तव्यमक्कुं ॥

ज्ञा ३ कु कु वि, सं १ अ, द २, च अ, ले ६ ६, भ १, स १ मिथ्यं, सं १, आ १, उ ५ । तदसंयतानां—

गु १ अ, जी २ प अ, प ६, ६, प्रा १०, ७, सं ४, ग ३ न ति म, इं १ पं, का १ त्र, यो १२ म ४ व ४ औ वै वैमि का, वे १ न, क ४, ज्ञा ३ म श्रु अ, सं १ अ, द ३ च अ अ, ले ६ ६, भ १, स ३, सं १, आ २, उ ६ । तत्पर्याप्तानां—गु १ अ, जी १ प, प ६, प्रा १०, सं ४, ग ३ न ति म । इ १, का १, यो १० म ४ व ४ औ १ वै १, वे १ न, क ४, ज्ञा ३ म श्रु अ, सं १ अ, द ३ च अ अ, ले ६ ६ । भ १, स ३ उ वे क्षा, सं १, आ १, उ ६ । तदपर्याप्तानां—गु १ अ । जी १ अ । प ६ अ । प्रा ७ अ । सं ४ । ग १ न । इं १ । का १ । यो २ वैमि का । वे १ न । क ४ । ज्ञा ३ । सं १ अ । द ३ च अ अ । ले २ क शु भा ३ अशुभ । भ १ । स २ वे क्षा । सं १ । आ २ । उ ६ । देशव्रतिनां—गु १ दे । जो १ प । प ६ । प्रा १० । सं ४ । ग २ ति म । इं १ । का १ । यो ९ म ४ व ४ औ १ । वे १ न । क ४ । ज्ञा ३ म श्रु अ । सं १ दे । द ३ च अ अ । ले ६ भा ३ शु । भ १ । स ३ उ वे क्षा । सं १ । आ १ । उ ६ । प्रमत्तात् प्रथमभागानिवृत्त्यंतं स्त्रीवेदिवत् किंतु वेदस्थाने नपुंसकवेद एव ।

व। अ। ले २ क शु। भ २। सं ५। मि। सा। उ। वे। क्षा। सं २। आ २। उ ८॥
भा ६

क्रोधकषायिमिथ्यादृष्टिगळ्गे। गु १। मि। जी १४। प ६। ६। ५। ५। ४। ४। प्रा १०। ७। ९। ७। ८। ६। ७। ५। ६। ४। ३। सं ४। ग ४। इं ५। का ६। यो १३। आहारद्वय-रहित। वे ३। क १ क्रो। ज्ञा ३। कु। कु। वि। सं १। अ। द २। च। अ। ले ६ । भ २।
६
सं १। मि। सं २। आ २। उ ५॥

क्रोधकषायिमिथ्यादृष्टिपर्य्याप्तरुगे। गु १। मि। जी ७। प। प ६। ५। ४। प। प्रा १०। ९। ८। ७। ६। ४। सं ४। ग ४। इं ५। का ६। यो १०। म ४। वा ४। औ। वै। वे ३। क १। क्रो। ज्ञा ३। कु। कु। वि। सं १। अ। द २। च। अ। ले ६। भ २। सं १। मि।
६
सं २। आ १। उ ५॥

क्रोधकषायिमिथ्यादृष्ट्यपर्य्याप्तरुगे। गु १। मि। जी ७। अ। प ६। ५। ४। अ। प्रा ७। ७। ६। ५। ४। ३। अ। सं ४। ग ४। इं ५। का ६। यो ३। औ मि।। वै मि। का। वे ३। क १ क्रो। ज्ञा २। कु। कु। सं १। अ। द २। ले २ क शु। भ २। सं १। मि। सं २।
भा ६
आ २। उ ४॥

क्रोधकषायिसासादनंगे। गु १। सा। जी २। प अ। प ६। ६। प्रा १०। ७। सं ४। ग ४। इं १। पं। का १। त्र। यो १३। हारद्वयवर्जित। वे ३। क १ क्रो। ज्ञा ३। कु। कु। वि। सं १। अ। द २। ले ६ । भ १। सं १। सासा। सं १। आ २। उ ५॥
६

म श्रु अ, सं १ अ सा छे, द ३ च अ अ, ले २ क शु, भ २, स ५ मि सा उ वे क्षा, सं २
भा ६
आ २, उ ८। तन्मिथ्यादृशां—गु १ मि, जी १४, प ६, ६, ५, ५, ४, ४, प्रा १० ७ ९ ७ ८ ६ ७ ५ ६ ४ ४ ३, सं ४, ग ४, इं ५, का ६। यो १३ आहारद्वयं नहि, वे ३, क १ क्रो, ज्ञा ३ कु कु वि, सं १ अ, द २ च अ। ले ६। भ २। स १ मि। सं २। आ २। उ ५। तत्पर्याप्तानां—गु १ मि। जी ७। प ६।
भा ६
५। ४। प्रा १०। ९। ८। ७। ६। ४। सं ४। ग ४। इं ५। का ६। यो १० म ४ व ४ औ १ वै १। वे ३। क १ क्रो। ज्ञा ३ कु कु वि। सं १ अ। द २ च अ। ले ६। भ २। स १ मि। सं २।
६
आ १। उ ५। तदपर्याप्तानां—गु १ मि। जी ७ अ। प ६ ५ ४ अ। प्रा ७। ७। ६। ५। ४। ३ अ। सं ४। ग ४। इं ५। का ६। यो ३ औमि वैमि का। वे ३। क १ क्रो। ज्ञा २ कु कु। सं १ अ। द २। ले २ क शु। भ २। स १ मि। सं २। आ २। उ ४। तत्सासादनानां—गु १ सा।
भा ६
जी २ प अ। प ६ ६। प्रा १०। ७। सं ४। ग ४। इं १ पं। का १ त्र। यो १३ आहारद्वयवर्ज्यं। वे ३। क १ क्रो। ज्ञा ३ कु कु वि। सं १ अ। द २। ले ६। भ १। स १ सा। सं १। आ १। उ ५।
६

क्रोधकषायिअपर्य्याप्तासंयतंगे। गु १। असं। जी १। अ। प ६। अ। प्रा ७। अ। सं ४। ग ४। इं १। पं। का १। त्र। यो ३। औ मि। वै मि। का। वे २। पुं। नपुं। क १ क्रो। ज्ञा ३। म। श्रु। अ। सं १। अ। द ३। च। अ। अ। । ले २ क शु भा ६। भ १। सं ३। उ। वे। क्षा। सं १। आ २। उ ६॥

क्रोधकषायिदेशव्रतिकंगे। गु १। दे। जी १। प। प ६। प्रा १०। सं ४। ग २। ति। म। इं १। पं। का १ त्र। यो ९। वे ३। क १ क्रो। ज्ञा ३। म। श्रु। अ। सं १। दे। द ३। च। अ। अ। ले ६ भा ६। भ १। सं ३। उ। वे। क्षा। सं १। आ १। उ ६॥

क्रोधकषायिप्रमत्तसंयतंगे। गु १। प्र। जी २। प ६। ६। प्रा १०। ७। सं ४। ग १ म। इं १ पं। का १ त्र। यो ११। म ४। वा ४। औ १। आ २। वे ३। क १ क्रो। ज्ञा ४। म। श्रु। अ। म। सं ३। सा। छे। प। द ३। ले ६ भा ३। भ १। सं ३। उ। वे। क्षा। सं १। आ १। उ ७॥

क्रोधकषायाप्रमत्तंगे। गु १ अप्र। जी १। प ६। प्रा १०। सं ३। भ। मै। प। ग १। म। इं १। पं। का १ त्र। यो ९। वे ३। क १ क्रो। ज्ञा ४। म। श्रु। अ। म। सं ३। सा। छे। प। द ३। च। अ। अ। ले ६ भा ३। भ १। सं ३। उ। वे। क्षा। सं १। आ १। उ ७॥

क्रोधकषायिअपूर्व्वकरणंगे। गु १ अपू। जी १। प। प ६। प्रा १०। सं ३। भ। मै। प। ग १। म। इं १ पं। का १ त्र। यो ९। वे ३। क १ क्रो। ज्ञा ४। म। श्रु। अ। म। सं २। सा। छे। द ३। च। अ। अ। ले ६ भा १। भ १। सं २। उ। क्षा। सं १। आ १। उ ७॥

उ ६। तदपर्याप्तानां—गु १ अ। जी १ अ। प ६ अ। प्रा ७ अ। सं ४। ग ४। इं १ पं। का १ त्र। यो ३ औमि वैमि का। वे २ पु न। क १ क्रो। ज्ञा ३ म श्रु अ। स १ अ। द ३ च अ अ। ले २ क शु भा ६। भ १। स ३ उ वे क्षा। सं १। आ २। उ ६। देशव्रतानां—गु १ दे। जी १ प। प ६। प्रा १०। सं ४। ग २ ति म। इं १ पं। का १ त्र। यो ९। वे ३। क १ क्रो। ज्ञा ३ म श्रु अ। सं १ दे। द ३ च अ अ। ले ६ भा ६। भ १। स ३ उ वे क्षा। सं १। आ १। उ ६। प्रमत्तानां—गु १ प्र। जी २ प अ। प ६ ६। प्रा १० ७। सं ४। ग १ म। इं १ पं। का १ त्र। यो ११ म ४। व ४। औ १। आ २। वे ३। क १ क्रो। ज्ञा ४ म श्रु अ म। सं ३ सा छे प। द ३। ले ६ भा ३। भ १। स ३ उ वे क्षा। सं १। आ १। उ ७। अप्रमत्तानां—गु १ अप्र। जी १। प ६। प्रा १०। सं ३ भ मै प। ग १ म। इं १ पं। का १ त्र। यो ९। वे ३। क १ क्रो। ज्ञा ४ म श्रु अ म। सं ३ सा छे प। द ३ च अ अ। ले ६ भा ३। भ १। स ३ उ वे क्षा। सं १। आ १। उ ७। अपूर्वकरणानां—गु १ अपू। जी १ प। प ६। प्रा १०। सं ३ भ मै प। ग १ म। इं १ पं। का १ त्र। यो ९। वे ३। क १ क्रो। ज्ञा ४ म श्रु अ म। सं २ सा छे। द ३ च अ अ। ले ६ भा १। भ १। स २ उ

२। सं ४। ग ४। इं ५। का ६। यो १३। वे ३। क ४। ज्ञा २। सं १ अ। द २। ले $\frac{६}{६}$। भ २। सं २। मि। सा। सं २। आ २। उ ४॥

कुमतिकुश्रुतज्ञानिपर्य्याप्तकर्गों। गु २। मि। सा। जी ७। प। प ६। ५। ४। प्रा १०। ९। ८। ७। ६। ४। सं ४। ग ४। इं ५। का ६। यो १०। म ४। वा ४। औ का १। वै का १। वे ३। क ४। ज्ञा २। कु। कु। सं १। अ। द २। च। अ। ले $\frac{६}{६}$। भ २। सं २। मि। सा। सं २। आ १। उ ४॥

कुमतिकुश्रुतज्ञानिअपर्य्याप्तकर्गों। गु २। मि। सा। जी ७। अ। प ६। ५। ४। अ। प्रा ७। ७। ६। ५। ४। ३। सं ४। ग ४। इं ५। का ६। यो ३। *औमि। वैमि। का।* वे ३। क ४। ज्ञा २। सं १। अ। द २। ले $\frac{२ क शु}{भा ६}$। भ २। सं २। मि। सा। सं २। आ २। उ ४॥

कुमतिकुश्रुतज्ञानिमिथ्यादृष्टिगळ्गों। गु १। मि। जी १४। प ६। ६। ५। ५। ४। ४। प्रा १०। ७। ९। ७। ८। ६। ७। ५। ६। ४। ४। ३। सं ४। ग ४। इं ५। का ६। यो १३। वे ३। क ४। ज्ञा २। सं १। अ। द २। ले $\frac{६}{६}$। भ २। सं १। मि। सं २। आ २। उ ४॥

कुमतिकुश्रुतज्ञानिपर्य्याप्तकर्गों। गु २। मि। सा। जी ७। प। प ६। ५। ४। प्रा १०। ९। ८। ७। ६। ४। सं ४। ग ४। इं ५। का ६। यो १०। म ४। वा ४। औ का १। वै का १। वे ३। क ४। ज्ञा २। कु। कु। सं १। अ। द २। च। अ। ले $\frac{६}{६}$। भ २। सं २। मि। सा। सं २। आ १। उ ४॥

३, सं ४। ग ४, इं ५, का ६, यो १३, वे ३, क ४, ज्ञा २, सं १ अ, द २, ले $\frac{६}{६}$, भ २, स २ मि सा, सं २, आ २, उ ४। तत्पर्याप्तानां—गु २ मि सा, जी ७ प, प ६ ५ ४, प्रा १० ९ ८ ७ ६ ४, सं ४, ग ४, इं ५, का ६, यो १० म ४ व ४ औ १ वै १, वे ३, क ४, ज्ञा २, कु कु, सं १ अ, द २ च अ, ले $\frac{६}{६}$, भ २, स २ मि सा, सं २, आ १, उ ४। तदपर्याप्तानां—गु २ मि सा, जी ७ अ, प ६ ५ ४, प्रा ७ ७ ६ ५ ४ ३, सं ४, ग ४, इं ५, का ६, यो ३ औमि वैमि का, वे ३, क ४, ज्ञा २, सं १ अ, द २ च अ, ले $\frac{२ क शु}{भा ६}$। भ २, स २ मि सा, सं २, आ २, उ ४। तन्मिथ्यादृशां—गु १ मि, जी १४, प ६ ६ ५ ५ ४ ४, प्रा १० ७ ९ ७ ८ ६ ७ ५ ६ ४ ४ ३, सं ४, ग ४, इं ५, का ६, यो १३ आहारद्वयवर्ज्यं, वे ३, क ४, ज्ञा २ कु कु, सं १ अ, द २ च अ, ले $\frac{६}{६}$, भ २, स १ मि, सं २, आ २, उ ४। तत्पर्याप्तानां—गु १ मि, जी ७ प, प ६ ५ ४ प, प्रा १० ९ ८ ७ ६ ४, सं ४, ग ४, इं ५, का ६, यो १०, म ४ व ४ औ १ वै १, वे ३, क ४, ज्ञा २ कु कु, सं १ अ, द २ च अ, ले $\frac{६}{६}$, भ २। स १ मि, सं २, आ १,

कुमतिकुश्रुतज्ञानिसासादनापर्य्याप्तकर्ग्गे । गु १ । सास । जो १ । अ । प ६ । अ । प्रा ७ । अ । सं ४ । ग ३ । ति । म । दे । इं १ । पं । का १ त्र । यो ३ । औ मि । वै मि । का । वे ३ । क ४ । ज्ञा २ । कु । कु । सं १ । अ । द २ । ले २ क शु । भ १ । सं १ । सासा । सं १ ।
भा ६
आ २ । उ ४ ॥

विभंगज्ञानिगक्र्ग्गे । गु २ । मि । सा । जो १ प । प ६ । प्रा १० । सं ४ । ग ४ । इं १ । पं । का १ त्र । यो १० । म ४ । वा ४ । औ का १ । वै का १ । वे ३ । क ४ । ज्ञा १ । विभंग । सं १ । अ । द २ । ले ६ । भ २ । सं २ । मि । सा । सं १ । आ १ । उ ३ ॥
६

विभंगज्ञानिमिथ्यादृष्टिगक्र्ग्ग । गु १ । मि । जो १ । प । प ६ । प्रा १० । सं ४ । ग ४ । इं १ । पं । का १ त्र । यो १० । वे ३ । क ४ । ज्ञा १ । सं १ । अ । द २ । ले ६ । भ २ ।
६
सं १ । मि । सं १ । आ १ । उ ३ ॥

विभंगज्ञानिसासादनंगे । गु १ । सासा । जो १ । प । प ६ । प्रा १० । सं ४ । ग ४ । इं १ । का १ । यो १० । म ४ । व ४ । औ का १ । वै का १ । वे ३ । क ४ । ज्ञा १ । विभंग । सं १ । अ । द २ । ले ६ । भ १ । सं १ । सासा । सं १ । आ १ । उ ३ ॥
६

मतिश्रुतज्ञानिगक्र्ग्गे । गु ९ । जो २ । प । अ । प ६ । ६ । प्रा १० । ७ । सं ४ । ग ४ । इं १ । का १ त्र । यो १५ । वे ३ । क ४ । ज्ञा २ । म । श्रु । सं ७ । द ३ । च । अ । अ । ले ६ ।
६
सं ३ । उ । वे । क्षा । सं १ । आ २ । उ ५ ॥

सं १, आ १, उ ४, तदपर्याप्तानां—गु १ सा, जो १ अ, प ६ अ, प्रा ७ अ, सं ४, ग ३ ति म दे, इं १ पं, का १ त्र, यो ३ औमि वैमि का, वे ३, क ४, ज्ञा २ कु कु, सं १ अ, द २, ले २ क शु । भ १, स १ सा,
भा ६
सं १, आ २, उ ४ । विभंगज्ञानिनां—गु २ मि सा, जो १ प, प ६, प्रा १०, सं ४, ग ४, इं १ पं, का १ त्र, यो १० म ४ व ४ औ १ वै १, वे ३, क ४, ज्ञा १ विभंगः । सं १ अ, द २, ले ६ । भ २,
६
स २ मि सा, सं १, आ १, उ ३ वि च अ । तन्मिथ्यादृष्टा—गु १ मि, जो १ प, प ६, प्रा १०, सं ४, ग ४, इं १ पं, का १ त्र, यो १०, वे ३, क ४, ज्ञा १, सं १ अ, द २, ले ६, भ २, स १ मि, सं १, आ
६
१, उ ३ । तत्सासादनानां—गु १ सा, जो १ प, प ६, प्रा १०, सं ४, ग ४, इं १, का १, यो १०, म ४ व ४ औ वै, वे ३, क ४, ज्ञा १ विभंगः । सं १ अ, द २, ले ६ । भ १, स १ सा, सं १, आ १, उ ३ ।
६
मतिश्रुतानां—गु ९, जो २ प अ । प ६ ६, प्रा १० ७, सं ४, ग ४ । इं १ । का १ त्र, यो १५ । वे ३ । क ४ । ज्ञा २ म श्रु । सं ७ । द ३ च अ अ । ले ६ । भ १ । स ३ उ वे क्षा । सं १, आ २ । उ ५ ।
६

औ २। का १। वे ०। क ०। ज्ञा ५। म। श्रु। अ। म। के। सं १। यथा। द ४। ले ६।
भा १
भ १। सं २। उ। क्षा। सं १। आ २। उ ९॥

उपशांतकषायप्रभृति अयोगिकेवलिपर्य्यंतं मूलौघभंगमक्कुं। देशसंयमक्के ओघभंगमेयक्कुं।

असंयमरुगळ्गे। गु ४। मि। सा। मि। अ। जी १४। प ६। ६। ५। ५। ४। ४। प्रा १०। ७। ९। ७। ८। ६। ७। ५। ६। ४। ४। ३। सं ४। ग ४। इं ५। का ६। यो १३। आहारकद्वयरहित। वे ३। क ४। ज्ञा ६। कु। कु। वि। म। श्रु। अ। सं १। अ। द ३। ले ६। भ २। सं ६। सं २। आ २। उ ९॥
६

असंयमिपर्य्याप्तकर्गे। गु ४। मि। सा। मि। अ। जी ७। प। प ६। ५। ४। प्रा १०। ९। ८। ७। ६। ४। सं ४। ग ४। इं ५। का ६। यो १०। म ४। व ४। औ का। वैं का। वे ३। क ४। ज्ञा ६। कु। कु। वि। म। श्रु। अ। सं १। अ। द ३। ले ६। भ २। सं ६।
६
मि। सा। मि। उ। वे। क्षा। सं २। आ १। उ ९॥

असंयमि अपर्य्याप्तकंगे। गु ३। मि। सा। अ। जी ७। अ। प ६। ५। ४। अ। प्रा ७। ७। ६। ५। ४। ३। सं ४। ग ४। इं ५। का ६। यो ३। औ मि। वै मि। का। वे ३। क ४। ज्ञा ५। कु। कु। म। श्रु। अ। सं १। अ। द ३। च। अ। अ। ले २ क शु। भ २। सं ५।
भा ६
मि। सा। उ। वे। क्षा। सं २। आ २। उ ८॥

मिथ्यादृष्टिप्रभृति असंयतसम्यग्दृष्टिपर्य्यंतं मूलौघभंगमक्कुं। इंतु संयममार्ग्गणे समाप्तमादुदु॥

ग १ म। इं १ पं। का १ त्र। यो ११ म ४ व ४ औ २ का १। वे ०। क ०। ज्ञा ५ म श्रु अ म के। सं १ य। द ४। ले ६। भ १। स २ उ क्षा। सं १। आ २। उ ९। उपशांतकषायाद्ययोगपर्यंतं देश-
१
संयतानां च मूलौघभंगः।

असंयतानां—गु ४ मि सा मि अ। जी १४। प ६। ६। ५। ५। ४। ४। प्रा १०। ७। ९। ७। ८। ६। ७। ५। ६। ४। ४। ३। सं ४। इं ५। का ६। यो १३ आहारद्वयं नहि। वे ३। क ४। ज्ञा ६ कु कु वि म श्रु अ। सं १ अ। द ३। ले ६। भ २। स ६। सं २। आ २। उ ९। तत्पर्याप्तानां—
६
गु ४ मि सा मि अ। जी ७। प ६। ५। ४। प्रा १०। ९। ८। ७। ६। ४। सं ४। ग ४। इं ५। का ६। यो १० म ४ व ४ औ १ वै १। वे ३। क ४। ज्ञा ६ कु कु वि म श्रु अ। सं १ अ। द ३। ले ६। भ २। स ६ मि सा मि उ वे क्षा। सं २। आ १। उ ९। तदपर्याप्तानां—गु ३ मि सा अ।
६
जी ७ अ। प ६। ५। ४। प्रा ७। ७। ६। ५। ४। ३। सं ४। ग ४। इं ५। का ६। यो ३ औमि वैमि का। वे ३। क ४। ज्ञा ५ कु कु म श्रु अ। सं १ अ, द ३ च अ अ, ले २ क शु। भ २,
भा ६
स ५ मि सा उ वे क्षा, सं २, आ २, उ ८। मिथ्यादृष्टितोऽसंयतांतं मूलौघभंगो भवति, संयममार्गणा गता।
दर्शनानुवादे ओघालापो भवति—

अवधिदर्शनिगळ्गे। गु ९। जो २। प। अ। प ६। ६। प्रा १०। ७। सं ४। ग ४। इं १। पं। का १ त्र। यो १५। वे ३। क ४। ज्ञा ४। म। श्रु। अ। म। सं ७। द १। अवधि-दर्शन। ले ६। भ १। सं ३। उ। वे क्षा। सं १। आ २। उ ५॥
६

अवधिदर्शनिपर्य्याप्तकर्गे।। गु ९। जो १ प। प ६। प्रा १०। सं ४। ग ४। इं १। पं। का १ त्र। यो ११। म ४। व ४। औ का। वै का। आ का। वे ३। क ४। ज्ञा ४। म। श्रु। अ। म। सं ७। द १। अवधि। ले ६। भ १। सं ३। सं १। आ १। उ ५॥
६

अवधिदर्शनिअपर्य्याप्तकर्गे। गु २। अ। प्र। जी १। प ६। अ प्रा ७। सं ४। ग ४। इं १ पं। का १ त्र। यो ४। औ मि। वै मि। आ मि। का। वे २। पुं। पं। क ४। ज्ञा ३। म। श्रु। अ। सं ३। अ। सा। छे। द १ अवधि। ले २। भ १। सं ३। सं १।
भा ६
आ २। उ ४॥

"असंयतप्रभृतिक्षीणकषायपर्य्यंतं अवधिज्ञानक्कै पेळ्दंते वक्तव्यमक्कुं। केवलदर्शनिगे केवलदर्शनिगे केवलज्ञानिगे पेळ्दंते वक्तव्यमक्कुं। इंतु दर्शनमार्गणे समाप्तमादुदु॥

लेश्यानुवाददोळु गुणस्थानालापं मूलोघदंतक्कुं। विशेषमावुदेंदोडे अयोगिगुणस्थानमिल्ल। कृष्णलेश्याजीवंगळ्गे। गु ४। मि। सा। मि। अ। जो १४। प ६। ६। ५। ५। ४। ४। प्रा १०। ७। ९। ७। ८। ६। ७। ५। ६। ४। ४। ३। सं ४। ग ४। इं ५। का ६। यो १३। वे ३। क ४। ज्ञा ६। कु। कु। वि। म। श्रु। अ। सं १। अ। द ३। च। अ। अ। ले ६। भ २।
भा १ कृ
सं ६। मि। सा। मि। उ। वे। क्षा। सं २। आ २। उ ९॥

कृष्णलेश्यपर्य्याप्तकर्गे। गु ४। मि। सा। मि। अ। जी ७। प। प ६। ५। ४।

अवधिदर्शनिनां—गु ९, जी २ प अ, प ६, ६, प्रा १०, ७, सं ४। ग ४, इं १ पं, का १ त्र, यो १५, वे ३, क ४, ज्ञा ४ म श्रु अ म, सं ७, द १ अ, ले ६। भ १, स ३ उ वे क्षा, सं १, आ २,
६
उ ५। तत्पर्याप्तानां—गु ९, जी १ प, प ६, प्रा १०, सं ४, ग ४, इं १ पं, का १ त्र, यो ११ म ४, व ४, औ १, वै १, आ १, वे ३, क ४, ज्ञा ४ म श्रु अ म, सं ७, द १ अ, ले ६। भ १। स ३, सं १, आ १,
६
उ ५। तदपर्याप्तानां—गु २ अ प्र, जी १ अ, प ६ अ, प्रा ७, सं ४, ग ४, इं ५, का १ त्र, यो ४ औमि वैमि आमि का, वे २ पुं न, क ४, ज्ञा ३ म श्रु अ, स ३ अ सा छे, द १ अ, ले २, भ २, स ३, सं १।
६
आ २, उ ४। असंयतात् क्षीणकषायांतं अवधिज्ञानिवत्। केवलदर्शनिनां केवलज्ञानिवत्। दर्शनमार्गणा गता। लेश्यानुवादे गुणस्थानालापो मूलोघवत्। अयोगिगुणस्थानं नास्ति।

कृष्णलेश्यानां—गु ४ मि सा मि अ। जो १४। प ६, ६, ५, ५, ४, ४, प्रा १०, ७, ९, ८, ६, ७, ५, ६, ४, ४, ३, सं ४, ग ४, इं ५, का ६, यो १३, वे ३, क ४, ज्ञा ६ कु कु वि म श्रु अ, सं १ अ, द ३ च अ अ, ले ६। भ २। स ६ मि सा मि उ वे क्षा, सं २, आ २, उ ९। तत्पर्याप्तानां—
भा १ कृ

अवधिदर्शनिगळ्गे। गु ९। जी २। प। अ। प ६। ६। प्रा १०। ७। सं ४। ग ४। इं १। पं। का १ त्र। यो १५। वे ३। क ४। ज्ञा ४। म। श्रु। अ। म। सं ७। द १। अवधिदर्शन। ले ६। भ १। सं ३। उ। वे क्षा। सं १। आ २। उ ५॥
६

अवधिदर्शनिपर्य्याप्तकर्ग्गे।। गु ९। जी १ प। प ६। प्रा १०। सं ४। ग ४। इं १। पं। का १ त्र। यो ११। म ४। व ४। औ का। वै का। आ का। वे ३। क ४। ज्ञा ४। म। श्रु। अ। म। सं ७। द १। अवधि। ले ६। भ १। सं ३। सं १। आ १। उ ५॥
६

अवधिदर्शनिअपर्य्याप्तकर्ग्गे। गु २। अ। प्र। जी १। प ६। अ प्रा ७। सं ४। ग ४। इं १ पं। का १ त्र। यो ४। औ मि। वै मि। आ मि। का। वे २। पुं। पं। क ४। ज्ञा ३। म। श्रु। अ। सं ३। अ। सा। छे। द १ अवधि। ले २। भ १। सं ३। सं १।
भा ६
आ २। उ ४॥

"असंयतनभृतिक्षीणकषायपर्य्यंतं अवधिज्ञानदके पेळदंते वक्तव्यमक्कुं। केवलदर्शनिगे केवलदर्शनिगे केवलज्ञानिगे पेळ्दंते वक्तव्यमक्कुं। इंतु दर्शनमार्ग्गणे समाप्तमादुदु॥

लेश्यानुवाददोळु गुणस्थानालापं मूलोघदंतक्कुं। विशेषमावुदें दोडे अयोगिगुणस्थानमिल्ल। कृष्णलेश्याजीवंगळ्गे। गु ४। मि। सा। मि। अ। जी १४। प ६। ६। ५। ५। ४। ४। प्रा १०। ७। ९। ७। ८। ६। ७। ५। ६। ४। ४। ३। सं ४। ग ४। इं ५। का ६। यो १३। वे ३। क ४। ज्ञा ६। कु। कु। वि। म। श्रु। अ। सं १। अ। द ३। च। अ। अ। ले ६। भ २।
भा १ कृ
सं ६। मि। सा। मि। उ। वे। क्षा। सं २। आ २। उ ९॥

कृष्णलेश्यपर्य्याप्तकर्ग्गे। गु ४। मि। सा। मि। अ। जी ७। प। प ६। ५। ४।

अवधिदर्शनिना—गु ९, जी २ प अ, प ६, ६, प्रा १०, ७, सं ४। ग ४, इं १ पं, का १ त्र, यो १५, वे ३, क ४, ज्ञा ४ म श्रु अ म, सं ७, द १ अ, ले ६। भ १, स ३ उ वे क्षा, सं १, आ २,
६
उ ५। तत्पर्याप्ताना—गु ९, जी १ प, प ६, प्रा १०, सं ४, ग ४, इं १ पं, का १ त्र, यो ११ म ४, व ४, औ १, वै १, आ १, वे ३, क ४, ज्ञा ४ म श्रु अ म, सं ७, द १ अ, ले ६। भ १। स ३, सं १, आ १,
६
उ ५। तदपर्याप्तानां—गु २ अ प्र, जी १ अ, प ६ अ, प्रा ७, सं ४, ग ४, इं ५, का १ त्र, यो ४ औमि वैमि आमि का, वे २ पुं न, क ४, ज्ञा ३ म श्रु अ, स ३ अ सा छे, द १ अ, ले २, भ २, स ३, सं १।
६
आ २, उ ४। असंयतात् क्षीणकषायांतं अवधिज्ञानिवत्। केवलदर्शनिनां केवलज्ञानिवत्। दर्शनमार्गणा गता। लेश्यानुवादे गुणस्थानालापो मूलोघवत्। अयोगिगुणस्थानं नास्ति।

कृष्णलेश्यानां—गु ४ मि सा मि अ। जी १४। प ६, ६, ५, ५, ४, ४, प्रा १०, ७, ९, ८, ६, ७, ५, ६, ४, ४, ३, सं ४, ग ४, इं ५, का ६, यो १३, वे ३, क ४, ज्ञा ६ कु कु वि म श्रु अ, सं १ अ, द ३ च अ अ, ले ६। भ २। स ६ मि सा मि उ वे क्षा, सं २, आ २, उ ९। तत्पर्याप्तानां—
भा १ कृ

ज्ञा २। कु। कु। सं १। च। द २। ले २ कशु। भ २। सं १। मि। सं २। आ २। उ ४॥
भा १ कृ

कृष्णलेश्यासासादनंगे। गु १। सासा। जी २। प। अ। प ६। ६। प्रा १०। ७। सं ४। ग ४। इं १। पं। का १ त्र। यो १३। आहारद्वयरहित। वे ३। क ४। ज्ञा ३। कु। कु। वि। सं १। अ। द २। ले ६। भ १। सं १। सासा। सं १। आ २। उ ५॥
भा १ कृ

कृष्णलेश्यासासादनपर्य्याप्तकर्ग्गे। गु १। सा। जी १। प। प ६। प्रा १०। सं ४। ग ३। न। ति। म। इं १। पं। का १ त्र। यो १०। म ४। वा ४। औ का। वै का। वे ३। क ४। ज्ञा ३। कु। कु। वि। सं १। अ। द २। ले ६। भ १। सं १। सासा। सं १। आ २। उ ५॥
भा १ कृ

कृष्णलेश्यासासादनापर्य्याप्तकर्ग्गे। गु १। सा। जी १। अ। प ६। अ। प्रा ७। अ। सं ४। ग ३। ति। म। दे। इं १। पं। का १ त्र। यो ३। औ मि। वै मि। का। वे ३। क ४। ज्ञा २। सं १। अ। द २। ले २ कशु। भ १। सं १। सासा। सं १। आ २। उ ४॥
भा १ कृ

कृष्णलेश्यामिश्रंग। गु १ मिश्र। जी १ प। प ६। प। प्रा १०। सं ४। ग ३। न। ति। म। देवगतियोळु कृष्णलेश्ये पर्य्याप्तकंगे संभविसदु। अपर्य्याप्तकालदोळ्मिश्रमिल्ल। इं १। पं। का १ त्र। यो १०। म ४। वा ४। औ का। वै का। वे ३। क ४। ज्ञा ३। मिश्रज्ञानंगळु। सं १। अ। द २। च। अ। ले ६। भ १। सं १। मिश्ररुचि। सं १। आ १। उ ५॥
भा १ कृ

कृष्णलेश्याऽसंयतसम्यग्दृष्टिगळ्गे। गु १। अ सं। जी २। प। अ। प ६। ६। प्रा १०। ७। सं ४। ग ३। न। ति। म। कृष्णलेश्याऽसंयतंगे। देवगति संभविसदु। इं १ पं। का १ त्र।

वे ३, क ४, ज्ञा २, कु कु, स १। सं १ अ, द २, ले २ क शु। भ २, स १ मि, सं २, आ २, उ ४।
भा १ कृ

तत्सासादनानां—गु १ सा, जी २ प अ, प ६, ६, प्रा १०, ७, सं ४, ग ४, इं १ पं, का १ त्र, यो १३ आहारद्वयाभावात्। वे ३, क ४, ज्ञा ३ कु कु वि, सं १ अ, द २, ले ६, भ १, स १ सा, सं १, आ २,
भा १ कृ

उ ५। तत्पर्याप्तानां—गु १ सा, जी १ प, प ६, प्रा १०, सं ४, ग ३ न ति म, इं १ पं, का १ त्र, यो १० म ४ व ४ औ वै, वे ३, क ४। ज्ञा ३ कु कु वि। सं १ अ, द २, ले ६। भ १, स १ सा, सं १, आ १,
भा १

उ ५। तदपर्याप्तानां—गु १ सा, जी १ अ, प ६ अ, प्रा ७ अ, सं ४, ग ३ ति म दे, इं १ पं, का १ त्र, यो ३ औमि वैमि का, वे ३, क ४, ज्ञा २ कु कु, सं १ अ, द २, च अ ले २ क शु। भ १, स १ सा,
भा १ कृ

सं १, आ २, उ ४। तन्मिश्राणां—गु १ मिश्र, जी १ पं, प ६, प्रा १०, सं ४, ग ३ न ति म, देवगतौ पर्याप्ते कृष्णलेश्या अपर्याप्ते मिश्रगुणस्थानं च नहि। इं १ पं, का १ त्र, यो १० म ४ व ४ औ वै, वे ३, क ४, ज्ञा ३ मिश्राणि, सं १ अ, द २ च अ, ले ६, भ १, स १ मिश्रं, सं १, आ १, उ ५। तदसंयतानां—
भा १ कृ

गु १ असं। जी २ प अ, प ६, ६, प्रा १०, ७, सं ४, ग ३ न ति म तेषां देवगतिर्नहि। इं १ पं, का १ त्र,

कपोतलेश्या पर्य्याप्तकर्गों । गु ४ । मि । सा । मि । अ । जो ७ । प । प ६ । ५ । ४ । प्रा १० । ९ । ८ । ७ । ६ । ४ । सं ४ । ग ३ । न । ति । म । अशुभलेश्याऽपर्य्याप्तकंगे देवगति संभविसवु । भवनत्रयादिदेवर्कळनितुं पर्य्याप्तकालदोळु शुभलेश्यरेयप्पुदरिदं । इं ५ । का ६ । यो १० । म ४ । वा ४ । औ का । वै का । वे ३ । क ४ । ज्ञा ६ । कु । कु । वि । म । श्रु । अ । सं १ । अ । द ३ । ले ६ । भ २ । सं ६ । मि । सा । मि । उ । वे । क्षा । सं २ । आ १ । उ ९ ॥
भा १

कपोतलेश्या अपर्य्याप्तकर्गों । गु ३ । मि । सा । अ । जो ७ । अ । प ६ । ५ । ४ । अ । प्रा ७ । ७ । ६ । ५ । ४ । ३ । सं ४ । ग ४ । इं ५ । का ६ । यो ३ । औ मि । वै मि । का । वे ३ । क ४ । ज्ञा ५ । कु । कु । । म । श्रु । अ । सं । अ । द ३ । च । अ । अ । ले २ क शु ।
भा १ क
भ २ । सं २ । मि । सा । वे । क्षा । सं २ । आ २ । उ ८ ॥

कपोतलेश्यामिथ्यादृष्टिगळ्गे । गु १ । मि । जो १४ । प ६ । ६ । ५ । ५ । ४ । ४ । प्रा १० । ७ । ९ । ७ । ८ । ६ । ७ । ५ । ६ । ४ । ४ । ३ । सं ४ । ग ४ । इं ५ । का ६ । यो १३ । वे ३ । क ४ । ज्ञा ३ । कु । कु । वि । सं १ । अ । द २ । च । अ । ले ६ । भ २ । सं १ । मि ।
भा १ क
आ २ । उ ५ ॥

कपोतलेश्यामिथ्यादृष्टिपर्य्याप्तकर्गों । गु १ । मि । जो ७ । प । प ६ । ५ । ४ । प्रा १० । ९ । ८ । ७ । ६ । ४ । सं ४ । ग ३ । न । ति । म । इं ५ । का ६ । यो १० । म ४ । वा ४ । औ का । वै का । वे ३ । क ४ । ज्ञा ३ । कु । कु । वि । सं १ । अ । द २ । च । अ । ले ६ । भ २ ।
भा १ क
सं १ । मि । सं २ । आ १ । उ ५ ॥

तत्पर्याप्तानां–गु ४ मि सा मि अ, जो ७ प, प ६, ५, ४, प्रा १०, ९, ८, ७, ६, ४, सं ४, ग ३ न ति म, देवगतिर्नहि भवनत्रयदेवानामपि पर्याप्तिकाले शुभलेश्यत्वात्, इं ५, का ६, यो १० म ४ व ४ औ वै, वे ३, क ४, ज्ञा ६ कु कु वि म श्रु अ, सं १ अ, द ३, ले ६ । भ २, स ६ मि सा मि उ वे क्षा, सं २, आ १,
भा १ क
उ ९ । तदपर्याप्तानां—गु ३ मि सा अ, जी ७ अ, प ६, ५, ४ अ । प्रा ७, ७, ६, ५, ४, ३, सं ४, ग ४, इं ५, का ६, यो ३ औमि वैमि का, वे ३, क ४, ज्ञा ६ कु कु वि म श्रु अ, सं १ अ, द ३ च अ अ, ले २ क शु, भ २, स ४ मि सा वे क्षा, सं २, आ २, उ ८ । तन्मिथ्यादृशां—गु १ मि, जी १४, प
भा १ क
६, ६, ५, ५, ४, ४, प्रा १०, ७, ९, ७, ८, ६, ७, ५, ६, ४, ४, ३, सं ४, ग ४, इं ५, का ६, यो १३, वे ३, क ४, ज्ञा ३ कु कु वि, सं १ अ, द २ च अ, ले ६ । भ २, स १ मि, सं २, आ २, उ ५ ।
भा १ क
तत्पर्याप्तानां—गु १ मि, जी ७ प, प ६, ५, ४, प्रा १०, ९, ८, ७, ६, ४, सं ४, ग ३ न ति म, इं ५, का ६, यो १० म ४ व ४ औ वै, वे ३, क ४, ज्ञा ३ कु कु वि, सं १ अ, द २ च अ, ले ६ । भ २,
भा १ क

कपोतलेश्याऽसंयतसम्यग्दृष्टिगळ्गे। गु १। असं। जी २। प। अ। प ६। ६। प्रा १०। ७। सं ४। ग ३। न। ति। म। इं १। पं। का १ त्र। यो १३। औ २। वै २। म ४। व ४। का १। वे ३। क ४। ज्ञा ३। म। श्रु। अ। सं १। अ। द ३। ले ६ भा १ क। भ १। सं ३। सं १। आ १। उ ६॥

कपोतलेश्यासंयतसम्यग्दृष्टिपर्य्याप्तकंगे। गु १। असं। जी १ प। प ६। प्रा १०। सं ४। ग ३। न ति म। इं १ पं। का १ त्र। यो १०। म ४। व ४। वै का। औ का। वे ३। क ४। ज्ञा ३। म श्रु अ। सं १ अ। द ३। ले ६ भा १ क। भ १। सं ३। सं १। आ १। उ ६॥

कपोतलेश्याऽसंयतापर्य्याप्तकंगे। गु १। असं। जी १। अ। प ६। अ। प्रा ७ अ। सं ४। ग ३। न। ति। म। इं १। पं। का १ त्र। यो ३। औमि। वैमि। का। वे २। पुं। नपुं। क ४। ज्ञा ३। सं १। अ। द ३। ले २ क शु भा १ क। भ १। सं २। वे। क्षा। सं १। आ २। उ ६॥

तेजोलेश्याजीवंगळ्गे। गु ७। जी २। प। अ। प ६। ६। अ। प्रा १०। ७। सं ४। ग ३। म ति दे। इं १। पं। का १ त्र। यो १५। वे ३। क ४। ज्ञा ७। केवलरहित। सं ५। अ। दे। सा। छे। प। द ३। ले ६ भा १ ते। भ २। सं ६। सं १। आ २। उ १०॥

तेजोलेश्यापर्य्याप्तकंगे। गु ७। जी १। प। प ६। प्रा १०। सं ४। ग ३। ति। म। दे। इं १ पं। का १ त्र। यो ११। म ४। व ४। औ का १। वै १। आ १। वे ३। क ४। ज्ञा ७। केवलरहित। सं ५। अ। दे। सा। छे। प। द ३। ले ६ भा १ ते। भ २। सं ६। सं १। आ १। उ १०॥

क ४, ज्ञा ३ विभावि, सं १ अ, द २, ले ६ भा १ क, भ १, स १ मिथ्या, सं १, आ १, उ ५। [illegible]—

गु १ अ, जी २ प अ, प ६, ६, प्रा १०, ७, सं ४, ग ३ न ति म, इं १ पं, का १ त्र, यो १३ म ४ व ४ औ २ वै २ का १, वे ३, क ४, ज्ञा ३ म श्रु अ, सं १ अ, द ३, ले ६ भा १ क, भ १, स ३, सं १, आ २,

उ ६। [illegible]—गु १ अ, जी १ प, प ६, प्रा १०, सं ४, ग ३ न ति म, इं १ पं, का १ त्र, यो १० म ४ व ४ औ वै, वे ३, क ४, ज्ञा ३ म श्रु अ, सं १ अ, द ३, ले ६ भा १ क, भ १, स ३, सं १,

आ १, उ ६। [illegible]—गु १ अ, जी १ अ, प ६ अ, प्रा ७ अ, सं ४, ग ३ न ति म, इं १ पं, का १ त्र, यो ३ औमि वैमि का, वे २, पुं न, क ४, ज्ञा ३, सं १ अ, द ३, ले २ क शु भा १ क, भ १, स २

वे क्षा। सं १, आ २, उ ६। तेजोलेश्यासु—गु ७, जी २ प अ, प ६ ६, प्रा १० ७, सं ४, ग ३ ति म दे, इं १ पं, का १ त्र, यो १५, वे ३, क ४, ज्ञा ७ केवलं विना, सं ५ अ दे सा छे प, द ३, ले ६ भा १ ते, भ २,

स ६, सं १, आ २, उ १०। [illegible]—गु ७, जी १ प, प ६, प्रा १०, सं ४, ग ३ ति म दे,

का १। ये ३। क ४। ज्ञा ३। कु। कु। वि। सं १। अ। द २। ले ६। भ १। सं १।
भा १ ते
सासादनरुचि। सं १। आ २। उ ५॥

तेजोलेश्यासासादनपर्य्याप्तकग्गं। गु १। सा। जी १। प। प ६। प्रा १०। सं ४। ग ३। ति म दे। इं १। पं। का १ त्र। यो १०। म ४। वा ४। औ का। वै का। वे ३। क ४। ज्ञा ३। कु। कु। वि। सं १। द २। ले ६। भ १। सं १। सासा। सं १। आ १।
भा १ ते
उ ५॥

तेजोलेश्यासासादनापर्य्याप्तकग्गं। गु १। सासा। जी १। अ। प ६। अ। प्रा ७। अ। सं ४। ग १। दे। इं १। पं। का १ त्र। यो २ वै मि। का। वे २ स्त्री पुं। क ४। ज्ञा २। सं १। अ। द २। ले २ क शु। भ १। सं १। सासा। सं १। आ २। उ ४॥
भा १ ते

तेजोलेश्यासम्यग्मिथ्यादृष्टिगळ्गे। गु १। मिश्र। जी १। प। प ६। प्रा १०। सं ४। ग ३। ति। म। दे। इं १। का १। यो १०। वे ३। क ४। ज्ञा ३। सं १। अ। द २। ले ६। भ १।
भा १ ते
सं १। मिश्र। सं १। आ १। उ ५॥

तेजोलेश्यासंयतसम्यग्दृष्टिगळ्गे। गु १। अ सं। जी २। प। अ। प ६। ६। प्रा १०। ७। सं ४। ग ३। ति। म। दे। इं १। का १। यो १३। वे ३। क ४। ज्ञा ३। सं १। अ। द ३। ले ६। भ १। सं ३। सं १। आ २। उ ६॥
भा १ ते

तेजोलेश्यापर्य्याप्तासंयतग्गें। गु १। असं। जी १। प। प ६। प्रा १०। सं ४। ग ३।

प्रा १० ७। सं ४। ग ३ ति म दे। इं १ पं। का १ त्र। यो १२ म ४ व ४ औ १ वै २ का १। वे ३। क ४। ज्ञा ३ कु कु वि। सं १ अ। द २। ले ६। भ १। स १ सा। सं १। आ २। उ ५।
भा १ ते
तत्पर्याप्तानां—गु १ सा। जी १ प। प ६। प्रा १०। सं ४। ग ३ ति म दे। इं १ पं। का १ त्र। यो १० म ४ व ४ औ वै। वे ३। क ४। ज्ञा ३ कु कु वि। सं १ अ। द २। ले ६। भ १। स १ सा।
भा १ ते
सं १। आ १। उ ५। तदपर्याप्तानां—गु १ सा। जी १ अ। प ६ अ। प्रा ७ अ। सं ४। ग १ दे। इं १ पं। का १ त्र। यो २ वैमि का। वे २ स्त्री पुं। क ४। ज्ञा २। सं १ अ। द २। ले २ क शु।
भा १ ते
भ १। स १ सा। सं १। आ २। उ ४। सम्यग्मिथ्यादृशां—गु १ मिश्रं। जी १ प। प ६। प्रा १०। सं ४। ग ३ ति म दे। इं १ पं। का १ त्र। यो १० म ४ व ४ वै औ। वे ३। क ४। ज्ञा ३। सं १ अ। द २। ले ६। भ १। स १ मिश्रं। सं १। आ १। उ ५। असंयतानां—गु १ अ। जी २ प। अ। प ६ ६।
भा १ ते
प्रा १० ७। सं ४। ग ३ ति म दे। इं १ पं। का १ त्र। यो १३। वे ३। क ४। ज्ञा ३। सं १ अ। द ३। ले ६। भ १। स ३। सं १। आ २। उ ६। तत्पर्याप्तानां—गु १ अ। जी १ प। प ६। प्रा
भा १ ते

पद्मलेश्याजीवंगळ्गे । गु ७। जी २। प। अ। प ६। ६। प्रा १०। ७। सं ४। ग ३। ति। म। दे। इं १। का १। यो १५। वे ३। क ४। ज्ञा ७। सं ५। अ। दे। सा। छे। प। द ३। ले ६। भ २। सं ६। सं १। आ २। उ १०॥
भा १ पद्म

पद्मलेश्यापर्य्याप्तकर्गे। गु ७। जी १। प ६। प्रा १०। सं ४। ग ३। ति। म। दे। इं १। का १। यो ११। म ४। वा ४। औ का। वै का। आ का। वे ३। क ४। ज्ञा ७। सं ५। अ। दे। सा। छे। प। द ३। । ले ६। भ २। सं ६। सं १। आ १। उ १०॥
भा १ पद्म

पद्मलेश्याऽपर्य्याप्तकर्गे। गु ४। मि। सा। अ। प्र। जी १। अ। प ६। अ। प्रा ७। अ। सं ४। ग २। म। दे। इं १। पं। का १ त्र। यो ४। औ मि। वै मि। का। आ मि। वे १। पुं। क ४। ज्ञा ५। कु। कु। म। श्रु। अ। सं ३। अ। सा। छे। द ३। ले २ क शु।
भा १ पद्म
भ २। सं ५। मि। सा। उ। वे। क्षा। सं १। आ २। उ ८॥

पद्मलेश्यामिथ्यादृष्टिगळ्गे। गु १। मि। जी २। प। अ। प ६। ६। प्रा १०। ७। सं ४। ग ३। ति। म। दे। इं १। का १। यो १२। म ४। वा ४। औ का १। वै २। का १। वे ३। क ४। ज्ञा ३। कु। कु। वि। सं १। अ। द २। ले ६। भ २। सं १। मि। सं १।
भा १ प
आ २। उ ५॥

पद्मलेश्यामिथ्यादृष्टिपर्य्याप्तंगे गु १। जी १। प। प ६। प्रा १०। सं ४। ग ३। ति। म। दे। इं १। का १। यो १०। म ४। वा ४। औ का। वै का। वे ३। क ४। ज्ञा ३। कु। कु। वि। सं १। अ। द २। ले ६। भ २। सं १। मि। सं १। आ १। उ ५॥
भा १ प

आ १। उ ७। पद्मलेश्यानां—गु ७। जी २ प अ। प ६ ६। प्रा १० ७। सं ४। ग ३ ति म दे। इं १। का १। यो १५। वे ३। क ४। ज्ञा ७। सं ५ अ दे सा छे प। द ३। ले ६। भ २। स ६।
भा १ प
सं १। आ २। उ १०। तत्पर्याप्तानां—गु ७। जी १। प ६। प्रा १०। सं ४। ग ३ ति म दे। इं १। का १। यो ११ म ४ व ४ औ वै आ। वे ३। क ४। ज्ञा ७। सं ५ अ दे सा छे प। द ३। ले ६।
भा १ प
भ २। स ६। सं १। आ १। उ १०। तदपर्याप्तानां—गु ४ मि सा अ प्र। जी १ अ। प ६ अ। प्रा ७ अ। सं ४। ग २ म दे। इं १ पं। का १ त्र। यो ४ औमि वैमि आमि का। वे १ पुं। क ४। ज्ञा ५ कु कु म श्रु अ। सं ३ अ सा छे। द ३। ले २ क शु। भ २। स ५ मि सा उ वे क्षा। सं १।
भा १ प
आ २। उ ८। तन्मिथ्यादृशां—गु १ मि। जी २ प अ। प ६। ६। प्रा १०। ७। सं ४। ग ३ ति म दे। इं १। का १। यो १२ म ४ व ४ औ १ वै २ का। वे ३। क ४। ज्ञा ३ कु कु वि। सं १ अ। द २। ले ६। भ २। स १ मि। सं १। आ २। उ ५। तत्पर्याप्तानां—गु १ मि। जी १ प। प ६।
भा १ प
प्रा १०। सं ४। ग ३ ति म दे। इं १। का १। यो १० म ४ व ४ औ १ वै १। वे ३। क ४।

पद्मलेश्याऽसंयतसम्यग्दृष्टिगळ्गे। गु १। असं। जो २। प। अ। प ६। ६। प्रा १०। ७। सं ४। ग ३। ति। म। दे। इं १। का १। यो १३। आहारद्वयरहित। वे ३। क ४। ज्ञा ३। म। श्रु। अ। सं १। अ। द ३। ले ६। भ १। सं ३। उ। वे। क्षा। सं १।
भा १ प
आ २। उ ६॥

पद्मलेश्याऽसंयतपर्य्याप्तकर्गे। गु १। अ। जो १। प। प ६। प्रा १०। सं ४। ग ३। ति। म। दे। इं १। का १। योग १०। म ४। वा ४। औ का। वै का। वे ३। क ४। ज्ञा ३। सं १। अ। द ३। ले ६। भ १। सं ३। उ। वे। क्षा। सं १। आ १। उ ६॥
भा १ प

पद्मलेश्याऽसंयताऽपर्य्याप्तकर्गे। गु १। असं। जो १। अ। प ६। अ। प्रा ७। अ। सं ४। ग २। म। दे। इं १। का १। यो ३। औ मि। वै मि। का। वे १। क ४। ज्ञा ३। म। श्रु। अ। सं १। अ। द ३। ले २ क शु। भ १। सं ३। उ। वे। क्षा। सं १। आ २। उ ६॥
भा १ प

पद्मलेश्यादेशव्रतिगळ्गे गु १। देश। जो १। प। प ६। प्रा १०। सं ४। ग २। म। ति। इं १। का १। यो ९। वे ३। क ४। ज्ञा ३। म। श्रु। अ। सं १। देश। द ३। ले ६। भ १।
भा १ प
सं ३। सं १। आ १। उ ६॥

पद्मलेश्या-प्रमत्तसंयतर्गे। गु १। प्र। जो २। प। अ। प ६। ६। प्रा १०। ७। सं ४। गति १। म। इं १। का १। यो ११। म ४। वा ४। औ का १। आ का २। वे ३। क ४। ज्ञा ४। म। श्रु। अ। म। सं ३। सा। छे। प। द ३। ले ६। भ १। सं ३। उ। वे। क्षा।
भा १ प
सं १। आ १। उ ७॥

मिश्राणि, सं १ अ। द २। ले ६। भ १। स १ मिश्रं। सं १। आ १, उ ५। असंयतानां—गु १ अ, जी
भा १ प
२ प अ, प ६, ६, प्रा १०, ७, सं ४, ग ३ ति म दे, इं १, का १। यो १३ आहारकद्वयाभावात्, वे ३, क ४, ज्ञा ३ म श्रु अ, सं १ अ, द ३, ले ६, भ १, स ३ उ वे क्षा, सं १, आ २, उ ६। तत्पर्याप्तानां—गु १ अ।
भा १ प
जी १ प। प ६। प्रा १०। सं ४, ग ३ ति म दे। इं १। का १। यो १० म ४ व ४ औदा वैक्रि। वे ३। क ४। ज्ञा ३। सं १ अ। द ३। ले ६। भ १। स ३ उ वे क्षा। सं १। आ १। उ ६। तद-
भा १ प
पर्याप्तानां—गु १ अ, जी १ अ, प ६ अ, प्रा ७ अ, सं ४, ग २ म दे, इं १, का १, यो ३ औमि वैमि का, वे १ पु, क ४, ज्ञा ३ म श्रु अ, सं १ अ, द ३। ले २ क शु, भ १, स ३ उ वे क्षा, सं १,
भा १ प
आ २ उ ६। देशव्रतानां—गु १ दे। जी १ प, प ६, प्रा १०, सं ४, ग २ ति म, इं १। का १। यो ९, वे ३, क ४, ज्ञा ३ म श्रु अ, सं १ दे, द ३। ले ६। भ १, स ३, सं १, आ १, उ ६।
भा १ प
प्रमत्तानां—गु १ प्र, जी २ प अ, प ६, ६, प्रा १० ७, सं ४, ग १ म, इं १, का १। यो ११ म ४ व ४ औ १ आ २, वे ३, क ४। ज्ञा ४ म श्रु अ म। सं ३ सा छे प। द ३। ले ६। भ १। स ३ उ वे क्षा,
भा १ प

शुक्ललेश्यामिथ्यादृष्टिपर्य्याप्तकर्गे । गु १। मि। जी १। प। प ६। प्रा १०। सं ४।
ग ३। ति। म। दे। इं १। का १। यो १०। म ४। वा ४। औ का १। वै का १। वे ३।
क ४। ज्ञा ३। कु। कु। वि। सं १। अ। द २। ले ६। भ २। सं १। मि। सं १। आ १।
भा १ शु
उ ५॥

शुक्ललेश्यामिथ्यादृष्ट्यपर्य्याप्तकर्गे । गु १। मि। जी १। अ। प ६। अ। ६। प्रा ७। अ।
सं ४। ग १। दे। इं १। का १। यो २। वै मि १। का १। वे १। पुं। क ४। ज्ञा २।
कु। कु। सं १। अ। द २। ले २ क शु। भ २। सं १। मि सं १। आ २। उ ४॥
भा १ शु

शुक्ललेश्यासासादनर्गे । गु १। सासा। जी २। प। अ। प ६। ६। प्रा १०। ७।
सं ४। ग ३। ति। म। दे। इं १। का १। यो १२। म ४। वा ४। औ का १। वै २।
का १। वे ३। क ४। ज्ञा ३। कु। कु। वि। सं १। अ। द २। ले ६ भ १। सं १। सासा।
भा १ शु
सं १ : आ २। उ ५॥

शुक्ललेश्यापर्य्याप्तसासादनसम्यग्दृष्टिगळ्गे। गु १। सासा। जी १। प ६। प्रा १०। सं ४।
ग ३। ति। म। दे। इं १। का १। यो १०। म ४। वा ४। औ का १। वैक्रि का १। वे ३।
क ४। ज्ञा ३। कु। कु। वि। सं १। अ। द २। ले ६। भ १। सं १। सासा सं १।
भा १ शु
आ १। उ ५॥

शुक्ललेश्यासासादनापर्य्याप्तकर्गे । गु १। सासा। जी १। अ। प ६। अ। प्रा ७। अ।
सं ४। ग १। दे। इं १। का १। यो २। वै मि। का १। वे १। पुं। क ४। ज्ञा २। कु। कु।
सं १। अ। द २। ले २ क शु। भ १। सं १। सासा। सं १। आ २। उ ४॥
भा १ शु

आ २, उ ५। तत्पर्याप्तानां—गु १ मि, जी १ प, प ६, प्रा १०, सं ४, ग ३ ति म दे, इं १, का १,
यो १० म ४ व ४ औ १ वै १, वे ३, क ४, ज्ञा ३ कु कु वि, सं १ अ, द २, ले ६, भ २, स १, सं १,
भा १ शु
आ १, उ ५। तदपर्याप्तानां—गु १ मि, जी १ अ, प ६। प्रा ७, सं ४, ग १ दे। इं १, का १, यो २, वैमि
का, वे १ पुं, क ४, ज्ञा २ कु कु, सं १ अ, द २, ले २ क शु। भ २, स १ मि, सं १, आ २, उ ४।
भा १ शु
सासादनानां—गु १ सा, जी २ प, अ, प ६, ६, प्रा १०, ७। सं ४। ग ३ ति म दे, इं १, का १,
यो १२ म ४ व ४ औ १ वै २ का १, वे ३, क ४, ज्ञा ३ कु कु वि, सं १ अ, द २। ले ६।
भा १ शु
भ १, स १ सा, सं १, आ २, उ ५। तत्पर्याप्तानां—गु १ सा, जी १ प, प ६, प्रा १०, सं ४, ग ३
ति म दे, इं १, का १, यो १० म ४, व ४ औ वै, वे ३, क ४, ज्ञा ३ कु कु वि, सं १ अ,। द २, ले ६,
भा १ शु
भ १, स १ सा, सं १, आ १,। उ ५। तदपर्याप्तानां—गु १ सा, जी १ अ, प ६ अ, प्रा ७ अ, सं ४,
ग १ दे, इं १, का १। यो २ वैमि का। वे १ पुं, क ४, ज्ञा २ कु कु, सं १ अ द २, ले २ क शु।
भा १ शु

शुक्ललेश्याप्रमत्तसंयतर्गे। गु १। प्र। जी २। प। अ। प ६। ६। प्रा १०। ७। सं ४। म। इं १। का १। यो ११। म४। वा ४। औ का १। आ २। वे ३। क ४। ज्ञा ४। सं ३। सा। छे। प। व ३। ले ६ / भा १ शु। भ १। सं ३। सं १। आ १। उ ७॥

शुक्ललेश्याअप्रमत्तसंयतंगे। गु १। अ प्र। जी १। प। प ६। प्रा १०। सं ३। ग १। म। इं १। का १। यो ९। वे ३। क ४। ज्ञा ४। सं ३। सा। छे। प। व ३। ले ६ / भा १ शु। भ १। सं ३। सं १। आ १। उ ७॥

शुक्ललेश्या अपूर्व्वकरणप्रभृतिसयोगकेवलिगुणस्थानपर्य्यंतं ओघभंगमेयक्कुं। अलेश्यरप्प अयोगकेवलिसिद्धपरमेष्ठिगळिगे ओघभंगमक्कुं। इंतु लेश्यामार्ग्गणे समाप्तमादुदु॥

भव्यानुवाददोळु भव्यरुगळ्गे ओघभंगमक्कुं। अभव्यसिद्धरुगळ्गे। गु १। मि। जी १४। प ६। ६। ५। ५। ४। ४। प्रा १०। ७। ९। ७। ८ ६। ७। ५। ६। ४। ४। ३। सं ४। ग ४। इं ५। का ६। यो १३। वे ३। क ४। ज्ञा ३। कु। कु। वि। सं १। अ। द २। ले ६ / ६। भ १। अभव्य। सं १। मिथ्या। सं २। आ २। उ ५॥

अभव्यपर्य्याप्तकर्गे। गु १। मि। जी ७। प ६। ५। ४। प्रा १०। ९। ८। ७। ६। ४। सं ४। ग ४। इं ५। का ६। यो १०। म ४। वा ४। औ का १। वै का १। वे ३। क ४। ज्ञा ३। कु। कु। वि। सं १ अ। द २। ले ६ / भा ६। भ १। अभव्य। सं १। मि। सं २। आ १। उ ५॥

सं १ दे। द ३। ले ६ / भा १ शु। भ १। स ३। सं १। आ १। उ ६। प्रमत्तानां—गु १ प्र। जी २ प। अ। प ६ ६। प्रा १०, ७। सं ४। ग १ म। इं १। का १। यो ११ म ४ व ४ औ १। आ २। वे ३। क ४। ज्ञा ४। सं ३। सा छे प, द ३। ले ६ / भा १ शु। भ १। स ३। सं १। आ १। उ ७। अप्रमत्तानां—गु १ अ प्र। जी १। प ६। प्रा १०। सं ३। ग १ म। इं १। का १। यो ९। वे ३। क ४। ज्ञा ४। सं ३ सा छे प। द ३। ले ६ / भा १ शु। भ १। स ३। सं १। आ १। उ ७। अपूर्वकरणात्सयोगपर्यंतानां अलेश्यायोगिसिद्धानां च ओघभंगो भवति। लेश्यामार्गणा गता।

भव्यानुवादे भव्यानामोघभंगः। अभव्यानां—गु १ मि। जी १४ प ६ ६ ५ ५ ४ ४। प्रा १० ७ ९ ७, ८ ६ ७ ५ ६ ४ ४ ३, सं ४। ग ४। इं ५। का ६। यो १३। वे ३। क ४। ज्ञा ३ कु कु वि। सं १ अ। द २। ले ६ / ६। भ १ अ। स १ मि। सं २। आ २। उ ५। तत्पर्याप्तानां—गु १ मि। जी ७। प ६ ५ ४। प्रा १० ९ ८ ७ ६ ४। सं ४। ग ४। इं ५। का ६। यो १० म ४ व ४ औ वै। वे ३। क ४। ज्ञा ३ कु कु वि। सं १ अ। द २। ले ६ / ६। भ १ अ। स १ मि। सं २। आ १।

तत्रियंगम्मनुष्यिरुम्ब । गु ११ । जी २ । प ६ । ६ । प्रा १० । ७ । ४ । २ । १ । सं ४ । ग ४ । इं १ । पं । का १ त्र । यो १५ । वे ३ । क ४ । ज्ञा ५ । सं ७ । द ४ । ले ६ । भा ६ भ १ । सं १ । सं १ । आ २ । उ ९ ॥

तत्रियंगम्मनुष्यिरुपर्याप्तकरुगळ्गे । गु ११ । जी १ । प ६ । प्रा १० । ४ । १ । सं ४ । ग ४ । इं १ । का १ । यो ११ । म ४ । व ४ । औ का १ । वै का १ । आ का १ । वे ३ । क ४ । ज्ञा ५ । म । श्रु । अ । म । के । सं ७ । द ४ । ले ६ भा ६ भ १ । सं १ । सा । सं १ । आ १ । उ ९ ॥

तत्रियंगम्मनुष्यरपर्याप्तकरुगळ्गे । गु ३ । मि । सा । स यो । जी १ । अ । प ६ । अ । प्रा ७ । २ । सं ४ । ग ४ । इं १ । पं । का १ त्र । यो ४ । औ मि । वै मि । आ मि । कार्म्म । वे २ । पुं । क ४ । ज्ञा ४ । म । श्रु । अ । म । के । सं ४ । अ । सा । छे । यथा । द ४ । च । अ । अ । के । ले २ क शु । भा ६ भ १ । सं १ । सा । सं १ । आ २ । उ ८ ॥

तत्रियंगम्मनुष्यि मनुष्यिनियर्गे । गु १ । अ । जी २ । प । अ । प ६ । ६ । प्रा १० । ७ । सं ४ । ग १ । इं १ । पं । का १ त्र । यो ११ । आहारद्वयरहित । वे ३ । क ४ । ज्ञा ३ । म । श्रु । अ । सं १ । अ । द ३ । च । अ । अ । ले ६ भा ६ । भ १ । सं १ । सा । सं १ । आ २ । उ ६ ॥

तत्रियंगम्मनुष्यिनियरपर्याप्तकरुगळ्गे । गु १ । अयो । जी १ । प ६ । प्रा १० । सं ४ । ग ४ । इं १ पं । का १ त्र । यो १० । म ४ । व ४ । औ का । वै का । वे ३ । क ४ । ज्ञा ३ । म । श्रु । अ । सं १ । अ । द ३ । च । अ । अ । ले ६ भा ६ । भ १ । सं १ । सा । सा । सं १ । आ १ । उ ६ ॥

तत्रियंगम्मनुष्यिना—गु ११ । जी २ । प ६ ६ । प्रा १० ७ ४ २ १ । सं ४ । ग ४ । इं १ पं । का १ त्र । यो १५ । वे ३ । क ४ । ज्ञा ५ । सं ७ । द ४ । ले ६ भा ६ । भ १ । स १ । सा । सं १ । आ २ । उ ९ । तत्पर्याप्तना—गु ११ । जी १ । प ६ । प्रा १० ४ १ । सं ४ । ग ४ । इं १ । का १ त्र । यो ११ म ४ व ४ औ वै आ, वे ३ । क ४ । ज्ञा ५ म श्रु अ म के । सं ७ । द ४ । ले ६ भा ६ । भ १ । स १ सा । सं १ । आ १ । उ ९ । तत्पर्याप्तना—गु ३ मि सा अ । जी १ अ । प ६ । प्रा ७, २ । सं ४ । ग ४ । इं १ पं । का १ त्र । यो ४ औमि वैमि आमि का । वे २ न, पुं । क ४ । ज्ञा ४ म श्रु अ के । सं ४ अ सा छे य । द ४ च अ अ के । ले २ क शु भा ६ । भ १ । स १ सा । सं १ । आ २ । उ ८ । तत्पर्याप्तना—गु १ अ । जी २ प अ । प ६ ६ । प्रा १० ७ । सं ४ । ग ४ । इं १ पं । का १ त्र । यो ११ आहारद्वयाभावात् । वे ३ । क ४ । ज्ञा ३ म श्रु अ । सं १ अ । द ३ च अ अ । ले ६ भा ६ । भ १ । स १ सा । सं १ । आ २ । उ ६ । तत्पर्याप्तना—गु १ अ । जी १ । प ६ । प्रा १० । सं ४ । ग ४ । इं १ पं । का १ त्र । यो १० म ४ व ४ औ १ वै १ । वे ३ । क ४ । ज्ञा ३ म श्रु अ । सं १ अ । द ३ च अ अ । ले ६ भा ६ ।

वेदकसम्यग्दृष्ट्यसंयतसम्यग्दृष्टिगळ्गे । गु १ । असं । जी २ प । अ । प ६ । ६ । प्रा १० ।
७ । सं ४ । ग ४ । इं १ पं । का १ त्र । यो १३ । म ४ । वा ४ । औ २ । वै २ । का १ । वे ३ ।
क ४ । ज्ञा ३ । म । श्रु । अ । सं १ । अ । द ३ । ले ६ । भ १ । सं १ । वे । सं १ । आ २ ।
भा ६
उ ६ ॥

वेदकसम्यग्दृष्ट्यसंयतपर्य्याप्तकर्गे । गु १ । जी १ । प ६ । प्रा १० । सं ४ । ग ४ ।
इं १ । का १ । यो १० । म ४ । वा ४ । औ का १ । वै का १ । वे ३ । क ४ । ज्ञा ३ । म । श्रु ।
अ । सं १ । असंयम । द ३ । ले ६ । भ १ । सं १ । वे । सं १ । आ १ । उ ६ ॥
भा ६

वेदकसम्यग्दृष्ट्यपर्य्याप्तासंयतसम्यग्दृष्टिगळ्गे । गु १ । अ । जी १ । अ । प ६ । प्रा ७ ।
अ । सं ४ । ग ४ । इं १ । का १ । यो ३ । औ मि । वै मि । का । वे २ । पं । पुं । क ४ ।
ज्ञा ३ । म । श्रु । अ । सं १ । अ । द ३ । ले २ । भ १ । सं १ । वे । सं १ । आ २ । उ ६ ॥
भा ६

वेदकसम्यग्दृष्टिदेशव्रतिगळ्गे । गु १ । देश । जो १ । प । प ६ । प्रा १० । सं ४ । ग २ ।
ति । म । इं १ । पं । का १ त्र । यो ९ । म ४ । वा ४ । औ का १ । वे ३ । क ४ । ज्ञा ३ ।
सं १ । देश । द ३ । ले ६ । भ १ । सं १ । वे । सं १ । आ १ । उ ६ ॥
भा ३

वेदकसम्यग्दृष्टि प्रमत्तगर्गे । गु १ । प्रम । जो २ । प अ । प ६ । ६ । प्रा १० । ७ ।
सं ४ । ग १ । म । इं १ । पं । का १ त्र । यो ११ । म ४ । वा ४ । औ १ । आ २ । वे ३ ।
क ४ । ज्ञा ४ । म । श्रु । अ । म । सं ३ । सा । छे । प । द ३ । ले ६ । भ १ । सं १ । वेद ।
भा ३
सं १ । आ १ । उ ७ ॥

सं ४, ग ४, इं १ पं, का १ त्र, यो ४ औमि वैमि आमि का, वे २ न पुं, क ४, ज्ञा ३ म श्रु अ, सं १ अ
सा छे, द ३, ले २, भ १, स १ वे, सं १, आ १, उ ६ । तदसंयतानां—गु १ अ, जो २ प, अ प ६, ६ ।
६
प्रा १०, ७ सं ४, ग ४, इं १ पं, का १ त्र, यो १३ म ४ व ४ औ २ वै २ का १, वे ३, क ४, ज्ञा ३ म श्रु
अ, सं १ अ, द ३, ले ६, भ १, स १ वे, सं १, आ २, उ ६ । तत्पर्याप्तानां—गु १ अ, जो १ प, प ६,
६
प्रा १०, सं ४, ग ४, इं १, का १ त्र, यो १०, म ४ व ४ औ १ वै १, वे ३, क ४, ज्ञा ३ म श्रु अ,
सं १ अ, द ३, ले ६, भ १, स १ वे, सं १, आ १, उ ६ । तदपर्याप्तानां—गु १ अ, जो १ अ । प ६ अ,
६
प्रा ७ अ, सं ४, ग ४, इं १, का १, यो ३ औमि वैमि का, वे २ षं पुं, क ४, ज्ञा ३ म श्रु अ, सं १ अ,
द ३, ले २ क शु, भ १, स १ वे, सं १, आ २, उ ६ । देशव्रतानां—गु १ दे, जो १ प, प ६, प्रा १०,
भा ६
सं ४, ग २ ति म, इं १ पं, का १ त्र, यो ९ म ४ व ४ औ, वे ३, क ४, ज्ञा ३, सं १ दे, द ३ ले ६,
३
भ १, स १ वे, सं १, आ १, उ ६ । प्रमत्तानां—गु १ प्र, जो २ प अ, प ६ ६, प्रा १० ७, सं ४, ग १ म,
इं १ पं, का १ त्र, यो ११ म ४ व ४ औ १, आ २, वे ३, क ४, ज्ञा ४ म श्रु अ म, सं ३ सा छे प,

उपशमसम्यग्दृष्टचसंयतपर्य्याप्तकर्गों। गु १। अ। जो १। प ६। प्रा १०। सं ४। ग ४। इं १। का १। यो १०। म ४। वा ४। ओ का १। वे का १। वे ३। क ४। ज्ञा ३। सं १। अ। व ३। ले ६ / भा ६। भ १। सं १। उ। सं १। आ १। उ ६॥

उपशमसम्यग्दृष्टचसंयतापर्य्याप्तकर्गों। गु १। अ। जो १। प ६। अ। प्रा ७। सं ४। ग १। दे। इं १। का १ त्र। यो २। वै मि १। का १। वे १ पुं। क ४। ज्ञा ३। सं १। अ। व ३। ले २ क शु / भा ३। भ १। सं १। उ। सं १। आ २। उ ६॥

उपशमसम्यग्दृष्टिदेशव्रतिगळ्गे। गु १। दे। जो १। प ६। प्रा १०। सं ४। ग २। ति। म। इं १। का १। यो ९। म ४। व ४। ओ का १। वे ३। क ४। ज्ञा ३। सं १। दे। व ३। ले ६ / भा ३। भ १। सं १। उ। सं १। आ १। उ ६॥

उपशमसम्यग्दृष्टिप्रमत्तर्गो। गु १। प्रम। जो १। प ६। प्रा १०। सं ४। ग १। म। इं १। का १। यो ९। म ४। व ४। ओ का १। वे ३। क ४। ज्ञा ४। म। श्रु। अ। म। सं २। सा। छे। व ३। ले ६ / भा ३। भ १। सं १। उ। सं १। आ १। उ ७॥

उपशमसम्यग्दृष्टिअप्रमत्तसंयतर्गों। गु १। अप्र। जी १। प ६। प्रा १०। सं ३। ग १ म। इं १। का १। यो ९। म ४। वा ४। ओ का १। वे ३। क ४। ज्ञा ४। सं २। सा। छे। व ३। ले ६ / भा २। भ १। सं १। उ। सं १। आ १। उ ७॥

उपशमसम्यग्दृष्टि अपूर्व्वकरणप्रभृति उपशांतकषायछद्मस्थवीतरागपर्य्यंतं ओघभंगमक्कुं। मिथ्यादृष्टिसासादनमिश्ररुचिगळ्गे ओघभंगमेयप्पुवु। इंतु सम्यक्त्वमार्ग्गणे समाप्तमादुवु॥

तत्पर्याप्तानां–गु १ अ। जी १। प ६। प्रा १०। सं ४। ग ४। इं १। का १। यो १० म ४ व ४ औ १ वै १। वे ३। क ४। ज्ञा ३। सं १ अ। द ३। ले ६/६। भ १। स १ उ। सं १। आ १। उ ६।

तदपर्याप्तानां–गु १ अ। जी १ अ। प ६ अ। प्रा ७। सं ४। ग १ दे। इं १। का १ त्र। यो २ वैमि का। वे १ पुं। क ४। ज्ञा ३। सं १ अ। द ३। ले २ क शु / भा ३। भ १। स १ उ। सं १। आ २। उ ६।

देशव्रतानां–गु १ दे। जी १। प ६। प्रा १०। सं ४। ग २ ति म। इं १। का १। यो ९ म ४ व ४ औ १। वे ३। क ४। ज्ञा ३। सं १ दे। द ३। ले ६/३। भ १। स १ उ। सं १। आ १। उ ६।

प्रमत्तानां–गु १ प्र। जी १। प ६। प्रा १०। सं ४। ग १ म। इं १। का १। यो ९ म ४ व ४। औ १। वे ३। क ४। ज्ञा ४ म श्रु अ म। सं २ सा छे। द ३। ले ६ / भा ३। भ १। स १ उ। सं १। आ १। उ ७।

अप्रमत्तानां–गु १ अ। जी १। प ६। प्रा १०। सं ३। ग १ म। इं १। का १ त्र। यो ९ म ४ व ४ औ। वे ३। क ४। ज्ञा ४। सं २ सा छे। द ३। ले ६ / भा ३। भ १। स १ उ। सं १। आ १। उ ७।

अपूर्वकरणादुपशांतकषायपर्यंतमोघभंगः। तथा मिथ्यादृष्टिसासादनमिश्ररुचीनामपि। सम्यक्त्वमार्गणा गता।

संज्ञिमिथ्यादृष्टयपर्य्याप्तकंगें। गु १। मि। जी १। अ। प ६। प्रा ७। सं ४। ग ४। इं १। पं। का १ त्र। यो ३। औ मि १। वै मि १। का १। वे ३। क ४। ज्ञा २। कु। कु। सं १। अ। द २। च। अ। ले २ क शु। भ २। सं १। मि। सं १। आ २। उ ४॥
भा ६

संज्ञिसासादनंगे। गु १। सासा। जी २। प। अ। प ६। ६। प्रा १०। ७। सं ४। ग ४। इं १। पं। का १ त्र। यो ११। म ४। वा ४। औ २। वै २। का १। वे ३। क ४। ज्ञा ३। कु। कु। वि। सं १। अ। द २। ले ६। भ १। सं १। सासा। सं १। आ २। उ ५॥
भा ६

संज्ञिपर्य्याप्तकसासादनंगे। गु १। सासा। जी १। प। प ६। प्रा १०। सं ४। ग ४। इं १। पं। का १ त्र। यो १०। म ४। वा ४। औ का १। वै १। वे ३। क ४। ज्ञा ३। कु। कु। वि। सं १। अ। द २। ले ६ भ १। सं १। सा। सं १। आ १। उ ५॥
भा ६

संज्ञिसासादनसम्यग्दृष्टयपर्य्याप्तकंगें। गु १। सासा। जी १। अ। प ६। अ। प्रा ७। अ। सं ४। ग ३। ति। म। दे। इं १। का १। यो ३। औ मि। वै मि। का। वे ३। क ४। ज्ञा २। कु। कु। सं १। अ। द २। ले २ क शु। भ १। सं १। सासा। सं १। आ २। उ ४॥
भा ६

संज्ञिमिश्रंगे। गु १। मिश्र। जी १। प। प ६। प्रा १०। सं ४। ग ४। इं १। का १। यो १०। म ४। व ४। औ का १। वै का १। आहारकद्वयमिश्रद्वय-कार्म्मणरहित। वे ३। क ४। ज्ञा ३। मिश्र। सं १। अ। द २। ले ६। भ १। सं १। मिश्र। सं १। आ १। उ ५॥
भा ६

सं १ अ। द २। ले ६। भ २। स १ मि। सं १। आ १। उ ५। तदपर्याप्तानां—गु १ मि। जी १ अ।
६
प ६। प्रा ७। सं ४। ग ४। इं १ पं। का १ त्र। यो ३ औमि वैमि का। वे ३। क ४। ज्ञा २ कु कु।
सं १ अ। द २। ले २ क शु। भ २। स १ मि। सं १। आ २। उ ४। सासादनानां—गु १ सा। जी २।
६
प ६ ६। प्रा १० ७। सं ४। ग ४। इं १। का १ त्र। यो ११ म ४ व ४ औ २ वै २ का १। वे ३।
क ४। ज्ञा ३ कु कु वि। सं १ अ। द २। ले ६। भ १। स १ सा। सं १। आ २। उ ५।
६
तत्पर्याप्तानां—गु १ सा। जी १। प ६। प्रा १०। सं ४। ग ४। इं १ पं। का १ त्र। यो १० म ४ व ४
औ १ वै १। वे ३। क ४। ज्ञा ३ कु कु वि। सं १ अ। द २। ले ६। भ १। स १ सा। सं १।
६
आ १। उ ५। तदपर्याप्तानां—गु १ सा। जी १ अ। प ६ अ। प्रा ७ अ। सं ४। ग ३ ति म दे। इं १।
का १। यो ३ औमि वैमि का। वे ३। क ४। ज्ञा २ कु कु। सं १ अ। द २। ले २। भ १। स १ सा।
६
सं १। आ २। उ ४। मिश्राणां—गु १ मिश्रं। जी १ प। प ६। प्रा १०। सं ४। ग ४। इं १। का १।
यो १०। औदारिकमिश्र-वैक्रियिकमिश्रकार्मणाहारकद्वयाभावात्। वे ३। क ४। ज्ञा ३ मिश्राणि। सं १ अ।

असंज्ञ्यपर्य्याप्तकंगे। गु १। मि। जो ६। अ। प ५। ४। अ प्रा ७। ६। ५। ४। ३।
सं ४। ग १ ति। इं ५। का ६। यो २। औ मि। का। वे ३। क ४। ज्ञा २। सं १। अ।
द २। ले २ क शु। भ २। स १। मि। सं १। असंज्ञि। आ २। उ ४॥
भा ३ अशु

संज्ञ्यसंज्ञिव्यपदेशरहितसयोगायोगि सिद्धरुगळ्गे मूलौघभंगमक्कुं। इंतु संज्ञिमार्ग्गणे समाप्तमादुदु॥

आहारानुवाददोळु आहारिगळ्गे। गु १३। जो १४। प ६। ६। ५। ५। ४। ४। प्रा १०।
७। ९। ७। ८। ६। ७। ५। ६। ४। ४। ३। ४। २। सं ४। ग ४। इं ५। का ६। यो १४।
कार्म्मणकाययोगरहित। वे ३। क ४। ज्ञा ८। सं ७। द ४। ले ६। भ २। सं ६। सं २।
६
आ १। उ १२॥

आहारिपर्य्याप्तकर्गें। गु १३। जो ७। प ६। ५। ४। प्रा १०। ९। ८। ७। ६। ५।
४। ४। सं ४। ग ४। इं ५। का ६। यो ११। म ४। वा ४। औ का। वै का। आ का।
वे ३। क ४। ज्ञा ८। सं ७। द ४। ले ६। भ २। सं ६। सं २। आ १। उ १२॥
भा ६

आहारिअपर्य्याप्तकर्गे। गु ५। मि। सा। अ। प्र। सयो। जी ७। अ। प ६। ५। ४। अ।
प्रा ७। ७। ६। ५। ४। ३। २। सं ४। ग ४। इं ५। का ६। यो ३। औ मि। वै मि। आ मि।
वे ३। क ४। ज्ञा ६। कु। कु। म। श्रु। अ। के। सं ४। अ। सा। छे। यथा। द ४।
ले १ क। भ २। सं ५। मि। सा। उ। वे। क्षा। सं २। आ १। उ १०॥
भा ६

तत्पर्याप्तानां–गु १ मि। जो ६ संज्ञिपर्याप्तो नहि। प ५। ४। प्रा ९। ८। ७। ६। ४। सं ४। ग १ ति।
इं ५। का ६। यो २ औ। अनुभयवचनं। वे ३। क ४। ज्ञा २ कु कु। सं १ अ। द २। ले ६। भ २। स १
भा ४ अ ३ शु १
मि। सं १ अ। आ १। उ ४। तदपर्याप्तानां–गु १ मि। जी ६ अ। प ४ अ। प्रा ७। ६। ५। ४। ३।
सं ४। ग १ ति। इं ५। का ६। यो २ औमि का। वे ३। क ४। ज्ञा २। सं १ अ। द २। ले २ क शु।
भा ३ अशु
भ २। स १ मि। सं १ अ। आ २। उ ४। संज्ञासंज्ञिव्यपदेशरहितानां सयोगायोगिसिद्धानां मूलौघभंगः।
संज्ञिमार्गणा गता।

आहारानुवादे आहारिणां–गु १३, जी १४, प ६, ६, ५, ५, ४, ४, प्रा १०, ७, ९, ७, ८, ६, ७,
५, ६, ४, ४, ३, ४, २, सं ४, ग ४, इं ५, का ६, यो १४ कार्मणो नहि, वे ३, क ४, ज्ञा ८, सं ७, द ४,
ले ६, भ २, स ६, सं २, आ १, उ १२। तत्पर्याप्तानां–गु १३, जी ७, प ६, ५, ४, प्रा १०, ९, ८, ७,
६
६, ४, ४, सं ४, ग ४, इं ५, का ६, यो ११ म ४ व ४ औ वै आ, वे ३, क ४, ज्ञा ८, सं ७, द ४, ले ६,
६
भ २, स ६, सं २, आ १, उ १२। तदपर्याप्तानां–गु ५ मि सा अ प्र स, जी ७ अ, प ६, ५, ४, प्रा ७,
७, ६, ५, ४, ३, २, सं ४, ग ४, इं ५, का ६, यो ३ औमि वैमि आमि, वे ३, क ४, ज्ञा ६ कु कु म श्रु
अ के, सं ४ अ सा छे यथा, द ४, ले १ क, भ २, स ५ मि सा उ वे क्षा, सं २, आ १, उ १०।
भा ६

ले ६। भ १। सं २। उ। क्षा। सं १। आ १। उ ७॥
भा १

आहार्य्युपशांतकषायवीतरागछद्मस्थंगे। गु १। उप। जी १। प ६। प्रा १०। सं ०। ग १। म। इं १। पं। का १ त्र। यो ९। म ४। वा ४। औ का १। वे ०। क ०। ज्ञा ४। म श्रु। अ। म। सं १। यथा। द ३। च। अ। अ। ले ६। भ १। सं २। उ। क्षा। सं १।
भा १
आ १। उ ७॥

आहारिक्षीणकषायछद्मस्थवीतरागंगे। गु १। क्षीण। जी १। प ६। प्रा १०। सं ०। ग १। म। इं १। पं। का १ त्र। योग ९। वे ०। क ०। ज्ञा ४। सं १। यथा। द ३। ले ६।
भा १
भ १। सं १। क्षा। सं १। आ १। उ ७॥

आहारिसयोगकेवलिभट्टारकंगे। गु १ सयोग के। जी २। प। अ। प ६। ६। प्रा ४। २। सं ०। ग १। म। इं १। पं। का १। त्र। यो ६। म २। वा २। औ २। वे ०। क ०। ज्ञा १। के। सं १। यथा। द १ के। ले ६। भ १। सं १। क्षा। सं ०। आ १। उ २॥
भा १

: ई प्रकारदिंदं सयोगकेवलिभट्टारकंगे पर्य्याप्तापर्य्याप्तालापद्वयं वक्तव्यमप्पुदु॥

अनाहारिगळ्गे। गु ५। मि सा। अ। सयोग अयोगि। जी। ८। एकेंद्रियबादरसूक्ष्मद्वित्रिचतुःपंचेंद्रियसंज्ञ्यसंज्ञिगळेंब अपर्य्याप्तकरु अयोगिकेवलिरहितमागि। प ६। ५। ४। प्रा ७। ७। ६। ५। ४। ३। २। १। सं ४। ग ४। इं ५। का ६। यो १। कार्म्मण। वे ३। क ४। ज्ञा ६। कु। कु। म। श्रु। अ। के। सं २। असंयममुं यथाख्यातमुं। द ४। ले १ शु। भ २।
भा ६
सं ५। मि। सा। उ। वे। क्षा। सं २। आ १। अनाहार उ १०॥

सू, द ३, ले ६, भ १, स २, उ क्षा, सं १, आ १, उ ७। उपशांतकषायाणां–गु १ उ, जी १, प ६,
१
प्रा १०, सं ०, ग १ म, इं १, का १, यो ९ म ४ व ४ औ, वे ०, क ४, ज्ञा ४ म श्रु अ म, सं १ य, द ३ च अ अ, ले ६, भ १, स २ उ क्षा, सं १, आ १, उ ७। क्षीणकषायाणां—गु १ क्षी, जी १, प ६,
१
प्रा १०, सं ४, ग १ म, इं १, का १ त्र, यो ९, वे ०, क ०, ज्ञा ४, सं १ य, द ३, ले ६, भ १, स १ क्षा,
१
सं १, आ १, उ ७। सयोगिकेवलिना—गु १ सयो, जी २ प अ, प ६ ६, प्रा ४, २, सं ०, ग १ म, इं १, का १ त्र, यो ६ म २ व २ औ २, वे ०, क ०, ज्ञा १ के, सं १ य, द १ के, ले ६, भ १, स १ क्षा,
१
सं ०, आ १, उ २। एषामपर्याप्तालापोऽपि वक्तव्यः।

अनाहारिणां–गु ५ मि सा अ स अ, जी ८ सप्तापर्याप्ता एकोऽयोगिनः, प ६, ५, ४, प्रा ७ ७ ६ २
५ ४ ३ २ १, सं ४, ग ४, इं ५, का ६, यो १, वे १, क ४, ज्ञा ६ कु कु म श्रु अ के, सं २ अ य, द ४,

अयोगिकेवलिभट्टारकर्गे। गु १ अयो। जी १। प। प ६। प्रा १। आयुष्य। सं ०। ग १। इं १। कां १। यो ०। वे ०। क ०। ज्ञा १ के। सं १ यथा। द १ के। ले ६ भा ०। भ १। सं १। सा। सं १। आ १ अनाहार। उ २॥

अनंतरं सिद्धपरमेष्ठिगळ्गे। गु ०। जी ०। प ०। प्रा ०। गति १ सिद्धगति। इं ०। का ०। यो ०। वे ०। क ०। ज्ञा १। के। सं ०। द १ के। ले ०। भ ०। सं १। क्षा। सं ०। आ १। अनाहार। उ २॥

अयोगकेवलिनां—गु १ अ। जी १ प। प ६। प्रा १ आयुः १। ग १। म १। इं १ पं। का १ त्र। यो ०। वे ०। क ०। ज्ञा १ के। सं १ य। द १ के। ले ६ भा ०। भ १। सं १ क्षा। सं ०। आ १। अ। उ २। सिद्धानां—गु ०। जी ०। प ०। प्रा ०। सं ०। ग १ सिद्धगतिः। इं ०। का ०। यो ०। वे ०। क ०। ज्ञा १ के। सं ०। द १ के। ले ०। भ ०। सं १ क्षा। सं ०। आ १। अ। उ २॥ ७२८॥

[ऊपर कर्णाटक टीका और तदनुसारी संस्कृत टीकामें गुणस्थानों और मार्गणास्थानोंमें बीस प्रकरणोंका कथन सांकेतिक अक्षरोंके द्वारा किया है। उन संकेतोंको समझ लेनेसे उक्त प्रकरणोंको समझ लेना सरल है।

प्ररूपणा और उनके संकेत अक्षर इस प्रकार हैं।

गु (गुणस्थान १४) जी (जीवसमास १४) प (पर्याप्ति ६) प्रा (प्राण १०) सं (संज्ञा ४) ग (गति ४) इं (इन्द्रिय ५) का (काय ६) यो (योग १५) वे (वेद ३), क (कषाय ४) ज्ञा (ज्ञान ८) सं (संयम ७) द (दर्शन ४) ले (लेश्या ६) भ (भव्यत्व-अभव्यत्व) स (सम्यक्त्व ६) सं (संज्ञी-असंज्ञी) आ (आहारक-अनाहारक)।

इन बीस प्ररूपणाओंमेंसे जहाँ जितनी संभव होती है उनको सूचक संकेताक्षरके आगे संख्यासूचक अंक लिखकर दी गयी है। जैसे पृ. ९९० में पर्याप्त गुणस्थानवालोंके गुणस्थान १४ कहे हैं। जीवसमास ७ पर्याप्त सम्बन्धी कहे हैं। पर्याप्ति ६, ५, ४ कही हैं क्योंकि पंचेन्द्रियके छह, विकलेन्द्रियके पाँच और एकेन्द्रियके चार पर्याप्तियाँ होती हैं। प्राण १०, ९, ८, ७, ६, ४, ४, १ कहे हैं क्योंकि संज्ञीके दस प्राण होते हैं फिर एक-एक इन्द्रिय घटती जाती है। एकेन्द्रियके चार ही प्राण होते हैं। सयोगकेवलीके चार और अयोगकेवलीके एक प्राण होता है। संज्ञा चारों होती है। गति चार, इन्द्रिय एकसे लेकर पाँच तक, काय छह, योग ग्यारह (चार मन, चार वचन, तीन पूर्णकाय योग) होते हैं। वेद तीन, कषाय चार, ज्ञान आठ (पाँच और तीन मिथ्या), संयम सात (संयम मार्गणाके सात भेद हैं), दर्शन चार, लेश्या छह, भव्यत्व-अभव्यत्व, सम्यक्त्व मार्गणाके ६ भेद, संज्ञी-असंज्ञी, आहारक होते हैं। उपयोग बारह—आठ ज्ञान, चार दर्शन। अपर्याप्त गुणस्थानवालोंके गुणस्थान पाँच हैं—मिथ्यात्व, सासादन, असंयत, प्रमत्त (आहारककी अपेक्षा), सयोगकेवली (समुद्घात अवस्थाकी अपेक्षा)। जीव समास सात अपर्याप्त होते हैं। पर्याप्ति [illegible] पाँच चार हैं। प्राण अपर्याप्त अवस्थामें सात, सात, छह, पाँच, चार, तीन, दो होते हैं। एकेन्द्रि[illegible] और समुद्घात केवलीके दो होते हैं। संज्ञा चार, गति चार, इन्द्रिय पाँच, [illegible] होते [illegible] ५ भेद होते हैं—औदारिक मिश्र, वैक्रियिक मिश्र, आहारक मिश्र, [illegible] होते हैं—कुमति, कुश्रुत, मति, श्रुत, अवधि, केवल। संयम

विदियुवसमसम्मत्तं सेढीदो दिण्ण अविरदादीसु ।
सगसगलेस्सामरिदे देव अपज्जत्तगेव हवे ॥७३०॥

द्वितीयोपशमसम्यक्त्वं श्रेणितोऽवतीर्णाविरतादिषु । स्वस्वलेश्यामृते देवापर्य्याप्तके एव भवेत् ॥

असंयतादिगळोळु द्वितीयोपशमसम्यक्त्वसंभवमें बुदुपशमश्रेणियिंदमिळिदु संक्लेशवशविदमसंयमादियोळु परिपतितरादरोळं तु निश्चैसूदु । आ द्वितीयोपशमसम्यग्दृष्टिगळप्प असंयतादिगळु तंतम्म लेश्येगळोळकूडि मृतरादरादोडे देवापर्य्याप्तकासंयतसम्यग्दृष्टिगळे नियमदिदमप्परेके दोडे बद्धदेवायुष्यंगल्लदे मरणमुपशमश्रेणियोळु संभविसदु । इतरायुस्त्रयबद्धायुष्यंगे देशसंयममुं सकलसंयममुं संभविसदप्पुदरिदं ।

सिद्धाणं सिद्धगई केवलणाणं च दंसणं खयियं ।
सम्मत्तमणाहारं उवजोगाणक्कमपउत्ती ॥७३१॥

सिद्धानां सिद्धगतिः केवलज्ञानं च दर्शनं क्षायिकं, सम्यक्त्वमनाहारः उपयोगयोरक्रमप्रवृत्तिः ॥

सिद्धपरमेष्ठिगळ्गे सिद्धगतियुं केवलज्ञानमुं केवलदर्शनमुं क्षायिकसम्यक्त्वमुं अनाहारमुं ज्ञानदर्शनोपयोगद्वयक्रमप्रवृत्तियुमरियल्पडुगुं ।

मत्तं सिद्धपरमेष्ठिगळु :—

गुणजीवठाणरहिया सण्णापज्जत्तिपाणपरिहीणा ।
सेसणवमग्गणूणा सिद्धा सुद्धा सदा होंति ॥७३२॥

गुणजीवस्थानरहिताः संज्ञापर्य्याप्तिप्राणपरिहीनाः । शेषनवमार्गणोनाः सिद्धाः शुद्धाः सदा भवंति ॥

द्वितीयोपशमसम्यक्त्वं संभवति । केषु ? उपशमश्रेणितः संक्लेशवशादधः असंयतादिषु अवतीर्णेषु । ते च असंयतादयः स्वस्वलेश्यया म्रियंते तदा देवापर्याप्तासंयता एव नियमेन भवंति । कुतः ? बद्धदेवायुष्कादन्यस्य उपशमश्रेण्यां मरणाभावात् । शेषत्रिबद्धायुष्कार्णां च देशसकलसंयमयोरेवासंभवात् ॥७३०॥

सिद्धपरमेष्ठिनां सिद्धगतिः केवलज्ञानं केवलदर्शनं क्षायिकसम्यक्त्वं अनाहारः ज्ञानदर्शनोपयोगयोरक्रमप्रवृत्तिश्च भवति ॥७३१॥

संक्लेश परिणामोंके वश उपशमश्रेणिसे नीचे उतरनेपर असंयत आदि गुणस्थानोंमें द्वितीयोपशम सम्यक्त्व होता है। वे असंयत आदि जब अपनी-अपनी लेश्याके अनुसार मरण करते हैं तो नियमसे देवगतिमें अपर्याप्त असंयत ही होते हैं, क्योंकि जिसने देवायुका बन्ध किया है उसके सिवा अन्यका उपशमश्रेणिमें मरण नहीं होता। जिन्होंने देवायुके सिवाय अन्य तीन आयुमें-से किसी एकका भी बन्ध किया है उसके तो देशसंयम और सकलसंयम ही नहीं होते ॥७३०॥

सिद्ध परमेष्ठीके सिद्धगति, केवलज्ञान, केवलदर्शन, क्षायिक सम्यक्त्व, अनाहार और ज्ञानोपयोग दर्शनोपयोगकी एक साथ प्रवृत्ति, इतनी प्ररूपणाएँ होती हैं ॥७३१॥

अज्जज्जसेणगुणगणसमूहसंधारि अजियसेणगुरु ।
भुवणगुरू जस्स गुरू सो राओ गोम्मटो जयउ ॥७३४ ॥

आर्य्यार्य्यसेनगुणगणसमूह संधार्य्यजितसेनगुरुर्भुवनगुरुर्य्यस्य गुरुः स राजो य गोम्मटो जयतु ॥

इंतु भगवदर्हत्परमेश्वर चारुचरणारविंदद्वंद्ववंदनानंदितपुण्यपुंजायमानश्रीमद्रायराजगुरु-भूमंडलाचार्य्यमहावादवादीश्वररायवादिपितामह सकलविद्वज्जनचक्रवर्त्तिश्रीमदभयसूरिसिद्धांत-चक्रवर्त्ति श्रीपादपंकजरजोरंजित ललाटपट्टं श्रीमत्केशवण्णविरचितमप्प गोम्मटसारकर्णाटकवृत्ति-जीवतत्त्वप्रदीपिकेयोळु आळापाधिकारं निरूपितमादुदु ॥

गणनेगळिविद्दं गुणगणमणिभूषण धर्म्मभूषणश्रीमुनि स–। द्गणियुपरोधदि नानोणद्दें गुणि गोम्मटसारवृत्तियं केशण्णं ।

आर्यार्यसेनगुणगणसमूहसंधार्यजितसेनगुरुः भुवनगुरुर्यस्य गुरुः स राजा गोम्मटो जयतु ॥७३४॥

इत्याचार्यश्रीनेमिचन्द्रसिद्धान्तचक्रवर्तिविरचितायां गोम्मटसारापरनामपञ्चसंग्रहवृत्तौ जीवतत्त्वप्रदीपिकाख्यायां जीवकाण्डे विंशतिप्ररूपणासु ओघादेशयोर्विंशतिप्ररूपणालाप नाम द्वाविंशतितमोऽधिकारः समाप्तः ॥२२॥

आर्य आर्यसेनके गुण और गणसमूहको धारण करनेवाले अजितसेन—जो तीन जगत्के गुरु हैं—वे जिसके गुरु हैं वह गोम्मटराज चामुण्डराय जयवन्त हों ॥७३४॥

इस प्रकार आचार्य श्री नेमिचन्द्र विरचित गोम्मटसार अपर नाम पंचसंग्रहकी भगवान् अर्हन्त देव परमेश्वरके सुन्दर चरणकमलोंकी वन्दनासे प्राप्त पुण्यके पुंजस्वरूप राजगुरु मण्डलाचार्य महावादी श्री अभयनन्दी सिद्धान्तचक्रवर्तीके चरणकमलोंकी धूलिसे शोभित ललाटवाले श्री केशववर्णीके द्वारा रचित गोम्मटसार कर्णाटवृत्ति जीवतत्त्व प्रदीपिकाकी अनुसारिणी संस्कृतटीका तथा उसकी अनुसारिणी पं. टोडरमल रचित सम्यग्ज्ञानचन्द्रिका नामक भाषाटीकाकी अनुसारिणी हिन्दी भाषा टीकामें जीवकाण्डके अन्तर्गत बीस प्ररूपणाओंमें-से आलाप प्ररूपणा नामक बाईसवाँ अधिकार सम्पूर्ण हुआ ॥२२॥

गो० जीवकाण्डगाथानुक्रमणी

इति जीवकाण्डप्रकरणस्याकारादिक्रमणिकासूची ।

□

विशिष्ट शब्द-सूची

सं १। आ १। उ ५॥

सामान्यतिर्य्यंचापर्य्याप्तसासादनंगे। गु १। जी १। प ६। प्रा ७। सं ४। ग १। इं १। का १। यो २। औ मि। का। वे ३। क ४। ज्ञा २। सं १। अ। द २। ले २ क शु। भ १।
३ अशुभ
सं १। सा। सं १। आ २। उ ४॥ कु। कु। च। अ॥

सामान्यतिर्य्यंचसम्यग्मिथ्यादृष्टिगळ्गे। गु १। जी १। प ६। प्रा १०। सं ४। ग १। इं १। का १। यो ९। वे ३। क ४। ज्ञा ३। सं १। द २। ले ६ भ १। स १। सं १।
६
आ १। उ ५॥

सामान्यतिर्य्यंचासंयतंगे। गु १। जी २। प ६। ६। प्रा १०। ७। सं ४। ग १। इं १। का १। यो ११। वे ३। क ४। ज्ञा ३। म। श्रु। अ। सं १। अ। द ३। च। अ। अ। ले ६
६
भ १। सं ३। उ। वे। क्षा। सं १। आ २। उ ६॥

सामान्यतिर्यंचासंयतपर्याप्तंगे। गु १। जी १। प ६। प्रा १०। सं ४। ग १। इं १। का १। यो ९। वे ३। क ४। ज्ञा ३। सं १। द ३। ले ६ भ १। सं ३। सं १।
६
आ १। उ ६॥

सामान्यतिर्य्यंचापर्य्याप्तासंयतंगे। गु १। जी १। प ६। अ। प्रा ७। सं ४। गति १। इं १। का १। यो २। वे १। पुं। क ४। ज्ञा ३। म। श्रु। अ। सं १। अ। द ३। च। अ। अ। ले २ क। शु। भ १। सं २। क्षा। वे। सं १। आ २। उ ६॥
भा १ क

का १, यो ९, वे ३, क ४, ज्ञा ३, सं १ अ, द २, ले ६, भ १, स १, सं १, आ १, उ ५, तदपर्याप्तानां
भा ६
गु १, जी १, प ६, प्रा ७, सं ४, ग १, इं १, का १, यो २ औ मि का, वे ३, क ४, ज्ञा २, सं १ अ, द २, ले २ क शु, भ १, स १ सा, सं १, आ २, उ ४, कु कु च अ। सम्यग्मिथ्यादृशां–गु १, जी १,
भा ३ अशुभ
प ६, प्रा १०, सं ४, ग १, इं १, का १, यो ९, वे ३, क ४, ज्ञा ३, सं १, द २, ले ६ भ १, स १,
भा ६
सं १, आ १, उ ५। असंयतानां–गु १, जी २, प ६ ६, प्रा १०, ७, सं ४, ग १, इं १, का १, यो ११, वे ३, क ४, ज्ञा ३, म श्रु अ, सं १ अ, द ३ च अ अ, ले ६, भ १, स ३ उ वे क्षा, सं १, आ २, उ ६,
भा ६
तत्पर्याप्तानां—गु १, जी १, प ६, प्रा १०, सं ४, ग १, इं १, का १, यो ९, वे ३, क ४, ज्ञा ३ म श्रु अ, सं १, द ३, ले ६, भ १, स ३, सं १, आ १, उ ६, तदपर्याप्तानां–गु १, जी १, प ६ अ, प्रा ७ अ,
भा ६
सं ४, ग १, इं १, का १, यो २, वे १ पुं, क ४, ज्ञा ३ म श्रु अ, सं १ अ, द ३ च अ अ, ले २ शु क,
भा १ क

पंचेंद्रियतिर्यग्लब्ध्यपर्याप्तकेषु । गु १ । जो २ । पं १ । प ६ । ५ । प्रा ७ । सं ४ । ग १ । इं १ । का १ । यो १ । वे ३ । क ४ । ज्ञा २ । कु । कु । सं १ । अ । द २ । च । अ । ले ६ भ २ । सं १ । मि । सं २ । आ १ । उ ५ ।
६

पंचेंद्रियतिर्यग्योनिमतीपर्याप्तकेषु । गु १ । जो २ । पं १ । प ६ । सं । अ । प्र । प्रा १ । प्रा सं ७ । अपर्याप्त = अ ७ । सं ४ । ग १ । इं १ । का १ । यो २ । मिश्र । वे ३ । क ४ । ज्ञा २ । कु । कु । सं १ । अ । द २ । च । अ । ले २ । क शु । भ २ । सं १ । मि । सं २ । आ २ । उ ४ ॥
भा ३ अ

पंचेंद्रियतिर्यक्सासादनेषु । गु १ । जो २ । सं = प अ । प ६ । ६ । प्रा १० । ७ । सं ४ । ग १ । इं १ । का १ । यो ११ । वे ३ । क ४ । ज्ञा ३ । सं १ । द २ । ले ६ । भ १ । सं १ । सा । सं १ । आ २ । उ ५ ॥ कु । कु । वि । च अ ॥
६

पंचेंद्रियतिर्यक्पर्याप्तसासादनेषु । गु १ । जो १ । प ६ । प्रा १० । सं ४ । ग १ । इं १ । का १ । यो ९ । वे ३ । क ४ । ज्ञा ३ । सं १ । द २ । ले ६ भ १ । सं १ । सा । सं १ । आ १ । उ ५ ॥
६

पंचेंद्रियतिर्यक्सासादनापर्याप्तकेषु । गु १ । जो १ । प ६ । । प्रा ७ । सं ४ । ग १ । इं १ । का १ अ । यो २ । मि । का । वे ३ । क ४ । ज्ञा २ । कु । कु । सं १ । अ । द २ । च अ । ले २ क शु भ १ । सं १ । सा । सं १ । आ २ । उ ४ । कु । कु । च । अ ॥
भा ३ अशुभ

पंचेंद्रियतिर्यग्मिथ्यादृष्टिषु । गु १ । जो १ । प ६ । प्रा १० । सं ४ । ग १ । इं १ । का १ ।

मि, सं २, आ २, उ ५, तत्पर्याप्तानां—गु १, जी २ सं अ, प ६ ५, प्रा १० ९, सं ४, ग १, इं १, का १, यो ९, वे ३, क ४, ज्ञा ३ कु कु वि, सं १ अ, द २ च अ, ले ६, भ २ स १ नि, सं २, आ १, उ ५
भा ६

तदपर्याप्तानां—गु १ जी २ सं अ, प अ ६ अ ५, प्रा सं ७, अ ७, सं ४, ग १, इं १, का १, यो २ मि का, वे ३, क ४, ज्ञा २ कु कु, सं १ अ, द २ च अ, ले २ क शु भ २, स १, सं २, आ २, उ ४,
भा ३ अशुभ

सासादनानां—गु १, जी २ सं प अ, प ६ ६, प्रा १० ७, सं ४, ग १, इं १, का १, यो ११, वे ३, क ४, ज्ञा ३, सं १, द २, ले ६, भ १, स १ सा, सं १, आ २, उ ५ कु कु वि च अ, तत्पर्याप्तानां—गु १,
भा ६

जी १, प ६, प्रा १०, सं ४, ग १, इं १, का १, यो ९, वे ३, क ४, ज्ञा ३, सं १, द २, ले ६, भ १, स १ सा, सं १, आ १, उ ५, तदपर्याप्तानां—गु १, जी १ अ, प ६, प्रा ७, सं ४, ग १, इं १, का १ त्र,
भा ६

यो २ मि का, वे ३, क ४, ज्ञा २ कु कु, सं १ अ, द २ च अ, ले २ क शु, भ १, स १ सा, सं १, आ २, उ ४ कु कु च अ, मिथ्यादृशां—गु १, जी १, प ६, प्रा १०, सं ४, ग १, इं १, का १, यो ९,
भा ३ अशु

पंचेंद्रियतिर्य्यंचयोनिमतिजीवंगळ्गे गु ५ । जी ४ । संज्ञ्यसंज्ञिपर्य्याप्तापर्य्याप्त भेदर्वि । प ६ । । ६ । सं ५ । ५ । अ । सं । प्रा १० । ७ । संज्ञि ९ । ७ । असंज्ञि । सं । ४ । ग १ । इं १ । का १ । योग ११ । वे १ । स्त्री । क ४ । ज्ञा ६ । म । श्रु । अ । कु । कु । वि । सं २ । अ । दे । द ३ । च । अ । अ । ले ६/६ भ २ । सं ५ । उ । वे । मि । सा । मि । सं २ । आ २ । उ ९ । म । श्रु । अ । कु । कु । वि । च । अ । अ ॥

तिर्य्यग्योनिमतिपर्य्याप्तजीवंगळ्गे । गु ५ । जी २ । सं । अ । प ६ । ५ । प्रा १० । सं ९ । अ । सं ४ । ग १ । ति । इं १ । पं । का १ । त्र । यो ९ । वे १ । स्त्री । क ४ । ज्ञा ६ । म । श्रु । अ । कु । कु । वि । सं २ । अ । दे । द ३ । ले ६/६ भ २ । सं । ५ । उ वे । मि । सा । मि । सं २ । आ १ । उ ९ । सं ३ । मि ३ । द ३ । तिर्य्यक्पंचेंद्रिययोनिमत्यपर्य्याप्तरगे ॥ गु २ । मि । सा । जी २ । संज्ञ्यपर्य्याप्त संज्ञ्यपर्य्याप्त । प ६ । सं । अ । ५ । अ । प्रा ७ । अ ७ । अ । सं ४ । ग १ । ति । इं १ । पं । का १ । त्र ॥ यो २ । मिश्र । का । वे १ । स्त्री । क ४ । ज्ञा २ । कु । कु । सं १ । अ । द २ । च । अ ले २ क शु / भा ३ अ शु भ २ । सं २ । मि । सा । सं २ । आ २ । उ ४ । कु । कु । च । अ ॥

पंचेंद्रियतिर्य्यग्योनिमतिमिथ्यादृष्टिगे । गु १ । मि । जी ४ । संज्ञ्यसंज्ञिपर्य्याप्तापर्य्याप्त । प ६ । ६ । ५ । ५ । असंज्ञि । प्रा १० । ७ । संज्ञि ९ । ७ । असंज्ञि । सं ४ । ग १ । इं १ । पं । का १ । त्र । यो ११ । वे १ । स्त्री । क ४ । ज्ञा ३ । सं १ । अ । द २ । ले ६/६ भ २ । सं १ । मिथ्यात्व । सं २ । आ २ । उ ५ । कु । कु । वि । च । अ ॥

तिर्यग्योनिमतीनां—गु ५, जी ४ संज्ञ्यसंज्ञिपर्याप्तापर्याप्तभेदतः प ६ ६ सं, ५ ५ अ सं, प्रा १० ७ संज्ञि ९ ७ असंज्ञि, सं ४, ग १, इं १, का १, यो ११, वे १ स्त्री, क ४, ज्ञा ६ म श्रु अ कु कु वि, सं २ अ दे, द ३ च अ अ, ले ६/६, भ २, स ५ उ वे मि सा मिश्राः, सं २, आ २, उ ९ म श्रु अ कु कु वि च अ अ, तत्पर्याप्तानां—गु ५, जी २ सं अ, प ६ ५, प्रा १० सं, ९ अ, सं ४, ग १ ति, इं १ पं, का १ त्र, यो ९, वे १ स्त्री, क ४, ज्ञा ६ म श्रु अ कु कु वि, सं २ अ दे, द ३, ले ६/६, भ २, स ५ उ वे मि सा मिश्राः, सं २, आ १, उ ९ स ३ मि ३ द ३, तदपर्याप्तानां—गु २ मि सा, जी २ संज्ञ्यसंज्ञिपर्याप्तौ, प ६ सं ५ अ, प्रा ७ अ, ७ अ सं अ, सं ४, ग १ ति, इं १ पं, का १ त्र, यो २ मिश्र का, वे १ स्त्री, क ४, ज्ञा २ कु कु, सं १ अ, द २ च अ, ले २ क शु / मा ३ अ शु, भ २, स २ मि सा, सं २, आ २, उ ४ कु कु च अ, मिथ्यादृशा—गु १ मि, जी ४ संज्ञ्यसंज्ञिपर्याप्तापर्याप्ताः, प ६ ६ संज्ञि, ५ ५ असंज्ञि, प्रा १० ७ सं, ९ ७ असंज्ञि, सं ४, ग १ ति, इं १ पं, का १ त्र, यो ११, वे १ स्त्री, क ४, ज्ञा ३, सं १ अ, द २, ले ६/६, भ २, स १

पंचेंद्रियतिर्य्यंग्योनिमतिमिश्रंगे। गु १। मिश्र। जो १। पं०। प। प ६। प्रा १०। सं ४। ग १। इं १। का १। यो ९। वे १। स्त्री। क ४। ज्ञा ३। सं १। द २। ले ६ भ १। सं १।
६
मिश्र। सं १। आ १। उ ५॥

पंचेंद्रियतिर्य्यंग्योनिमत्यसंयतंग। गु १। अ। जी १। प ६। प्रा १०। सं ४। ग १। इं १।
का १। यो ९। वे १। स्त्री। क ४। ज्ञा ३। सं १। अ। द ३। ले ६ भ १। सं ३। उ।
६
वे। सं १। आ १। उ ६॥

पंचेंद्रियतिर्य्यंग्योनिमतिसंयतासंयतंगे। गु १। दे। जो १। प ६। प्रा १०। सं ४। ग १॥
इं १। का १। यो ९। वे १। स्त्री। क ४। ज्ञा ३। सं १। द ३ ले ६ भ १। सं ३। उ।
भा ३
वे। सं १। आ १। उ ६॥

तिर्य्यक्पंचेंद्रियलब्ध्यपर्य्याप्तकर्गे। गु १। मि। जो २। सं०। अ। प ६। ५। प्रा ७।
७। सं ४। ग १। इं १। का १। यो २। मिश्र। का। वे १। षं। क ४। ज्ञा २। सं १। अ।
द २ ले २ क शु भ २। सं १। मि। सं २। आ २। उ ४॥
भा ३ अशु

मनुष्यरु चतुर्व्विकल्पमप्परु। अल्लि सामान्यमनुष्यग्गें। गु १४। जी २। प ६। ६।
प्रा १०। ७। सं ४। ग १। इं १। का १। यो १३। वैक्रियिकद्वयरहितं। वे ३। क ४। ज्ञा ८।
सं ७। द ४। ले ६ भ २। सं ६। सं १। आ २। उ १२॥
६

सामान्यमनुष्यपर्य्याप्तकर्गों। गु १४। जी १। प ६। प्रा १०। सं ४। ग १। इं १।

ले २ क शु, भ १, स १, सं १, आ २, उ ४, कु कु च अ, मिश्राणां—गु १ मिश्रं, जी १ सं प, प ६,
भा ३ अशुभ
प्रा १०, सं ४, ग १, इं १, का १, यो ९, वे १ स्त्री, क ४, ज्ञा ३, सं १, द २, ले ६, भ १, स १ मिश्रं,
६
सं १, आ १ उ ५, असंयतानां—गु १ अ, जी १, प ६, प्रा १०, सं ४ ग १, इं १, का १, यो ९, वे १
स्त्री, क ४, ज्ञा ३, सं १ अ, द ३, ले ६ भ १, स २ उ वे, सं १, आ १, उ ६, संयतासंयतानां—गु १
६
दे, जी १, प ६, प्रा १०, सं ४, ग १, इं १, का १, यो ९, वे १ स्त्री, क ४, ज्ञा ३, सं १ दे, द ३,
ले ६, भ १ स २ उ वे, स १, आ १, उ ६, तिर्यक्पञ्चेन्द्रियलब्ध्यपर्याप्तानां—गु १ मि, जी २ सं, अ,
भा ३
प ६ ५, प्रा ७ ७, सं ४, ग १, इं १, का १, यो २ मिश्र का, वे १ षं, क ४, ज्ञा २ कु कु। स १ अ,
द २, ले २ क शु, भ २, स १ मि, सं २, आ २, उ ४, चतुर्विधमनुष्येषु सामान्यानां—गु १४, जी २,
भा ३ अशुभ
प ६ ६, प्रा १०, ७, सं ४, ग १, इं १, का १, यो १३ वैक्रियिकद्वयं नहि, वे ३, क ४, ज्ञा ८, सं ७,
द ४, ले ६ भ २, स ६, सं १, आ २, उ १२, तत्पर्याप्तानां—गु १४, जी १, प ६, प्रा १०, सं ४,
भा ६

सामान्यमनुष्यसासावनंगे। गु १ सा। जो २। प ६। ६। प्रा १०। ७। सं ४। ग १। म। इं १। पं का १ त्र। यो ११। वे ३। क ४। ज्ञा ३। कु। कु। वि। सं १। अ। द २ ले ६/६ भ १ सं १। सा। सं १। आ २। उ ५॥

सामान्यमनुष्यसासावनपर्य्याप्तकर्गो। गु १। जो १। प ६। प्रा १०। सं ४। ग १। म। इं पं १। का १। त्रं। यो ९। वे ३। क ४। ज्ञा ३। कु। कु। वि। सं १। अ। द २। ले ६/६ भ १। सं १। सं १। आ १। उ ५॥

सामान्यमनुष्यापर्य्याप्तसासावनंगे। गु १। सा। जो १। अ। प ६। अ। प्रा ७। अ। सं ४। ग १। इं १। का १। यो २। औ। मिश्र। का। वे ३। क ४। ज्ञा २। सं १। अ। द २। ले। क। शु। भ १। सं १। सा। सं १। आ २। उ ४॥ भा ३ अशुभ

सामान्यमनुष्यसम्यग्मिथ्यादृष्टिगे। गु १। मिश्र। जो १। प ६। प्रा १०। सं ४। गति १। म। इं १। पं। का १। त्र। यो ९। वे ३। क ४। ज्ञा ३। सं १। अ। द २। ले ६/६ भ १। सं १। मिश्र। सं १। आ १। उ ५॥

सामान्यमनुष्यासंयतंगे। गु १। अ। जो २। प ६। ६। प्रा १०। ७। सं ४। ग १। इं १। का १। यो ११। वे ३। क ४। ज्ञा ३। सं १। द ३। ले ६/६ भ १। सं ३। सं १। आ २। उ ६॥

सामान्यमनुष्यपर्य्याप्तासंयतग्गों। गु १। जो १। प ६। प्रा १०। सं ४। ग १। इं १। का १। यो ९। वे ३। क ४। ज्ञा ३। सं १। अ। द ३। ले ६/६ भ १। सं ३। उ। वे। क्षा।

सासादनानां—गु १ सा। जी २। प ६ ६। प्रा १० ७। सं ४। ग १ म। इ १ पं। का १० त्र। यो ११। वे ३। क ४ ज्ञा ३ कु कु वि। सं १ अ। द २। ले ६/भा ६। भ १, स १ सा, सं १। आ २। उ ५। तत्पर्याप्तानां गु १ सा। जी १। प ६। प्रा १०। सं ४, ग १ म, इं १ पं। का १ त्र। यो ९। वे ३। क ४। ज्ञा ३ कु कु वि। सं १ अ। द २। ले ६/भा ६, भ १। स १ सा। सं १, आ १। उ ५। तदपर्याप्तानां—गु १ सा। जी १ अ। प ६ अ। प्रा ७ अ। सं ४। ग १। इं १। का १। यो २ मि का। वे ३। क ४। ज्ञा २। सं १, द २ ले २ क शु/भा ३ अशु, भ १, स १ सा सं १; आ २. उ ४, सम्यग्मिथ्यादृशां—गु १ मि, जी १, प ६, प्रा १०, सं ४, ग १ म, इं १, का १, यो ९, वे ३, क ४, ज्ञा ३, सं १, द २। ले ६/भा ६, भ १ स १ मिश्र। सं १। आ १। उ ५। असंयतानां—गु १ असं। जी २। प ६ ६। प्रा १० ७। सं ४। ग १। इं १। का १। यो ११ वे ३, क ४, ज्ञा ३, सं १ अ - द ३, ले ६/६। भ १, स ३, सं १, आ २; उ ६, तत्पर्याप्तानां—गु १, जी १, प ६, प्रा १०, सं ४, ग १, इं १ पं, का १, यो ९, वे ३, क ४, ज्ञा ३, सं १ अ,

ग १ । म । ई १ । पं । का १ । त्र । यो १ । आ मि = ॥ वे १ । पुं । क ४ । ज्ञा ३ । म । श्रु । अ ।
सं २ । सा । छे । द ३ । च । अ । अ । ले १ क भ १ । सं २ । वे क्षा । सं १ । आ १ । उ ६ ।
भा ३ शु
म । श्रु । अ । च । अ । अ ॥

सामान्यमनुष्याप्रमत्तरगें । गु १ । जि १ । प ६ । प्रा १० । सं ३ । आहारसंज्ञेइल्लेकेंदोडे
प्रमत्तनोळे असातसातावेदोदीरणेगे व्युच्छित्तियुंटप्पुदरिवं । ग १ । इं १ । का १ । यो ९ । वे ३ ।
क ४ । ज्ञा ४ । सं ३ । द ३ । ले ६ भ १ । स ३ । सं १ । आ १ । उ ७ ॥
भा ३

मनुष्यसामान्यापूर्व्वकरणंगे । गु १ । जी १ । प ६ । प्रा १० । स ३ । ग १ । इं १ । का १ ।
यो ९ । वे ३ । क ४ । ज्ञा ४ । सं २ । सा छे । द ३ । ले ६ भ १ । सं २ । द्वितीयोपशम-
भा १ शु
क्षायिकंगळु । सं १ । आ १ । उ ७ ॥

सामान्यमनुष्यप्रथमभागानिवृत्तिगे । गु १ । जो १ प ६ । प्रा १० । सं २ । मै । प । ग १ ।
इं १ । का १ । यो ९ । वे ३ । क ४ । ज्ञा ४ । सं २ । सा । छे । द ३ । ले ६ भ १ । सं २ ।
भा १
उ । क्षा । सं १ । आ १ । उ ७ ॥

द्वितीयभागानिवृत्तिगे । गु १ । जो १ । प ६ । प्रा १० । सं १ । परिग्रह । ग १ । इं १ ।
का १ । यो ९ । वे ० । क ४ । ज्ञा ४ । सं २ । सा । छे । द ३ । ले ६ भ १ । सं २ । उ । क्षा ।
सं १ । आ १ । उ ७ ॥ भा १

सामान्यमनुष्यतृतीयभागानिवृत्तिगे । गु १ । जो १ । प ६ । प्रा १० । सं १ । परिग्रह ।

---

१ । जी १ अ । प ६ अ । प्रा ७ अ । सं ४ । ग १ म । इं १ पं । का १ त्र । यो १ आ मि । वे १ पुं । क ४ ।
ज्ञा ३ म श्रु अ । सं २ सा छे । द ३ च अ अ । ले १ क भ १ । स २ वे क्षा । सं १ । आ १ । उ ६ म श्रु
भा ३ शु
अ च अ अ । अप्रमत्तानां—गु १ । जी १ । प ६ । प्रा १० । सं ३ आहारसंज्ञा नहि सातासातानुदीरणात् ।
ग १ । इं १ । का १ । यो ९ । वे ३ । क ४ । ज्ञा ४ । सं ३ । द ३ । ले ६ । भ १ । स ३ । सं १ । आ
६
१ । उ ७ । अपूर्वकरणानां—गु १ । जी १ । प ६ । प्रा १० । सं ३ । ग १ । इं १ । का १ । यो ९ । वे
३ । क ४ । ज्ञा ४ । सं २ सा छे । द ३ । ले ६ । भ १ । स २ द्वितीयोपशमक्षायिको । सं १ । आ १ ।
भा १
उ ७ । अनिवृत्तिकरणप्रथमभागे—गु १ । जो १ । प ६ । प्रा १० । सं २ मै प । ग १ । इं १ । का १ । यो
९ । वे ३ । क ४ । ज्ञा ४ । सं २ सा छे । द ३ । ले ६ । भ १ । स २ उ क्षा । सं १ । आ १ । उ ७ ।
भा १
द्वितीयभागे—गु १ । जो १ । प ६ । प्रा १० । सं १ परिग्रहः । ग १ । इं १ । का १ । यो ९ । वे ० ।
क ४ । ज्ञा ४ । सं २ सा छे । द ३ । ले ६ । भ १ । स २ उ क्षा । सं १ । आ १ । उ ७ । तृतीयभागे—
भा १

सामान्यमनुष्यसयोगकेवलिगें। गु १। जो २। प ६। ६। प्रा ४। २। सं।०। ग १। इं १। का १। यो ७। म २। वा २। औ २। का १। वे ०। क ०। ज्ञा १। सं १। द १। ले ६ भ १। सं १।०। आ २। उ २
भा १

सामान्यमनुष्यायोगिकेवलिगळ्गे। गु १। जी १। प ६। प्रा १। आयुष्य। सं। ०। ग १। इं १। का १। यो ०। वे ०। क ०। ज्ञा १। सं १। द १। ले ६ भ १। सं १। सं। ०।
भा ०
अनाहार। उ २॥

पर्य्याप्तमनुष्यर्गे मूलोघं वक्तव्यमक्कुं। मानुषियर्गे। गु १४। जी २। प ६। ६। प्रा १०। ७। सं ४। ०। संज्ञारहितरं। ग १। इं १। का १। यो। ११। ०। अयोगिगळु। वे १। ०। वेदरहितरं। क ४। कषायरहितरं। ज्ञा ७। म। श्रु। अ। म। के। कु। कु। वि। सं ६। अ। दे। सा। छे। सू। य। द ४। च। अ। अ। के। ले ६ लेश्यारहितरं। भ २। सं ६। सं १।
६
। ०। रहितसंज्ञित्वरं। आ २। उ ११॥

मनःपर्य्ययज्ञानोपयोगरहितरं॥ पर्य्याप्तमानुषियर्गे। गु १४। जी १। प ६। प्रा १०। सं ४। ०। संज्ञारहितरं। ग १। इं १। का १। यो ९। ०। योगरहितरं। वे १। स्त्री ०॥ वेदरहितरं। क ४। ०। कषायरहितरं। ज्ञा ७। सं ६। द ४। ले ६ अलेश्यरं। भ २। सं ६।
६
सं १। ०। संज्ञित्वशून्यरं। आ २। उ ११॥

सं १ यथाख्यातः। द १। ले ६। भ १। स १ क्षा। सं १। आ १। उ ७। सयोगिजिने—गु १। जी २।
१
प ६ ६। प्रा ४ २। सं ०। ग १। इं १। का १। यो ७ म २ वा २ औ २ का १। वे ०। क ०। ज्ञा १। सं १। द १। ले ६। भ १। स १। सं ०। आ २। उ २। अयोगिजिने—गु १। जी १। प ६। प्रा
भा १
१ आयुष्यं। सं ०। ग १। इं १। का १। यो ०। वे ०। क ०। ज्ञा १। सं १। द १। ले ६। भ १।
भा ०
स १। सं ०। आ १ अनाहारः। उ २। पर्याप्तामनुष्याणां मूलौघो वक्तव्यः। मानुषीणां—गु १४। जी २। प ६ ६। प्रा १० ७। सं ४ शून्यं च। ग १। इं १। का १। यो ११ शून्यं च। वे १। क ४ शून्यं च। ज्ञा ७ म श्रु अ के कु कु वि। सं ६ अ दे सा छे सू य। द ४ च अ अ के। ले ६ शून्यं च। भ २। स ६।
६
सं १ शून्यं च। आ २। उ ११ मनःपर्ययो नहि।

तत्पर्याप्तानां—गु १४। जी १। प ६। प्रा १०। सं ४ शून्यं च। ग १। इं १। का १। यो ९ शून्यं च। वे १ स्त्री शून्यं च। क ४ शून्यं च। ज्ञा ७। सं ६। द ४। ले ६ शून्यं च। भ २। स ६। सं
६

---

१. भावस्त्रीणां।

सं १। सं १। आ २। उ ५॥

मानुषि सासादनपर्य्याप्तिकंगे। गु १। सा। जी १। प ६। प्रा १०। सं ४। ग १। इं १। का १। यो ९। वे १। स्त्री। क ४। ज्ञा ३। सं १। अ। द २। ले ६/६ भ १। सं १। सं १। आहा १। उ ५॥

मानुषिसासादनापर्य्याप्तिगे। गु १। सा। जी १। प ६। अ। प्रा ७। अ। सं ४। ग १। इं १। का १। यो २। वे १। स्त्री। क ४। ज्ञा २। सं १। अ। द २। ले २ क शु / भा ३ अशुभ। भ १। सं १। सा। सं १। आ २। उ॥

मानुषिसम्यग्मिथ्यादृष्टिगळ्गे। गु १। मिश्र। जी १। प ६। प्रा १०। सं ४। ग १। इं १। का १। यो ९। वे १। स्त्री। क ४। ज्ञा ३। सं १। अ। द २। ले ६/६। भ १। सं १। मिश्र। सं १। आ १। उ ५॥

मानुष्यसंयतसम्यग्दृष्टिगळ्गे। गु १। अ। जी १। प ६। प्रा १०। सं ४। ग १। इं १। का १। यो ९। वे १। स्त्री। क ४। ज्ञा ३। सं १। अ। द ३। ले ६/६ भ १। सं ३। सं १। आ १। उ ६॥

मानुषिदेशसंयतंगे। गु १। जी १। प ६। प्रा १०। सं ४। ग १। का १। इं १। यो ९। वे १। स्त्री। क ४। ज्ञा ३। सं १। दे। द ३। ले ६ / भा ३ शुभ भ १। सं ३। सं १। आ १। उ ६॥

मानुषिप्रमत्तसंयतग्गे। गु १। जी १। प ६। प्रा १०। सं ४। ग १। इं १। का १। यो ९। वे १। स्त्री। क ४। ज्ञा ३॥

क ४। ज्ञा ३ कु कु वि। सं १। द २। ले ६/६ भ १। स १ सा। सं १। आ २। उ ५। तत्पर्याप्त-सासादनाना—गु १ सा। जी १। प ६। प्रा १०। सं ४। ग १। इं १। का १। यो ९। वे १ स्त्री। क ४। ज्ञा ३। सं १ अ। द २। ले ६/६। भ १। स १ सा। सं १। आ १। उ ५। तदपर्याप्तानां—गु १ सा। जी १। प ६ अ। प्रा ७ अ। सं ४। ग १। इं १। का १। यो २। वे १ स्त्री। क ४। ज्ञा २। सं १ अ। द २। ले २ क शु / भा ३ अशुभ। भ १। स १ सा। सं १। आ २। उ ४। सम्यग्मिथ्यादृष्टेः—गु १ मिश्रं। जी १। प ६। प्रा १०। सं ४। ग १। इं १। का १। यो ९। वे १ स्त्री। क ४। ज्ञा ३। सं १ अ। द २। ले ६/६। भ १। स १ मिश्रं। सं १। आ १। उ ५। असंयतानां—गु १ अ। जी १। प ६। प्रा १०। सं ४। ग १। इं १। का १। यो ९। वे १ स्त्री। क ४। ज्ञा ३। सं १ अ। द ३। ले ६/६। भ १। स ३। सं १। आ १। उ ६। देशसंयतस्य—गु १। जी १। प ६। प्रा १०। सं ४। ग १। इं १। का १।

मानुषितृतीयभागानिवृत्तिगळ्गे। गु १। जो १। प ६। प्रा १०। सं १। ग १। इं १। का १। यो ९। वे ०। क ३। मा। या। लो। ज्ञा ३। सं २। सा। छे। द ३। ले ६ भ १। सं २। सं १। आ १। उ ६॥
भा १

मानुषिचतुर्थभागानिवृत्तिगळ्गे। गु १। जो १। प ६। प्रा १०। सं १। ग १। इं १। का १। यो ९। वे ०। क २। मा। लो। ज्ञा ३। सं २। द ३। ले ६। भ १। सं २। सं १। आ १। उ ६॥
भा १

मानुषिपंचमभागानिवृत्तिगे। गु १। जो १। प ६। प्रा १०। सं १। परिग्रह। ग १। इं १। का १। यो ९। वे ०। क १। बा=। लो। ज्ञा ३। सं २। सा। छे। द ३। ले ६ भ १। सं २। उ। क्षा। सं १। आ १। उ ६॥
भा।

मानुषिसूक्ष्मसांपरायगे। गु १। सू। जो १। प ६। प्रा १०। सं १। परिग्रह। ग १। इं १। का १। यो ९। वे ०। क १। सू=लो। ज्ञा ३। सं १। सू। द ३। ले ६। भ १। सं २। उ। क्षा। सं १। आ १। उ ६॥
भा १

मानुष्युपशांतकषायंगे। गु १। जो १। प ६। प्रा १०। सं। ०। ग १। इं १। का १। यो ९। वे ०। क ०। ज्ञा ३। सं १। यथा। द ३। ले ६। भ १। सं २। उ। क्षा। सं १। आ १। उ ६॥
भा १

तृतीयभागे—गु १। जो १। प ६। प्रा १०। सं १। ग १। इं १। का १। यो ९। वे ०। क ३। मा माया लो। ज्ञा ३। सं २ सा छे। द ३। ले ६। भ १। स २। सं १। आ १। उ ६। चतुर्थ
भा १
भागे—गु १। जी १। प ६। प्रा १०। सं १। परि। ग १। इं १। का १। यो ९। वे ०। क २ मा लो। ज्ञा ३। सं २ सा छे। द ३ ले ६। भ.१। स २। सं १। आ १। उ ६। पंचमभागे—गु १। जो १।
भा १
प ६। प्रा १०। सं १ प। ग १। इं १। का १। यो ९। वे ०। क १ बा लो। ज्ञा ३। सं २ साछे। द ३। ले ६। भ १। स २ उ क्षा। सं १। आ १। उ ६। सूक्ष्मसांपरायस्य—गु १ सू। जी १। प ६।
१
प्रा १०। सं १ परिग्रहः। ग १। इं १। का १। यो ९। वे ०। क १। सू लो। ज्ञा ३। सं १ सू। द ३। ले ६। भ १। स २ उ क्षा। सं १। आ १। उ ६। उपशांतकषायस्य—गु १। जी १। प ६। प्रा १०।
भा १
सं ०। ग १। इं १। का १। यो ९। वे ०। क ०। ज्ञा ३। सं १ य। द ३। ले ६। भ १। स १ क्षा।
भा १

देवसामान्यपर्य्याप्तकाणां । । गु ४ । जी १ । प ६ । प्रा १० । सं ४ । ग १ । दे १ । इं १ । का १ । त्र । यो ९ । वे २ । क ४ । ज्ञा ६ । सं १ । अ । द ३ । ले ६ भा ३ । भ २ । सं ६ । सं १ । आ १ । उ ९ ॥

देवसामान्यापर्य्याप्तकाणां । गु ३ । मि । सा । अ । जी १ । अ । प ६ । अ । प्रा ७ । अ । सं ४ । ग १ । इं १ । का १ । यो २ । मि । का । वे २ । क ४ । ज्ञा ५ । म । श्रु । अ । कु । कु । सं १ । द ३ ले २ क । शु भा ६ । भ २ । सं ५ । उ । वे । क्षा मि । सा । सं १ । आ २ । उ ८ । म । श्रु । अ । कु । कु । च । अ । अ ॥

देवसामान्यमिथ्यादृष्टिगळ्गे । गु १ । मि । जी २ । प ६ । ६ । प्रा १० । ७ । सं ४ । ग १ । इं १ । का १ । यो ११ । वे २ । क ४ । ज्ञा ३ । कु । कु । वि । सं १ । अ । द २ । च । अ । ले ६ भा ६ । भ २ । सं १ । मि । सं १ । आ २ । उ ५ । कु । कु । वि । च । अ ॥

देवसामान्यमिथ्यादृष्टिपर्य्याप्तकाणां । गु १ । मि । जी १ । प ६ । प्रा १० । सं ४ । ग १ । इं १ । का १ । यो ९ । वे २ । क ४ । ज्ञा ३ । सं १ । अ । द २ । ले ६ भा ३ भ २ । सं १ । मि । सं १ । आ १ । उ ५ ॥

देवसामान्यापर्य्याप्तमिथ्यादृष्टिगळ्गे । गु १ । जी १ । अ । प ६ । अ । प्रा ७ । अ । सं ४ । ग १ । इं १ । का १ । यो २ । मि । का । वे २ । क ४ । ज्ञा २ । सं १ । अ । द २ । ले २ । क शु भा ६ । भ २ । सं १ । मि । सं १ । आ २ । ऊ ४ ॥

च अ अ । ले ६ भा ६ । भ २ । स ६ । सं १ । आ २ । उ ९ । म श्रु अ कु कु वि च अ अ । तत्पर्याप्तानां— गु ४ । जी १ । प ६ । प्रा १० । सं ४ । ग १ दे । इं १ पं । का १ त्र । यो ९ । वे २ । क ४ । ज्ञा ६ । सं १ अ । द ३ । ले ६ भा ३ । भ २ । स ६ । सं १ । आ १ । उ ९ । तदपर्याप्तानां—गु ३ मि सा अ । जी १ अ । प ६ । प्रा ७ अ । सं ४ । ग १ । इं १ । का १ । यो २ मि का । वे २ । क ४ । ज्ञा ५ म श्रु अ कु कु । सं १ अ । द ३ । ले २ क शु भा ६ । भ २ । स ५ उ वे क्षा मि सा । सं १ । आ २ । उ ८ म श्रु अ कु कु च अ अ । मिथ्यादृशां—गु १ मि । जी २ । प ६ ६ । प्रा १० ७ । सं ४ । ग १ । इं १ । का १ । यो ११ । वे २ । क ४ । ज्ञा ३ कु कु वि । सं १ अ । द २ च अ । ले ६ भा ६ । भ २ । स १ मि । सं १ । आ २ । उ ५ कु कु वि च अ । तत्पर्याप्तानां—गु १ मि । जी १ । प ६ । प्रा १० । सं ४ । ग १ । इं १ । का १ । यो ९ । वे २ । क ४ । ज्ञा ३ । सं १ अ । द २ । ले ६ भा ३ शुभ । भ २ । स १ मि । सं १ । आ १ । उ ५ । तदपर्याप्तानां—गु १ । जी १ अ । प ६ अ । प्रा ७ अ । सं ४ । ग १ । इं १ । का १ । यो २ मि

देवसामान्यासंयतपर्याप्तकर्मो । गु १ । जो १ । प ६ । प्रा १० । सं ४ । ग १ । इं १ ।
का १ । यो ९ । वे २ । क ४ । ज्ञा ३ । सं १ । अ । द ३ । ले ६ भ १ । सं ३ । सं १ ।
भा ३
आ १ । उ ६ ॥

देवसामान्यासंयतापर्याप्तकर्मो । गु १ । जो १ । प ६ । अ । प्रा ७ । अ । सं ४ । ग १ ।
इं १ । का १ । यो २ । मि । का । वे १ । पु ० । क ४ । ज्ञा ३ । सं १ । द ३ । ले २ क शु
भा ३ शु
भ १ । सं ३ । सं १ । आ २ । उ ६ ॥

भवनत्रयदेवरर्कळो । गु ४ । जो २ । प ६ । ६ । प्रा १० । ७ । सं ४ । ग १ । इं १ ।
का १ । यो ११ । वे २ । क ४ । ज्ञा ६ । सं १ । द ३ । ले ६ भ २ । सं ५ । उ । वे । मि ।
भा ४
सा । मि । सं १ । आ २ । उ ९ । म । श्रु । अ । कु । कु । वि । च । अ । अ ॥

भवनत्रयपर्य्याप्तदेवर्कळगे । गु १ । जो १ । प ६ । प्रा १० । सं ४ । ग १ । इं १ । का १ ।
यो ९ । वे २ । क ४ । ज्ञा ६ । म । श्रु । अ । कु । कु । वि । सं १ । द ३ । ले ६ भ २ ।
भा १
सं ५ । उ । वे । मि । सा । मि । सं १ । आ १ । उ ९ ॥

भवनत्रयापर्य्याप्तदेवर्कळगे । गु २ । मि । सा । जो १ । प ६ । प्रा ७ । अ । सं ४ । ग १ ।
इं १ । का १ । यो २ । मि । का । वे । २ । क ४ । ज्ञा २ । सं १ । द २ । ले २ क शु भ २ ।
भा ३ अ शु
सं २ । मि । सा । सं १ । आ २ । उ ४ ॥

उ ६ । तत्पर्याप्तानां—गु १ । जी १ । प ६ । प्रा १० । सं ४ । ग १ । इं १ । का १ । यो ९ । वे २ ।
क ४ । ज्ञा ३ । सं १ अ । द ३ । ले ६ । भ १ । स ३ । सं १ । आ १ । उ ६ । तदपर्याप्तानां—गु १ जी १
भा ३
अ । प ६ अ । प्रा ७ अ । सं ४ । ग १ । इं १ । यो २ मि का । वे १ पुं । क ४ । ज्ञा ३ । सं १ । द ३ ।
ले २ क शु । भ १ । स ३ । सं १ । आ २ । उ ६ । भवनत्रयदेवानां—गु ४ । जी २ । प ६ ६ । प्रा १० ७ ।
भा ३ शुभ
सं ४ । ग १ । इं १ । का १ । यो ११ । वे २ । क ४ । ज्ञा ६ । सं १ । द ३ । ले ६ । भ २ । स ५ उ वे
भा ४
मि सा मि । सं १ । आ २ । उ ९ म श्रु अ कु कु वि च अ अ । तत्पर्याप्तानां—गु ४ । जी १ । प ६
प्रा १० । सं ४ । ग १ । इं १ । का १ । यो ९ । वे २ । क ४ । ज्ञा ६ म श्रु अ कु कु वि । सं १ । द
च अ अ । ले ६ भ २ । स ५ उ वे मि सा मि । सं १ आ १ । उ ९ । तदपर्याप्तानां—गु २ मि सा । जी
१
अ । प ६ अ । प्रा ७ अ । सं ४ । ग १ । इं १ । का १ यो २ मि का । वे २ । क ४ । ज्ञा २ । सं १
द २ । ले २ क शु । भ २ । स २ मि सा । सं १ । आ २ । उ ४ ।
भा ३ अशु

भवनत्रयसम्यग्मिथ्यादृष्टिगळ्गे। गु १। जो १। प ६। प्रा १०। सं ४। ग १। इं १। का १। यो ९। वे २। क ४। ज्ञा ३। सं १। द २। ले ६ भ १। सं १। मिश्र। सं १।
भा १
आ १। उ ५॥

भवनत्रयासंयतर्गे ॥ गु १। जो १। प ६। प्रा १०। सं ४। ग १। इं १। का १। यो ९। वे २। क ४। ज्ञा ३। सं १। द ३। ले ६ भ १। सं २। उ। वे। सं १। आ १। उ ६॥
भा १

सौधर्म्मैशानदेवक्र्कळ्गे। गु ४। जो २। प ६। ६। प्रा १०। ७। सं ४। ग १। इं १। का १। यो ११। वे २। क ४। ज्ञा ६। सं १। द ३ ले ३ पी। प। शु। भ २। स ६।
भा १
सं १। आ २। उ ९॥

सौधर्म्मद्वयपर्य्याप्तदेवक्र्कळ्गे। गु ४। जो १। प ६। प्रा १०। सं ४। ग १। इं १। का १। यो ९। वे २। क ४। ज्ञा ६। सं १। द ३। ले १ ते भ २। सं ६। सं १।
१
आ १। उ ९॥

सौधर्म्मद्वयापर्य्याप्तदेवक्र्कळ्गे। गु ३। मि। सा। अ। जो १। प ६। अ। प्रा ७। अ। सं ४। ग १। इं १। का १। यो २। वे २। क ४। ज्ञा ५। कु। कु। म। श्रु। अ। सं १। द ३ ले २ भ २। सं ५। उ। वे। क्षा। मि। सा। सं १। आ २। उ ८। म। श्रु। अ।
भा १
कु। कु। च। अ। अ॥

सौधर्म्मद्वयमिथ्यादृष्टिगळ्गे। गु १। जो २। प ६। ६। प्रा १०। ७। सं ४। ग १। इं १। का १। यो ११। वे २। क ४। ज्ञा ३। सं १। द २ ले ३ भ २। सं १। मि।
भा १
सं १। आ २। उ ५॥

ले २ क शु भ १, स १ सा, सं १ आ २, उ ४, सम्यग्मिथ्यादृशां–गु १, जी १, प ६, प्रा १०, सं ४, ग १,
भा ३ अशु
इं १, का १, यो ९, वे २, क ४, ज्ञा ४, सं १, द २, ले ६, भ १, स १ मिश्रं, सं १, आ १, उ ५
भा १
असंयतानां–गु १, जी १, प ६, प्रा १०, सं ४, ग १, इं १, का १, यो ९, वे २, क ४, ज्ञा ३, सं १, द ३, ले ६, भ १, स २ उ वे, सं १, आ १, उ ६, सौधर्मैशानदेवानां–गु ४, जी २, प ६, प्रा १० ७,
भा १
सं ४, ग १, इं १, का १, यो ११, वे २, क ४, ज्ञा ६, सं १ द ३, ले ३ पी क शु, भ २, स ६, सं १,
भा १ ते
आ २, उ ९, तत्पर्याप्तानां–गु ४, जी १, प ६, प्रा १०, सं ४, ग १, इं १, का १, यो ९, वे २, क ४, ज्ञा ६, सं १, द ३ ले १ ते, भ २, स ६, सं १, आ १, उ ९, तदपर्याप्तानां—गु ३ मि स अ, जी १,
भा १
प ६ अ, प्रा ७ अ, सं ४, ग १, इं १, का १, यो २, वे २, क ४, ज्ञा ५ कु कु म श्रु अ, सं १, द ३, ले २, भ २, स ५ उ वे क्षा मि सा, सं १, आ २ उ ८ म श्रु अ कु कु च अ अ, मिथ्यादृष्टीनां–गु १,
भा १

सौधर्म्मंद्वयासंयतरगें । गु १। जो २। प ६।६। प्रा १०।७। सं ४। ग १। इं १। का १। यो ११। वे २। क ४। ज्ञा ३। सं १। द ३। ले ३ ते क । शु १ भा १ ते भ १। सं ३। उ। वे। क्षा। सं १। आ २। उ ६॥

सौधर्म्मंद्वयपर्य्याप्तासंयतरगें । गु १। जो १। प ६। प्रा १०। सं ४। ग १। इं १। का १। यो ९। वे २। क ४। ज्ञा ३। सं १। द ३ ले १ भा १ भ १। सं ३। सं १। आ १। उ ६॥

सौधर्म्मंद्वयापर्य्याप्तासंयतरगें । गु १। जो १। प ६। अ। प्रा ७। अ। सं ४। ग १। इं १। का १। यो २। मि। का। वे १। पु ०। क ४। ज्ञा ३। सं १। द ३। ले २ क शु भा १ ते भ १। सं ३। सं १। आ २। उ ६॥

अपर्य्याप्तकालदोळुपशमसम्यक्त्वमेंतु संभविसुगुमें दोडे पेळल्पडुगुं । श्रेणियिंदमवतीर्णरप्प मंदपरिणामिगळ्गे असंयतादिचतुर्गुणस्थानंगळोळु द्वितीयोपशमसम्यक्त्वमुंटप्पुदरिंदं अल्लि मध्यमतेजोलेश्येयोळु कालंगेय्दु सौधर्म्मद्वयदेवर्कळोळु उत्पन्नरगें अपर्य्याप्तकालदोळुपशमसम्यक्त्वमं पडेयल्पडुगुमेके दोडे :—

तिण्हं दोण्हं दोण्हं छण्हं दोण्हं च तेरसण्हं च ।
एत्तो य चोद्दसण्हं लेस्सा भवणादिदेवाणं ॥
तेऊ तेऊ तह तेउ पम्मा पम्मा य पम्मसुक्का य ।
सुक्का य परमसुक्का लेस्सा भवणादिदेवाणं ॥

इत्यादिसूत्रसूचितक्रमदिदमल्लपर्य्याप्तकालदोळुपशमसम्यक्त्वास्तित्वमरियल्पडुगुं । असंयतसम्यग्दृष्टिगे स्त्रीवेददोळु उत्पत्तिसंभविसदे बितु आतंगे पर्य्याप्ताळापमों दे वक्तव्यमक्कुमल्लि क्षायिकसम्यक्त्वमुमिल्लेके दोडे देवगतियोळु दर्शनमोहनीयक्षपणाभावमप्पुदरिंदमिंते विशेषमरियल्पडुगुं ।

द २ ले १ ते भा १, भ १, स १ मिश्रं, सं १, आ १, उ ५, असंयतानां—गु १, जी २, प ६ ६, प्रा १०, ७, सं ४, ग १, इं १, का १, यो ११, वे २, क ४, ज्ञा ३, सं १, द ३, ले ३ ते क शु, भा १ ते भ १ स ३ उ वे क्षा, सं १, आ २, उ ६, तत्पर्याप्तानां—गु १, जी १, प ६, प्रा १०, सं ४, ग १, इं १, का १, यो ९, वे २, क ४, ज्ञा ३, सं १, द ३, ले १ भा १, भ १, स ३, सं १, आ १, उ ६, तदपर्याप्तानां—गु १, जी १, प ६ अ, प्रा ७ अ, सं ४, ग १, इं १, का १, यो २ मि का, वे १ पुं, क ४, ज्ञा ३, सं १, द ३, ले २ क शु भा १ ते भ १, स ३ सं १, आ २, उ ६, वैमानिकेषु द्वितीयोपशमसम्यक्त्वं आरोहकापूर्वकरणप्रथमभागवर्जितोपशमश्रेण्यारोहकावरोहकाणां तदवतीर्णचतुरसंयतादीनां च तत्सम्यक्त्वमृतानां तत्तल्लेश्यया तत्रोत्पत्तेरपर्याप्तकाले संभवति, असंयतस्त्रीणामेकः पर्याप्तालाप एव सम्यग्दृष्टीनां तत्रानुत्पत्तेः, पर्याप्तकर्मभूमिमनुष्याणामेव दर्शनमोहक्षपणाप्रारंभसंभवेऽपि तन्निष्ठापकानां चतुर्गतिषूत्पत्तेः, क्षायिकसम्यक्त्वमत्र संभवतीति विशेषः स्मर्तव्यः ।

इंद्रियानुवाददोळु मूलौघालापमक्कुं। सामान्यैकेंद्रियंगळगे पेळल्पडुवल्लि। गु १। मि। जी ४। बा। सू =। प। अ। प ४। ४। प्रा ४। ३। सं ४। ग १। ति। इं १। ए। का ५। त्रसरहितमागि योग ३। औदारिक तन्मिश्रकार्म्मण। वे १। षंढ। क ४। ज्ञा २। कु। कु। सं १। अ। द १। अचक्षु। ले ६। भ २। सं १। मि। सं। अ १। आ २। उ ३। कु। कु। अचक्षु।
भा ३ अशुभ

सामान्यैकेंद्रिय पर्य्याप्तकग्गें। गु १। मि। जि २। बा ० सू ०। प ४। प्रा ४। ए। का उ। आयुः। सं ४। ग १ ति। इं १। ए। का ५॥ त्रसरहितमागि। यो १। औ का वे १। षंढ। क ४। ज्ञा २। कु। कु। सं १। अ। व १। अचक्षु ले ६। भ २। सं १। मि। सं १।
भा ३ अशु
असंज्ञि। आ। उ ३। कु। कु। अचक्षुदर्शन ॥

सामान्यैकेंद्रियापर्य्याप्तकग्गें। गु १। मि। जी २। बा। अ ० सू अ। प ४। अ प्रा ३। अ सं ४। ग १। ति इं १। ए। का ५। यो २। मि। का। वे १। ष ०। क ४। ज्ञा २। कु। कु। सं १। अ। द १। अचक्षु ले २ क शु भ २। सं १। मि। सं १। असं। आ २। उ ३।
भा ३ अशु
कु। कु। अच ॥

बादरैकेंद्रियंगळगे। गु १। मि। जी २। प। अ। प ४। ४। प्रा ४। ३। सं ४। ग १। ति। इं १। ए। का ५। यो ३। औ। मि। का। वे १। षं। क ४। ज्ञा २। कु। कु। सं १। अ। द १। अ च। ले ६। भ २। सं १। मि। सं १। असंज्ञि। आ २। उ ३॥
भा ३ अशु

बादरैकेंद्रिय पर्य्याप्तकग्गें। गु १। मि। जी १। प ४। प्रा ४। सं ४। ग १। ति इं १। ए। का ५ यो १। औ काय। वे १। षं। क ४। ज्ञा २। सं १। अ। द १। अ च ले ६ भ २।
भा ३ अशु
सं १। मि। सं १। असंज्ञि। आ १। उ ३॥

इन्द्रियानुवादे मूलौघः—तत्र सामान्यैकेन्द्रियाणां—गु १ मि, जी ४ बा सू प अ, प ४ ४, प्रा ४ ३, सं ४, ग १ ति, इं १ ए, का ५ त्रसो नहि, यो ३ औदारिकतन्मिश्रकार्मणाः, वे १ षं, क ४, ज्ञा २ कु कु, सं १ अ, द १ अ, ले ६ भ २, स १ मि, सं १ असंज्ञा, आ २, उ ३ कु कु अचक्षुः। तत्पर्याप्तानां—गु १ मि,
भा ३ अशु
जी २ बा प सू प, प ४ ए, प्रा ४ ए का उ आयुः, सं ४, ग १ ति, इं १ ए, का ५, त्रसो नहि, यो १ औ, वे १ षं, क ४, ज्ञा २ कु कु, सं १ अ, द १ अच, ले ६ भ २, स १ मि, सं १ असंज्ञी, आ १, उ ३ कु कु
भा ३ अशु
अचक्षुर्दर्शनं, तदपर्याप्तानां—गु १ मि, जी २ बा अ सू अ, प ४ अ, प्रा ३ अ, सं ४, ग १ ति, इं १ ए, का ५, यो २ मि का, वे १ षं, क ४, ज्ञा २ कु कु, सं १ अ, द १ अच, ले २ क शु, भ २, स १ मि,
३ अ शु
सं १ असंज्ञी, आ २, उ ३ कु कु अच, बादराणा—गु १ मि, जी २ प अ, प ४ ४, प्रा ४ ३, स ४, ग १ ति, इ १ ए, का ५, यो ३ औ मि का, वे १ षं, क ४, ज्ञा २ कु कु, सं १ अ, द १ अच, ले ६, भ २,
३ अशु
स १ मि, सं १ असंज्ञी, आ २, उ ३, तत्पर्याप्तानां—गु १ मि, जी १ प, प ४, प्रा ४, सं ४, ग १ ति, इं १

सूक्ष्मेकेंद्रियाऽपर्य्याप्तकर्गे । गु १ । जो १ । प ४ । अ । प्रा ३ । ए । का । आ । सं ४ । ग १ । इं १ । का ५ । यो २ । मि । का । वे १ । पं ० । क ४ । ज्ञा २ । सं १ । अ । द १ । अच
ले २ क शु । भ २ । सं १ । मि । सं १ । असंज्ञि । आ २ । उ ३ ॥
भा ३

इंतु पर्य्याप्तनामकर्म्मोदय सहितरप्प सूक्ष्मेकेंद्रिय निर्वृत्यपर्य्याप्तकर्गे आलापत्रयं पेळल्पट्टुदु । सूक्ष्मेकेंद्रियलब्ध्यपर्य्याप्तनामकर्म्मोदयसहितर्गे ओंदे अपर्य्याप्तालापं वक्तव्यमक्कुमदुं सूक्ष्मकेंद्रियापर्य्याप्तालापवंतक्कु । विशेषमिल्ल ॥

द्वींद्रियंगळ्गे । गु १ । मि । जो २ । प । अ । प ५ । ५ । प्रा ६ । सं ४ । ग १ । ति । इं १ । द्वि । का १ । त्र । यो ४ । औ २ । वा १ । का १ । वे १ । पं । क ४ । ज्ञा २ । स १ । अ । द १ । अच । ले ६ । भ २ । सं १ । मि । सं १ । असंज्ञि । आ २ । उ ३ ॥
भा ३ अ शु

द्वींद्रियपर्य्याप्तकर्गे । गु १ । जो १ । प ५ । प्रा ६ । सं ४ । ग १ । इं १ । का १ । यो २ । वा १ । का १ । वे १ । पं । क ४ । ज्ञा २ । सं १ । अ । द १ । अच । ले ६ । भ २ । सं १ ।
भा ३
मि । सं १ । असंज्ञि । आ १ । उ ३ ॥

द्वींद्रियापर्य्याप्तकर्गे । गु १ । जो १ । अ । प ५ । प्रा ४ । सं ४ । ग १ । ति । इं १ । द्वी । का १ । त्र । यो २ । मि । का । वे १ । प० । क ४ । ज्ञा २ । सं १ । अ । द १ । अ । च ।
ले २ क शु भ २ । सं १ । मि । सं १ । अ । आ २ । उ ३ ॥
भा ३ अ शु

द्वींद्रियलब्ध्यपर्य्याप्तंगोंदे अपर्य्याप्तालापं माडल्पडुगे । त्रींद्रियंगळ्गे गु १ । जी २ । प ५ । ५ । प्रा ७ । ५ । सं ४ । ग १ ति । इं १ त्रि । का १ त्र यो ४ । औ २ वा १ । का । १ । वे १ । पं । क ४ । ज्ञा २ । सं १ । अ । द १ । अ । च । ले ६ भ २ । सं १ । मि । सं १ । अ ।
भा ३
आ २ । उ ३ ॥

आ १, उ ३ । तदपर्याप्तानां–गु १, जी १, प ४ अ, प्रा ३ ए का आ, सं ४, ग १, इं १, का ५, यो २ मि का, वे १ पं, क ४, ज्ञा २, सं १ अ, द १ च अशु, ले २ क शु, भ २, स १ मि, सं १ अ, आ १, उ ३ ।
भा ३ अशु
तल्लब्ध्यपर्याप्तानां तदपर्याप्तवत्, द्वीन्द्रियाणां–गु १ मि, जी २ प अ, प ५ ५, प्रा ६, ४, सं ४, ग १ ति, इं १ द्वीं, का १ त्र, यो ४, औ २, वाक् १, का १ वे १ पं, क ४, ज्ञा २, सं १ अ, द १ च अ, ले ६, भ २,
भा ३ अशु
स १ मि, सं १ असंज्ञी, आ २, उ ३ । तत्पर्याप्तानां–गु १ मि, जी १, प ५, प्रा ६, सं ४, ग १ ति, इं १ द्वीं, का १ त्र, यो २, वा १, का १, वे १ पं, क ४, ज्ञा २, सं १ अ, द १ अच, ले ६, भ २, स १ मि,
भा ३
सं १ अ, आ १, उ ३ । तदपर्याप्तानां–गु १, जी १, प ५ अ, प्रा ४ अ, सं ४, ग १, इं १, का १, यो २ मि का, वे १ पं, क ४, ज्ञा २, सं १ अ, द १ अ च, ले २ क शु, भ २, स १ मि, सं १, आ २, उ ३ ।
भा ३ अ शु
तल्लब्ध्यपर्याप्तानां तदपर्याप्तवत्, त्रीन्द्रियाणां–गु १, जी २, प ५ ५, प्रा ७ ५, सं ४, ग १ ति, इं १ त्री, का १ त्र, यो ४ औ २ वा १ का १, वे १ पं, क ४, ज्ञा २, सं १ अ, द १ अ च, ले ६, भ २,
भा ३

संप्रतिसामान्यपंचेंद्रियलब्ध्यपर्य्याप्तकग्गे । गु १ । मि । जी २ । संज्ञ्यपर्य्याप्तासंज्ञ्यपर्य्याप्त ।
प ६ । अ । सं ५ । अ । अ । प्रा ७ । सं । अ । ७ । अ । अ । सं ४ । ग २ ति । म । इं १ । पं । का
१ । त्र । यो २ । औमि १ । का १ । वे १ । प ० । क ४ । ज्ञा २ । सं १ । अ । द २ । चा । अ
ले २ क । शु भ २ । सं १ । मि । सं २ । आ २ । ऊ ४ ॥
भा ३ अशु

संज्ञिपंचेंद्रियलब्ध्यपर्य्याप्तकग्गे । गु १ । मि । जी १ । सं ० अ । प ६ । अ । प्रा ७ । अ ।
सं ४ । ग २ ति । म । इं १ । पं । का १ । त्र । यो २ । औ मि । का १ । वे १ । प ० । क ४ ।
ज्ञा २ । सं १ । अ । द २ । ले २ क शु भ २ । सं १ । मि । सं १ । संज्ञि । आ २ । ऊ ४ ॥
भा ३ अशु

असंज्ञिपंचेंद्रियलब्ध्यपर्य्याप्तकग्गे । गु १ । मि । जी १ । प ५ । अ । प्रा ७ । अ सं ४ ।
ग १ ति । इं १ । पं । का १ । त्र । यो २ । औ मि । का १ । वे १ पं । क ४ । ज्ञा २ । सं १ ।
अ । द २ । च । अ । ले २ क शु भ २ । सं १ । मि । सं १ । असंज्ञि । आ २ । उ ४ ॥
भा ३ अशु

अनिंद्रियरुगळ्गे सिद्धगतियोळ्पेळ्दंतप्पकुमेकेंदोडे सिद्धरुगळ्गे एकेंद्रियादिनामकर्म्मोदय-
भावमप्पुदरिंदमितींद्रियमार्गणे समाप्तमादुदु ॥

कायानुवाददोळु । गु १४ । जी ५७ । ९८ । ४०६ । प ६ । ६ । ५ । ५ । ४ । ४ । प्रा १० ।
७ । ९ । ७ । ८ । ६ । ७ । ५ । ६ । ४ । ४ । ३ । ४ । २ । १ । सं ४ । ग ४ । इं ५ । का ६ । यो १५ ।
वे ३ । क ४ । ज्ञा ८ । सं ७ । द ४ । ले ६ भ २ । सं ६ । सं २ । आ २ । उ १२ ॥
६

स १ मि, सं १ असंज्ञी, आ २, उ ४ । पंचेन्द्रियलब्ध्यपर्याप्तानां—गु १ मि, जी २ संज्ञ्यसंज्ञ्यपर्याप्तौ, प ६
अ, सं ५ अ अ, प्रा ७ सं अ, ७ अ अ, सं ४, ग २ ति म, इं १ पं, का १ त्र, यो २ औ मि १ का ।,
वे १ पं, क ४, ज्ञा २, सं १ अ, द २ च अ, ले २ क शु, भ २, स १ मि, सं २, आ २, उ ४ ।
भा ३ अशु

तत्संज्ञिनां—गु १ मि, जी १ प अ, प ६ प, प्रा ७ अ अ, सं ४, ग २ ति म, इं १ पं, का १ त्र, यो २
औमि का, वे १ पं, क ४, ज्ञा २, सं १ अ, द २, ले २ क शु, भ २, स १ मि, सं १ संज्ञी, आ २, उ ४ ।
भा ३ अशु

तदसंज्ञिनां–गु १ मि, जी १, प ५ अ, प्रा ७ अ, सं ४, ग १ ति, इं १ पं, का १ त्र, यो २ औमि का,
वे १ पं, क ४, ज्ञा २, सं १ अ, द २ च अ, ले २ क शु, भ २, स १ मि, सं १ अ, आ २, उ ४ ।
भा ३ अशु

अतीन्द्रियाणां सिद्धगतिवत् । इति इन्द्रियमार्गणा गता ।

कायानुवादे—गु १४, जी ५७ ९८ ४०६, प ६ ६, ५ ५, ४, ४, प्रा १०, ७, ९ ७, ८, ६, ७, ६,
६, ४, ४ ३, ४ २ १, सं ४, ग ४, इं ५, का ६, यो १५, वे ३, क ४, ज्ञा ८, सं ७, द ४, ले ६, भ २
६
६, सं २, आ २, उ १२ ।

पृथ्वीकायापर्य्याप्तकग्गों। गु १। जी २। वा ० अ। पृ ० अ। प ४। अ। प्रा ३। अ। सं ४। ग १। ति। इं १। ए। का १। पृ। यो २। ओ मि। का। वे १। पं। क ४। ज्ञा २। सं १। अ। द १। अच। ले २ क शु भ २। सं १। मि। सं १। असं। आ २। उ ३॥
भा ३ अशु

बादरपृथ्वीकायिकंगळ्गे। गु १। जी २। प। अ। प ४। ४। प्रा ४। ३। सं ४। ग १। ति। इं १। ए। का १। पृ। यो ३। ओ २। का। वे १। पं। क ४। ज्ञा २। सं १। अ। द १। अच। ले ६ भ २। सं १। मि। सं १। असं। आ २। उ ३॥
भा ३ अशु

बादरपृथ्वीकायपर्य्याप्तकग्गं। गु १। मि। जी १। प ४। प्रा ४। सं ४। ग १। ति। इं १। ए। का १। पृ। यो १। औ। वे १। पं। क ४। ज्ञा २। सं १। असं। द १। अच। ले ६ भ २। सं १। मि। सं १। अ। आ १। उ ३॥
भा ३

बादरापर्य्याप्तपृथ्वीकायंगळ्गे। गु १। मि। जी १। अ। प ४। अ। प्रा ३। अ। सं ४। ग १ ति। इं १। ए। का १ पृथ्वी। यो २। मि। का वे १। पं। क ४। ज्ञा २। कु। कु। सं १। असं। द १। अच। ले २ क शु भ २। सं १। मि। सं १। असं। आ २। उ ३॥
भा ३ अशु

बादरपृथ्वीकायलब्ध्यपर्य्याप्तकंगे अपर्य्याप्तकंगे पेळ्वंते पेळ्दुकोळ्गे। सूक्ष्मपृथ्वीकायंगे सूक्ष्मैकेंद्रियवंते पेळ्दुकोळ्गे। अल्लि विशेषमुंटवावुवें बोडे सूक्ष्मपृथ्वीकायंगे वितावापमं माळके। अप्कायिकंगळ्गे पृथ्वीकायिकंगळ्गे पेळवंते पेळ्दुकोंबुदु। विशेषमुंटवावुवें बोडे प्रर्य्याविद बादरपर्य्याप्तियोळु शुक्ललेश्येयक्कुं। तेजस्कायिकंगळ्गे लेश्येयोळभेदमंटावुवें बोडे प्रर्य्यावि सूक्ष्मंगळ्गे

ले ६। भ २। स १ मि। सं १ अ। आ १। उ ३। तदपर्याप्तानां—गु १। जी २ वा अ सू अ। प ४ अ। प ४। प्रा ४ ३। सं ४। ग १ ति। इं १ ए। का १ पृ। यो २ औमि का। वे १ पं। क ४। ज्ञा २। सं १ अ। द १ अच। ले २ क शु। भ २। स १ मि। सं १ अ। आ २। उ ३। तद्बादराणां—गु १। जी २ मि। ओ १। प ४। प्रा ४। सं ४। ग १ ति। इं १ ए। का १ पृ। यो ३ औ २ का १। वे १ पं। क ४। ज्ञा २। सं १ अ। द १ अच। ले ६ भ २। स १ मि। सं १ असं। आ २। उ ३। तत्पर्याप्तानां—गु १ मि। जी १ अ। प ४। प्रा ४। सं ४। ग १ ति। इं १ ए। का १ पृ। यो १ औ। वे १ पं। क ४। ज्ञा २। सं १ अ। द १ अच। ले ६। भ २। स १ मि। सं १ अ। आ १। उ ३। तदपर्याप्तानां—गु १ मि। जी १ अ। प ४ अ। प्रा ३ अ। सं ४। ग १ ति। इं १ ए। का १ पृ। यो २ मि का। वे १ पं। क ४। ज्ञा २ कु कु। सं १ अ। द १ अच। ले २ क शु। भ २। स १ मि। सं १ असं। आ २। उ ३।
भा ३ अनु

तल्लब्ध्यपर्याप्तानां तदपर्याप्तवत्। तत्सूक्ष्माणां सूक्ष्मैकेन्द्रियवत्। अप्कायिकानां पृथ्वीकायिकवत्। किन्तु तेषां बादरपर्याप्ते शुक्ला तेजस्कायिकेषु सूक्ष्माणां पर्याप्तापर्याप्तयोः कपोता। बादराणां पर्याप्तकाले

प्रत्येकशरीरवनस्पतिपर्य्याप्तकग्गे । गु १ । मि । जो २ । प ४ । प्रा ४ । सं ४ । ग १ ति । इं १ ए । का १ वन । यो १ औ । वे १ पं । क ४ । ज्ञा २ । सं १ अ । द १ अच । ले ६ भ २ ।
भा ३
सं १ । मि । सं १ । असं । आ २ । उ ३ ॥

प्रत्येकशरीरापर्य्याप्तवनस्पतिगे । गु १ मि । जो १ । प ४ । प्रा ३ । अ । सं ४ । ग १ ति । इं १ ए । का १ वन । यो २ । मि । का । वे १ पं । क ४ । ज्ञा २ । सं १ । अ । द १ । अच ले २ क शु भ २ । सं १ मि । सं १ अ । आ २ । उ ३ ॥
भा ३ अ शु

इंतु निर्वृत्यपर्य्याप्तकग्गे आलापत्रयं पेळल्पट्टुदु । लब्ध्यपर्य्याप्तकग्गे यो दे आलापमक्कुमदुवुं प्रत्येकबादरनिगोदप्रतिष्ठितंगळ्गे तु पेळ्दंते वक्तव्यमक्कुं ॥

साधारणवनस्पतिगळ्गे गु १ मि । जी ८ ॥ नित्यचतुर्गतिबादरसूक्ष्मपर्य्याप्तापर्य्याप्त । प ४ । ४ । प्रा ४ । ३ । सं ४ । ग १ ति । इं १ ए । का १ वन । यो ३ । औ २ । का १ । वे १ पं । क ४ । ज्ञा २ । सं १ । अ । द १ । अच ले ६ भ २ । सं १ । मि । सं १ अ । आ २ । उ ३ ॥
भा ३

साधारणवनस्पतिपर्य्याप्तकग्गे । गु १ । मि । जी ४ । नित्यचतुर्गतिबादरसूक्ष्मपर्य्याप्तकव । प ४ । प्रा ४ । सं ४ । ग १ ति । इं १ ए । का १ वन । यो १ औ । वे १ पं । क ४ । ज्ञा २ । सं १ । अ । द १ । अच । ले ६ भ २ । सं १ । मि । सं १ । अ । आ १ । उ ३ ॥
भा ३

क ४ । ज्ञा २ । सं १ अ । द १ अच । ले ६ । भ २ । स १ मि । सं १ असं । आ २ । उ ३ । तत्पर्याप्ताना-
३
गु १ मि । जी २ । प ५ ४ । प्रा ४ ४ ४ । ग १ ति । इ १ ए । का १ व । यो १ औ । वे १ पं । क ४ । ज्ञा २ । सं १ अ । द १ अच । ले ६ । भ २ । स १ मि । सं १ असं । आ १ । उ ३ । तदपर्याप्ताना—गु
३
१ । जी २ अ । प ४ अ । प्रा ३ अ । सं ४ । ग १ ति । इ १ ए । का १ व । यो २ मि का । वे १ पं । क ४ । ज्ञा २ । स १ अ । द १ अच । ले २ क शु । भ २ । स १ मि । सं १ असं । आ २ । उ ३ ।
३
तल्लब्ध्यपर्याप्तानां तन्निर्वृत्यपर्याप्तवत् ।

साधारणाना—गु १ मि । जी ८ बादरसूक्ष्मनित्येतरनिगोदाः पर्याप्तापर्याप्ताः । प ४ ४ । प्रा ४ ३ । सं ४ । ग १ ति । इ १ ए । का १ व । यो ३ औ २ का १ । वे १ पं । क ४ । ज्ञा २ । सं १ अ । द १ अच । ले ६ । भ २ । स १ मि । सं १ अ । आ २ । उ ३ । तत्पर्याप्ताना—गु १ मि । जी ४ बादरसूक्ष्म-
३
नित्यचतुर्गतिनिगोदाः पर्याप्ताः । प ४ । प्रा ४ । सं ४ । ग १ ति । इ १ ए । का १ व । यो १ औ । वे १ पं । क ४ । ज्ञा २ । सं १ अ । द १ अच । ले ६ । भ २ । स १ मि । सं १ अ । आ १ । उ ३ ।
३

मावुदेंदोडे नाल्कु जीवसमासेगळुं सूक्ष्मसाधारणवनस्पतियें वितु यक्तव्यमक्कुं। मुळिदंते निर्विशेषमक्कुं। चतुर्गति निगोदंगळग साधारणवनस्पतिये पेळ्द क्रममेयक्कुं। नित्यनिगोदंगळगमुना क्रममेयक्कुं। अल्लिगुपयोगिगाथा :—

पुढवीआविचउण्णं केवळिआहारदेवणि रयंगा।
अपदिट्ठिवा हु सव्वे पदिट्ठिवंगा हुवे सेसा॥

त्रसकायंगळ्गे। गु १४। जी १०। वि। ति। च संपं। अ पं प ६। ६। ५। ५।
२ २ २ २ २
प्रा १०। ७। ९। ७। ८। ६। ७। ५। ६। ४। ४। २। १। सं ४। ग ४। इं ४। वि। ति। च। पं। का १ त्र। यो १५। वे ३। क ४। ज्ञा ८। सं ७। द ४। ले ६ भ २। सं ६। सं २।
६
आ २। उ १२॥

त्रसपर्याप्तकग°। गु १४। जी ५ वि। ति। च। पं सं। पं अ। प ६। ५। प्रा १०। ९।
१ १ १ १ १
८। ७। ६। ४। १। सं ४। ग ४। इं ४। वि। ति। च। पं। का १ त्र। यो ११। वे ३। क ४। ज्ञा ८। सं ७। द ४ ले ६ भ २। सं ६। सं २। आ २। उ १२। त्रसाऽपर्य्याप्तकर्गं गु ५।
६
मि। सा। अ। प्र। स यो। जी ५ वि। ति। च। पं सं। अ सं प ६। अ ५। अ प्रा। ७।
१ १ १ १ १
७। ६। ५। ४। २। सं ४। ग ४। इं ४। वि। ति। च। पं। का १ त्र। यो ४। मिश्रत्रयकार्म्मणयोगंगळु। वे ३। क ४। ज्ञा ६। म। श्रु। अ। के। कु। कु। सं ४। अ। सा। छे।

साधारणवत्। अत्रोपयोगिगाथा—

पुढवीयादिचउण्हं केवलिआहारदेवणिरयंगा।
अपदिट्ठिदा हु सव्वे पदिट्ठिदंगा हवे सेसा॥१॥

त्रसकायानां—गु १४। जी १० वि ति च सं असं। पं ६ ६। ५ ५। प्रा १० ७। ९। ७। ८। ६।
२ २ २ २ २
७ ५ ६ ४। ४। २। १। सं ४। ग ४। इं ४ वि ति च पं। का १ त्र। यो १५। वे ३। क ४। ज्ञा ८। सं ७। द ४। ले ६। भ २। स ६। सं २। आ २। उ १२। तत्पर्याप्तानां—गु १४। जी ५। वि ति च
६ १ १ १
सं असं। प ६ ५। प्रा १० ९ ८ ७ ६ ४ १। सं ४ ग ४। इं ४ वि ति च पं। का १ त्र। यो ११। वे ३।
१ १
क ४। ज्ञा ८। सं ७। द ४। ले ६। भ २। स ६। सं २। आ २। उ १२। तदपर्याप्तानां—गु ५ मि
६
सा अ प्र स। जी ५ वि ति च सं असं। प ६ अ। ५ अ। प्रा ७। ७। ६। ५। ४। २। सं ४। ग ४। इं ४ वि ति च पं। का १ त्र। यो ४ मिश्राः ३ कार्मणः। वे ३। क ४। ज्ञा ६ म श्रु अ के कु कु।
१ १ १ १

अकायरुगळ्गे। गु ०। जो ०। प ०। प्रा ०। सं। ०॥ ग १। सिद्धगति। का ०। यो ०। वे ०। क ०। ज्ञा १ के ०। सं ०। द १ के ०। ले ०। भ ०। सं १। क्षा। सं। ०। आ १। अनाहार। उ २॥

त्रसलब्ध्यपर्य्याप्तकर्गें। गु १। मि। जो ५। वि। ति। च। पं। अ प ६। ५। प्रा ७।
१ १ १ १ १
७। ६। ५। ४। सं ४। ग २ ति। म। इं ४। वि। ति। च। पं का १। त्र। यो २। औ
१ १ १ १
मि। का १। वे १ पं। क ४। ज्ञा २। सं १ अ। द च। अ। ले २ क शु भ २। सं १ मि।
भा ३ अ शु
सं २। आ २। उ ४। इंतु कायमार्ग्गणे समाप्तमादुदु॥

योगानुवाददोळु मूलौघभंगमक्कुं। विशेषमावुवें दोडे त्रयोदशगुणस्थानंगळप्पुवु। मनोयोगिगळ्गे। गु १३। जी १। पं ० प १। प ६। प्रा १०। स ४। ग ४। इं १। का १। त्र। यो ४। नाल्कुं मनोयोग। वे ३। क ४। ज्ञा ८। सं ७। द ४ ले ६ भ २। सं ६। सं १।
भा ६
आ १। उ १२॥

मनोयोगिमिथ्यादृष्टिगळ्गे। गु १ मि। जो १। प ६। प्रा १०। सं ४। ग ४। इं १। का १। यो ४। नाल्कुं मनोयोगंगळुं। वे ३। क ४। ज्ञा ३। सं १। अ। द २ ले ६ भ २।
भा ६
सं १। मि। सं १। आ १। उ ५॥

मनोयोगिसासादनंगे। गु १। सा। जो १। प ६। प्रा १०। सं ४। ग ४। इं १। पं। का १ त्र। यो ४। मनोयोगंगळु। वे ३। क ४। ज्ञा ३। कु। कु। वि। सं १। अ। द २
ले ६ भ १। सं १। सासा। सं १। आ १। उ ५॥
६

आ २. उ ४। सासादनाद्ययोगांतेषु मूलौघवत्, अकायानां—गु ०, जो०, प०, प्रा०, सं० ग १ सिद्धगतिः, इं०, का०, यो०, वे०, क०, ज्ञा १ के, सं० द० ले०, भ० । स १ क्षा, सं० आ १ अनाहारः, उ २, तल्लब्ध्यपर्याप्तानां—गु १, जी ५ वि ति च सं अ प ६, ५ अ, प्रा ७, ७, ६, ५, ४, सं ४, ग २ ति म, इं ४
१ १ १ १ १
वि ति च पं। का १ त्र, यो २ औ मि १ का १, वे १ पं, क ४, ज्ञा २, सं १ अ, द २ च अ, ले २ क शु।
१ १ १ १ भा ३ अशु
भ २। स १ मि। सं २। आ २। उ ४। कायमार्गणा गता।

योगानुवादे मूलौघः किंतु गुणस्थानानि त्रयोदशैव, मनोयोगिनां—गु १३, जो १, पं प, प ६, प्रा १०, सं ४। ग ४, इं १, का १ त्र, यो ४ म, वे ३, क ४, ज्ञा ८, सं ७, द ४, ले ६ भ २, स ६, सं १ आ १,
६
उ १२। तन्मिथ्यादृशां—गु १ मि, जो १, प ६, प्रा १०, सं ४, ग ४, इं १, का १, यो ४ म, वे ३, क ४, ज्ञा ३, सं १ अ, द २ ले ६ भ २, स १ मि, सं १, आ १, उ ५। तत्सासादनस्य—गु १ सा, जो १, प ६,
६
प्रा १०। सं ४। ग ४। इं १ पं, का १ त्र। यो ४ म। वे ३। क ४। ज्ञा ३ कु कु वि। सं १ अ।

असत्यमनोयोगिगळ्गे। गु १२। जी १। प ६। प्रा १०। सं ४। ग ४। इं १। का १। यो १। असत्यमनोयोग वे ३। क ४। ज्ञा ७। कु। कु। वि। म। श्रु। अ। म। सं ७। अ। दे। सा। छे। प। सू। यथा। द ३। ले ६/भा ६ भ २। सं ६। मि। सा। मि। उ। वे। क्षा। सं १। आ १। उ १०॥

मिथ्यादृष्टिप्रभृतिक्षीणकषायपर्य्यंतमसत्यमनोयोगिगळ्गमुभयमनोयोगिगळ्गं स्वस्वयोगने वक्तव्यमक्कुं इनितै विशेषमक्कुं॥

वाग्योगिगळ्गे। गु १३। जी ५। बि। ति। च। सं। अ। प ६। ५। प्रा १०। ९। ८। ७। ६। ४। सं ४। ग ४। इं ४। का १ त्र। यो ४। वचनयोगंगळु। वे ३। क ४। ज्ञा ८। सं ७। द ४। ले ६/६। भ २। सं ६। सं २। आ १। उ १२॥

वाग्योगिमिथ्यादृष्टिगळ्गे। गु १। मि। जी ५। प ६। ५। प्रा १०। ९। ८। ७। ६। सं ४। ग ४। इं ४। का १। त्र। यो ४॥ वाग्योगंगळु। वे ३। क ४। ज्ञा ३। सं १। अ। द २। ले ६/६ भ २। सं १। मि। सं २। आ १। उ ५॥

सासादनप्रभृतिसयोगकेवलिपर्य्यंतं मनोयोगिभंगं वक्तव्यमक्कुं। विशेषमिदु नाल्कुवाग्योगंगळेंदु वक्तव्यमक्कुं। सयोगरिगेयुं एल्लेल्लि मनोयोगं पेळल्पट्टुदल्लल्लि वाग्योगं वक्तव्यमक्कुं॥

काययोगिगळ्गे। गु १३। जी १४। प ६। ६। ५। ५। ४। ४। प्रा १०। ७। ९। ७। ८। ६। ७। ५। ६। ४। ४। ३। ४। २॥ सयोगिकेवलि। सं ४। ग ४। इं ५। का ६। यो ७॥ काययोगंगळु। वे ३। क ४। ज्ञा ८। सं ७। द ४। ले ६/६। भ २। सं ६। सं २। आ २। उ १२॥

असत्यमनोयोगिनां—गु १२। जी १। प ६। प्रा १०। सं ४। ग ४। इं १। का १। यो १ असत्यमनः। वे ३। क ४। ज्ञा ७ कु कु वि म श्रु अ म। सं ७ अ दे सा छे प सू यथा। द ३। ले ६/६ भ २। स ६ मि सा मि उ वे क्षा। सं १। आ १। उ १०। तन्मिथ्यादृष्ट्यादिक्षीणकषायांतं योज्यं। उभयमनोयोगिनामप्येवं। स्वस्वयोग एव वक्तव्यः।

वाग्योगिना—गु १३। जी ५ वि ति च सं अ। प ६ ५। प्रा १०। ९। ८। ७। ६। ४। सं ४। ग ४। इं ४। का १ त्र। यो ४। वा। वे ३। क ४। ज्ञा ८। सं ७। द ४। ले ६/६। भ २। स ६। सं २। आ १। उ १२। तन्मिथ्यादृशां—गु १ मि। जी ५। प ६ ५। प्रा १०। ९। ८। ७। ६। सं ४। ग ४। का १ त्र। यो ४ वा। वे ३। क ४। ज्ञा ३। सं १ अ। द २। ले ६/६। भ २। स १ मि। सं २। आ १। उ ५। सासादनादिसयोगांतं मनोयोगिवत् किंतु योगस्थाने वाग्योगो वक्तव्यः।

काययोगिनां—गु १३। जी १४। प ६ ६ ५ ५ ४ ४। प्रा १० ७ ९ ७ ८ ६ ७ ४ ६ ४ ४ ३ ४ २। सं ४। ग ४। इं ५। का ६। यो ७ कायस्य। वे ३। क ४। ज्ञा ८। सं ७। द ४। ले ६/६। भ २। स ६।

काययोगि अपूर्व्वकरणप्रभृतिक्षीणकषायपर्य्यंतं काययोगिगळ्गे मूलौघभंगमक्कुं। विशेषमावुर्दोडे औदारिककाययोगमे वक्तव्यमक्कुं। काययोगि सयोगकेवलिगळ्गे। गु १। स के। जो २। प। अ। प ६। प ६। प्रा ४। २। सं। ०। ग १। म। इं १ पं। का १। त्र। यो ३। औ २। का १। वे ०। क ०। ज्ञा १। के। सं १। यथा। द १ के। ले ६ भं १। सं १। क्षा।
भा १.
सं। ०। आ २। उ २। के। के॥

औदारिककाययोगिगळ्गे। गु १३। जी ७। प ६। ५। ४। प्रा १०। ९। ८। ७। ६। ४। ४। सं ४। ग २। म। ति। इं ५। का ६। यो १। औ। वे ३। क ४। ज्ञा ८। सं ७। द ४। ले ६। भ २। सं ६। सं २। आ १। उ १२॥
६

औदारिककाययोगिमिथ्यादृष्टिगळ्गे। गु १। मि। जी ७। प ६। ५। ४। प्रा १०। ९। ८। ७। ६। ४। सं ४। ग २। ति। म। इं ५। का ६। यो १। औ। वे ३। क ४। ज्ञा ३। सं १। अ। द २। ले ६। भ २। सं १। मि। सं २। आ १। उ ५॥
६

औदारिककाययोगिसासादनंगे। गु १। जी १। प ६। प्रा १०। सं ४। ग २। म। ति। इं १। पं। का १ त्र। यो १। औ। वे ३। क ४। ज्ञा ३। सं १। अ द २। ले ६। भ १।
६
सं १। सासा। सं १। आ १। उ ५॥

औदारिककाययोगिसम्यग्मिथ्यादृष्टिगळ्गे। गु १ मिश्र। जी १। प ६। प्रा १०। सं ४। ग २। ति। म। इं १। पं। का १ त्र। यो १। औ। वे ३। क ४। ज्ञा ३। सं १। अ। द २। ले ६। भ १। सं १। मिश्र। सं १। आ १। उ ५॥
६

ले ६। भ १। स ३। सं १। आ १। उ ७। अपेऽपूर्वकरणात् क्षीणकषायपर्यंतं मूलौघवत् किंतु औदारिकयोग एव वक्तव्यः।
३

सयोगकेवलिनां—गु १ स, जी २ प अ, प ६ ६, प्रा ४ २ सं ०, ग १ म, इं १ पं, का १ त्र, यो ३ औ २ का १, वे ० क ०, ज्ञा १ के, सं १ यथा, द १ के, ले ६। भ १ स १ क्षा, सं ०, आ २, उ २ के के। औदारिकयोगिनां—गु १३, जी ७ प, प ६, ५, ४, प्रा १०, ९, ८, ७, ६, ४, ४, सं ४, ग २ म ति, इं ५, का ६, यो १ औ, वे ३, क ४, ज्ञा ८, सं ७, द ४, ले ६। भ २, स ६, सं २, आ १, उ १२। तन्मिथ्यादृशां—गु १ मि, जी ७, प ६ ५ ४, प्रा १०, ९, ८, ७, ६, ४, सं ४, ग २ ति म, इं ५, का ६, यो १ औ, वे ३, क ४, ज्ञा ३, सं १ अ, द २, ले ६। भ २, स १ मि, सं २, आ २, उ ५। सासादनानां—गु १, जी १, प ६, प्रा १०, सं ४, ग २ म ति, इं १ पं, का १ त्र, यो १ औ, वे ३, क ४, ज्ञा ३, सं १ अ द २, ले ६, भ १, स १ सा, सं १, आ १, उ ५, सम्यग्मिथ्यादृशां—गु १ मिश्रं,
भा १　भा ६　भा ६　६

व २। ले १। भ १। सं १। सासा। सं १। आ १। उ ४॥
भा ३

औदारिकमिश्रकाययोगि असंयत सम्यग्दृष्टिगळ्गे। गु १। असं। जो १ अ। प ६। प्रा ७। अ। सं ४। ग २। ति। म। इं १। पं। का १। त्र। यो १। औ मि। वे १। पुं। क ४। ज्ञा ३। सं १। अ। द ३। ले १ क। भ १। सं २। वे। क्षा। सं १। आ १। उ ६॥
भा ६

औदारिकमिश्रकाययोगिसयोगिकेवलिगळ्गे। गु १। जो १। अ। प ६। प्रा २। का १। आयुः १। सं। ०। ग १। म। इं १ प। का १ त्र। यो १। औ मि। वे ०। क ०। ज्ञा १। के। सं १। यथा। द १। के। ले १ क। भ १। सं १। क्षा। सं। ०। आ १। उ २॥
भा १ शु

वैक्रियिककाययोगिगळ्गे। गु ४। मि। सा। मि। अ। जो १। प। प ६। प्रा १०। सं ४। ग २। न। दे। इं १। पं। का १ त्र। यो १। वै का। वे ३। क ४। ज्ञा ६। कु। कु। वि। म। श्रु। अ। सं १। अ। द ३। ले ६ भ २। सं ६। मि। सा। मि। उ। वे। क्षा।
भा ६
सं १। आ १। उ ९॥

वैक्रियिक काययोगिमिथ्यादृष्टिगळ्गे। गु १। जी १। प ६। प्रा १०। सं ४। ग २। न दे। इं १। पं। का १ त्र। यो १। वै का। वे ३। क ४। ज्ञा ३। कु। कु। वि। सं १ अ। द २। ले ६। भ १। मि। सं १। आ १। उ ५॥
६

वैक्रियिककाययोगिसासादनर्गे। गु १। सा। जो १। प ६। प्रा १०। सं ४। ग २। न दे। इं १। पं। का १। त्र। यो १। वै का। वे ३। क ४। ज्ञा ३। कु। कु। वि। सं १। अ। द २। ले ६। भ २। सं १। सासा। सं १। आ १। उ ५॥
भा ६

[illegible] आ १। औ मि। [illegible] ले १। भ १। [illegible]
भा ३ अशुभ
[illegible]
[illegible]
भा ६
[illegible]
[illegible]
१ शु
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]

सं १। अ। द २। ले १ क। भ १। सं १। सासा। सं १। आ १। उ ४॥
भा ६

वैक्रियिकमिश्रकाययोगि असंयतसम्यग्दृष्टिगळ्गे। गु १। जी १। अ। प ६। अ। प्रा ७। अ। सं ४। ग २। न दे। इं १। पं। का १ त्र। यो १। वै मि। वे २ षं पुं। क ४। ज्ञा ३। म। श्रु। अ। सं १। अ। द ३। ले १ क। भ १। सं ३। उ। वे। क्षा। सं १। आ १। उ ६॥
भा ४

आहारककाययोगिगळ्गे। गु १। प्र। जी १। प ६। प्रा १०। सं ४। ग १। म। इं १। पं। का १ त्र। यो १। आ का। वे १ पुं। क ४। ज्ञा ३। म। श्रु। अ। सं २। सा। छे। द ३। ले शु १। भ १। सं २। वे। क्षा। सं १। आ १। उ ६॥
भा ३

आहारकमिश्रकाययोगिगळ्गे। गु १। जी १। प ६। अ। प्रा ७। अ। सं ४। ग १। म। इं १। पं। का १ त्र। यो १। आ मि। वे १। पुं। क ४। ज्ञा ३। म। श्रु। अ। सं २। सा। छे। द ३। च। अ। अ। ले १ क भ १। सं २। वे क्षा। सं १। आ १। उ ६॥
भा ३ शु

कार्म्मणकाययोगिगळ्गे। गु ४। मि। सा। अ। सयो। जी [illegible]। अ। प ६। अ ५। अ ४। अ। प्रा ७। ७। ६। ५। ४। ३। २। सं ४। इं ५। का ६। यो १। का। वे ३। क ४। ज्ञा ६। कु। कु। म। श्रु। अ। के। सं २। अ। यथा। द ४। च अ। अ। के। ले १ शु भ २। सं ५। मि। सा। उ। वे। क्षा। सं २। आ १। अनाहार। उ १०॥
भा ६

कार्म्मणकाययोगिमिथ्यादृष्टिगळ्गे। गु १। मि। जी ७। अ। प ६। ५। ४। अ। प्रा ७। ७। ६। ५। ४। ३। सं ४। ग ४। इं ५। का ६। यो १। का। वे ३। क ४। ज्ञा २। कु। कु।

द २, ले १ क। भ १, स १ सा। सं १, आ १, उ ४।
भा ६

तदसंयतानां—गु १ अ। जी १ अ। प ६ अ, प्रा ७ अ, सं ४, ग २ न दे, इं १ पं, का १ त्र, यो १ वैमि, वे २ षं पुं, क ४, ज्ञा ३ म श्रु अ, सं १ अ। द ३, ले १ क। भ १। सं ३, उ वे क्षा,
भा ४ शु ३ क १
स १, आ १, उ ६। आहारकयोगिना—गु १ प्र, जी १। प ६, प्रा १०, सं ४, ग १ म, इं १ पं, का १ त्र। यो १ आ, वे १ पु, क ४, ज्ञा ३ म श्रु अ, सं २ सा छे, द ३, ले १ शु, भ १, स २ वे क्षा, सं १, आ १, उ ६। तन्मिश्रयोगिना—गु १ प्र, जी १, प ६ अ, प्रा ७ अ, सं ४, ग १ म, इं १ पं, का १ त्र, यो १ आमि, वे १ पुं, क ४, ज्ञा ३ म श्रु अ, सं २ सा छे, द ३ च अ अ, ले १ क। भ १, स २ वे क्षा,
भा ३
सं १ आ १, उ ६। कार्मणयोगिना—गु ४ मि सा अ स, जी ७ अ, प ६ अ, ५ अ, ४ अ, प्रा ७, ७, ६, ५, ४, ३, २, सं ४, ग ४, इं ५, का ६, यो १ का, वे ३, क ४, ज्ञा ६ कु कु म श्रु अ के, स २ अ य, द ४ च अ अ के, ले १ शु। भ २, स ५ मि सा उ वे क्षा, सं २, आ १ अनाहारः, उ १०। तन्मिथ्यादृशां—
भा ६
गु १ मि, जी ७ अ, प ६ ५ ४ अ, प्रा ७ ७ ६ ५ ४ ३, सं ४, ग ४, इं ५, का ६, यो १ का, वे ३,

स्त्रीवेदिपर्य्याप्तकर्म्मो । गु ९ । जी २ । सं । । अ । प ति । म । दे । इं १ । पं । का १ त्र । यो १० । म ४ । ज्ञा ६ । कु । कु । वि । म । श्रु । अ । सं ४ । अ । दे । सा ।

भ २ । सं ६ । मि । सा । मि । उ । वे । क्षा । सं २ । आ १ !

स्त्रीवेदियपर्य्याप्तकर्म्मो । गु २ । मि । सा । जी २ । अ प्रा ७ । ७ । सं ४ । ग ३ । ति । म । दे । इं १ । पं । का १ । वे १ । स्त्री । क ४ । ज्ञा २ । कु । कु । सं १ । अ । द २

सं २ । मि । सा । सं २ । आ २ । उ ४ । कु । कु । च । अ ॥

स्त्रीवेदिमिथ्यादृष्टिगळ्गे । गु १ । मि । जी ४ । ६ । ५ । ५ । प्रा १० । ७ । ९ । ७ । सं ४ । ग ३ । ति । म । दे । आहारकद्वयरहित वे १ । स्त्री । क ४ । ज्ञा ३ । कु । कु । वि ।

भ २ । सं १ । मि । सं २ । आ २ । उ ५ ॥

स्त्रीवेदिमिथ्यादृष्टिपर्य्याप्तकर्म्मो । गु १ । जी २ । प्रा १० । ९ । सं ४ । ग ३ । ति । म । दे । इं १ । पं । का १ त्र यो । वे १ । स्त्री । क ४ । ज्ञा ३ । कु । कु । वि । सं १ । अ सं । द

सं १ । मि । सं २ । आ १ । उ ५ ॥

स्त्रीवेदिमिथ्यादृष्टिअपर्य्याप्तकर्म्मो । गु १ । मि । जी २ । ५ । अ । प्रा ७ । ७ । सं ४ । ग ३ । ति । म । इं १ । पं । का १ त्र ।

तत्पर्याप्तानां—गु ९ । जी २ सं अ । प ६ ५ । प्रा १० ९ । सं ४ । ग ३ यो १० म ४ व ४ औ १ वै १ । वे १ स्त्री । क ४ । ज्ञा ६ कु कु वि म श्रु च अ अ । ले ६ / १ । भ २ । स ६ मि सा मि उ वे क्षा । सं २ । आ १ । उ

सा । जी २ संज्ञ्यसंज्ञ्यपर्याप्तौ । प ६ ५ अ । प्रा ७ ७ । सं ४ । ग ३ ति म दे १ औमि वैमि का । वे १ स्त्री । क ४ । ज्ञा २ कु कु । सं १ अ । द २ च अ । भा

मि सा । सं २ । आ २ । उ ४ कु कु च अ । तन्मिथ्यादृशां—गु १ मि । जी ४ ६ ६ ५ ५ । प्रा १० ७ ९ ७ । सं ४ । ग ३ म ति दे । इं १ पं । का १ त्र । यो वे १ स्त्री । क ४ । ज्ञा ३ कु कु वि । सं १ अ । द २ । ले ६ / ६ । भ २ । स १ मि

तत्पर्याप्तानां—गु १ मि । जी २ संज्ञ्यसंज्ञिपर्याप्तौ । प ६ ५ । प्रा १० ९ । सं ४ । का १ त्र । यो १० म ४ व ४ औ १ वै १ । वे १ स्त्री । क ४ । ज्ञा ३ कु कु वि । ल ६ / ६ । भ २ । स १ । सं २ । आ १ । उ ५ । तदपर्याप्तानां—गु १ मि । जो २

स्त्रीवेदिपर्याप्तकर्गे । गु ९ । जी २ । मं । । अ । प ६ । ५ । प्रा १० । ९ । सं ४ । ग ३ । ति । म । दे । इं १ । पं । का १ त्र । यो १० । म ४ । व ४ । औ वै । वे १ । स्त्री । क ४ । ज्ञा ६ । कु । कु । वि । म । श्रु । अ । सं ४ । अ । दे । सा । छे । द ३ । च । अ । अ । ले ६ ।
६
भ २ । सं ६ । मि । सा । मि । उ । वे । क्षा । सं २ । आ १ । उ ९ ॥

स्त्रीवेदियपर्याप्तकर्गे । गु २ । मि । सा । जी २ । संज्ञ्यसंज्ञ्यपर्याप्तक । प ६ । ५ । अ प्रा ७ । ७ । सं ४ । ग ३ । ति । म । दे । इं १ । पं । का १ त्र । यो ३ । औमि १ । वै मि । का १ । वे १ । स्त्री । क ४ । ज्ञा २ । कु । कु । सं १ । अ । द २ च । अ । ले २ क शु । भ २ ।
भा ३ अ शु
सं २ । मि । सा । सं २ । आ २ । उ ४ । कु । कु । च । अ ॥

स्त्रीवेदिमिथ्यादृष्टिगळ्गे । गु १ । मि । जी ४ । संज्ञ्यसंज्ञिपर्याप्तकापर्याप्तक । प ६ । ६ । ५ । ५ । प्रा १० । ७ । ९ । ७ । सं ४ । ग ३ । ति । म । दे । इं १ । पं । का १ त्र । यो १३ । आहारकद्वयरहित वे १ । स्त्री । क ४ । ज्ञा ३ । कु । कु । वि । सं १ । अ सं । द २ । ले ६ ।
६
भ २ । सं १ । मि । सं २ । आ २ । उ ५ ॥

स्त्रीवेदिमिथ्यादृष्टिपर्याप्तकर्गे । गु १ । जी २ । संज्ञिपर्याप्तासंज्ञिपर्याप्तक । प ६ । ५ । प्रा १० । ९ । सं ४ । ग ३ । ति । म । दे । इं १ । पं । का १ त्र । यो १० । म ४ । व ४ । औ । वै । वे १ । स्त्री । क ४ । ज्ञा ३ । कु । कु । वि । सं १ । अ सं । द २ । च । अ । ले ६ । भ २ ।
६
सं १ । मि । सं २ । आ १ । उ ५ ॥

स्त्रीवेदिमिथ्यादृष्टिअपर्याप्तकर्गे । गु १ । मि । जी २ । संज्ञ्यपर्याप्तासंज्ञ्यपर्याप्त । प ६ । ५ । अ । प्रा ७ । ७ । सं ४ । ग ३ । ति । म । इं १ । पं । का १ त्र । यो ३ । औ । मि । वै मि ।

तत्पर्याप्तानां—गु ९ । जी २ सं अ । प ६ ५ । प्रा १० ९ । सं ४ । ग ३ ति म दे । इं १ पं । का १ त्र । यो १० म ४ व ४ औ १ वै १ । वे १ स्त्री । क ४ । ज्ञा ६ कु कु वि म श्रु अ । सं ४ अ दे सा छे । द ३ च अ अ । ले ६ । भ २ । स ६ मि सा मि उ वे क्षा । सं २ । आ १ । उ ९ । तदपर्याप्तानां—गु २ मि
६
सा । जी २ संज्ञ्यसंज्ञ्यपर्याप्तौ । प ६ ५ अ । प्रा ७ ७ । सं ४ । ग ३ ति म दे । इं १ पं । का १ त्र । यो ३ औमि वैमि का । वे १ स्त्री । क ४ । ज्ञा २ कु कु । सं १ अ । द २ च अ । ले २ क शु । भ २ । स २
भा ३ अ शु
मि सा । सं २ । आ २ । उ ४ कु कु च अ । तन्मिथ्यादृशां—गु १ मि । जी ४ संज्ञ्यसंज्ञिपर्याप्तापर्याप्ताः । प ६ ६ ५ ५ । प्रा १० ७ ९ ७ । सं ४ । ग ३ म ति दे । इं १ पं । का १ त्र । यो १३ आहारकद्वयाभावात् । वे १ स्त्री । क ४ । ज्ञा ३ कु कु वि । सं १ अ । द २ । ले ६ । भ २ । स १ मि । सं २ । आ २ । उ ५ ।
६
तत्पर्याप्तानां—गु १ मि । जी २ संज्ञ्यसंज्ञिपर्याप्तौ । प ६ ५ । प्रा १० ९ । सं ४ । ग ३ ति म दे । इं १ पं । का १ त्र । यो १० म ४ व ४ औ १ वै १ । वे १ स्त्री । क ४ । ज्ञा ३ कु कु वि । सं १ अ । द २ च अ । ले ६ । भ २ । स १ । सं २ । आ १ । उ ५ । तदपर्याप्तानां—गु १ मि । जी २ संज्ञ्यसंज्ञ्यपर्याप्तौ ।
६

स्त्रीवेदिपर्य्याप्तकर्गो । गु ९ । जी २ । सं । । अ । प ६ । ५ । प्रा १० । ९ । सं ४ । ग ३ । ति । म । दे । इं १ । पं । का १ त्र । यो १० । म ४ । व ४ । औ वै । वे १ । स्त्री । क ४ । ज्ञा ६ । कु । कु । वि । म । श्रु । अ । सं ४ । अ । दे । सा । छे । द ३ । च । अ । अ । ले ६/६ । भ २ । स ६ । मि । सा । मि । उ । वे । क्षा । सं २ । आ १ । उ ९ ॥

स्त्रीवेदियपर्य्याप्तकर्गो । गु २ । मि । सा । जो २ । संज्ञ्यसंज्ञ्यपर्य्याप्तक । प ६ । ५ । अ प्रा ७ । ७ । सं ४ । ग ३ । ति । म । दे । इं १ । पं । का १ त्र । यो ३ । औमि १ । वै मि । का १ । वे १ । स्त्री । क ४ । ज्ञा २ । कु । कु । सं १ । अ । द २ च । अ । ले २ क शु / भा ३ अ शु । भ २ । सं २ । मि । सा । सं २ । आ २ । उ ४ । कु । कु । च । अ ॥

स्त्रीवेदिमिथ्यादृष्टिगर्गो । गु १ । मि । जी ४ । संज्ञ्यसंज्ञियपर्य्याप्तकापर्य्याप्तक । प ६ । ६ । ५ । ५ । प्रा १० । ७ । ९ । ७ । सं ४ । ग ३ । ति । म । दे । इं १ । पं । का १ त्र । यो १३ । आहारकद्वयरहित वे १ । स्त्री । क ४ । ज्ञा ३ । कु । कु । वि । सं १ । अ सं । द २ । ले ६/६ । भ २ । स १ । मि । सं २ । आ २ । उ ५ ॥

स्त्रीवेदिमिथ्यादृष्टिपर्य्याप्तकर्गो । गु १ । जो २ । संज्ञिपर्य्याप्तासंज्ञिपर्य्याप्तक । प ६ । ५ । प्रा १० । ९ । सं ४ । ग ३ । ति । म । दे । इं १ । पं । का १ त्र । यो १० । म ४ । व ४ । औ । वै । वे १ । स्त्री । क ४ । ज्ञा ३ । कु । कु । वि । सं १ । अ सं । द २ । च । अ । ले ६/६ । भ २ । सं १ । मि । सं २ । आ १ । उ ५ ॥

स्त्रीवेदिमिथ्यादृष्टिअपर्य्याप्तकर्गो । गु १ । मि । जो २ । संज्ञ्यपर्य्याप्तासंज्ञ्यपर्य्याप्त । प ६ । ५ । अ । प्रा ७ । ७ । सं ४ । ग ३ । ति । म । इं १ । पं । का १ त्र । यो ३ । औ । मि । वै मि ।

स्त्रीवेदीनाना—गु ९ । जो २ सं अ । प ६ ५ । प्रा १० ९ । सं ४ । ग ३ ति म दे । इं १ पं । का १ त्र । यो १० म ४ व ४ औ १ वै १ । वे १ स्त्री । क ४ । ज्ञा ६ कु कु वि म श्रु अ । सं ४ अ दे सा छे । द ३ च अ अ । ले ६/६ । भ २ । स ६ मि सा मि उ वे क्षा । सं २ । आ १ । उ ९ । तदपर्याप्तानां—गु २ मि सा । जो २ संज्ञ्यसंज्ञ्यपर्याप्तौ । प ६ ५ अ । प्रा ७ ७ । सं ४ । ग ३ ति म दे । इं १ पं । का १ त्र । यो ३ औमि वैमि का । वे १ स्त्री । क ४ । ज्ञा २ कु कु । सं १ अ । द २ च अ । ले २ क शु / भा ३ अशु । भ २ । स २ मि सा । सं २ । आ २ । उ ४ कु कु च अ । तन्मिथ्यादृशां—गु १ मि । जो ४ संज्ञ्यसंज्ञिपर्याप्तापर्याप्ताः । प ६ ६ ५ ५ । प्रा १० ७ ९ ७ । सं ४ । ग ३ ति म दे । इं १ पं । का १ त्र । यो १३ आहारकद्वयाभावात् । वे १ स्त्री । क ४ । ज्ञा ३ कु कु वि । सं १ अ । द २ । ले ६/६ । भ २ । स १ मि । सं २ । आ २ । उ ५ । तत्पर्याप्तानां—गु १ मि । जो २ संज्ञ्यसंज्ञिपर्याप्तौ । प ६ ५ । प्रा १० ९ । सं ४ । ग ३ ति म दे । इं १ पं । का १ त्र । यो १० म ४ व ४ औ १ वै १ । वे १ स्त्री । क ४ । ज्ञा ३ कु कु वि । सं १ अ । द २ च अ । ले ६/६ । भ २ । स १ मि । सं २ । आ १ । उ ५ । तदपर्याप्तानां—गु १ मि । जो २ संज्ञ्यसंज्ञ्यपर्याप्तौ ।

पुंवेदिमिथ्यादृष्टिगळ्गे । गु १ । मि । जी ४ । प ६ । ६ । ५ । ५ । प्रा १० । ७ । ९ । ७ सं ४ । ग ३ । ति । म । दे । इं १ । पं । का १ त्र । यो १३ । आहारद्वयरहित । वे १ । पुं । क ४ ज्ञा ३ । कु । कु । वि । सं १ । अ । द २ । ले ६/६ । भ २ । स १ । मि । सं २ । आ २ । उ ५ ।

पुंवेदिमिथ्यादृष्टिपर्य्याप्तकंगे । गु १ । मि । जी २ । प ६ । ५ । प्रा १० । ९ । सं ४ । ग ३ । ति । म । दे । इं १ । का १ । यो १० । म ४ । व ४ । औ १ । वै १ । वे १ । पुं । क ४ । ज्ञा ३ । कु । कु । वि । सं १ । अ । द २ । ले ६/६ । भ २ । स १ । मि । सं २ । आ १ उ ५ ॥

पुंवेदिमिथ्यादृष्टिअपर्य्याप्तकंगे । गु १ । मि । जी २ । प ६ । ५ । अ । प्रा ७ । ७ । सं ४ । ग ३ । ति । म । दे । इं १ । का १ । यो ३ । औमि । वैमि । का । वेद १ । पुं । क ४ । ज्ञा २ । सं १ । अ । द २ । ले २ क शु । भा १ । भ २ । सं १ । मि । सं २ । आ २ । उ ४ ॥

पुंवेदिसासादनप्रभृति प्रथमानिवृत्तिपर्य्यंतं मूलोघभंग वक्तव्यमक्कुमल्लि विशेषमावुदें दोडे सर्व्वत्र पुंवेदमो दे वक्तव्यमक्कुं । सासादनमिश्रासंयतरुगें गतित्रयं वक्तव्यमक्कुं । देशसंयतंगे गतिद्वयं वक्तव्यमक्कुंमन्यत्र विशेषमिल्ल । नपुंसकवेदिगळ्गे । गु ९ । जी १४ । प ६ । ६ । ५ । ५ । ४ । ४ । प्रा १० । ७ । ९ । ७ । ८ । ६ । ७ । ५ । ६ । ४ । ४ । ३ । सं ४ । ग ३ । न । ति । म । इं ५ । का ६ । यो १३ । आहारद्वयरहित । वे १ नं । क ४ । ज्ञा ६ । कु । कु । वि । म । श्रु । अ । सं ४ । अ । दे । सा । छे । द ३ । च । अ । अ । ले ६/६ । भ २ । स ६ । सं २ । आ २ । उ ९ ॥

नपुंसकवेदिपर्य्याप्तकंगे । गु ९ । जी ७ । प ६ । ५ । ४ । प्रा १० । ९ । ८ । ७ । ६ । ४ । सं ४ । ग ३ । न । ति । म । इं ५ । का ६ । यो १० । म ४ । व ४ । औ १ । वै १ । वे १ नं ।

तन्मिथ्यादृशां—गु १ मि, जी ४, प ६, ६, ५, ५, प्रा १०, ७, ९, ७, सं ४, ग ३ ति म दे, इं १ पं, का १ त्र, यो १३ आहारकद्वयं नहि, वे १ पुं, क ४, ज्ञा ३ कु कु वि, सं १ अ, द २, ले ६/६, भ २, स १ मि, सं २, आ २, उ ५ । तत्पर्याप्तानां—गु १ मि, जी २, प ६ ५, प्रा १०, ९, सं ४, ग ३ ति म दे, इं १ का १ त्र, यो १० म ४ व ४ औ वै, वे १ पु, क ४, ज्ञा ३ कु कु वि, सं १ अ, द २, ले ६/६, भ २, स १ मि, सं २, आ २, उ ५ । तदपर्याप्तानां—गु १ मि, जी २, प ६, ५, अ, प्रा ७, ७, सं ४, ग ३ ति म दे, इं १ पं, का १, यो ३ औमि वैमि का, वे १ पुं, क ४, ज्ञा २, सं १ अ, द २ । ले २ क शु, भा ६, भ २, स १ मि, सं २, आ २, उ ४ । तत्सासादनात् प्रथमानिवृत्तिपर्यंतं मूलोघः अत्र सर्वत्र पुंवेदो वक्तव्यः सासादनमिश्रासंयतानां गतित्रयं । देशसंयतस्य गतिद्वयं, अन्यत्र विशेषो नास्ति । नपुंसकवेदिनां—गु ९ । जी १४ । प ६ । ६ । ५ । ५ । ४ । ४ । प्रा १० । ७ । ९ । ७ । ८ । ६ । ७ । ५ । ६ । ४ । ४ । ३ । सं ४, ग ३ न ति म, इं ५, का ६ । यो १३ आहारद्वयाभावात् । वे १ नं, क ४, ज्ञा ६ कु कु वि म श्रु अ, सं ४ अ दे सा छे, द ३ च अ अ, ले ६/६ भ २, स ६, सं २, आ २, उ ९ । तत्पर्याप्तानां—गु ९, जी ७, प ६, ५, ४, प्रा १०, ९, ८, ७, ६, ४, सं ४ । ग ३ न ति म, इं ५, का ६, यो

पुंवेदिमिथ्यादृष्टिगळ्गे । गु १ । मि । जो ४ । प ६ । ६ । ५ । ५ । प्रा १० । ७ । ९ । ७ संं ४ । ग ३ । ति । म । दे । इं १ । पं । का १ त्र । यो १३ । आहारद्वयरहित । वे १ । पुं । क ४ ज्ञा ३ । कु । कु । वि । सं १ । अ । द २ । ले ६/६ । भ २ । सं १ । मि । सं २ । आ २ । उ ५

पुंवेदिमिथ्यादृष्टिपर्य्याप्तकंगे । गु १ । मि । जो २ । प ६ । ५ । प्रा १० । ९ । सं ४ । ग ३ ति । म । दे । इं १ । का १ । यो १० । म ४ । व ४ । औ १ । वै १ । वे १ । पुं । क ४ । ज्ञा ३ कु । कु । वि । सं १ । अ । द २ । ले ६/६ । भ २ । सं १ । मि । सं २ । आ १ उ ५ ॥

पुंवेदिमिथ्यादृष्टिअपर्य्याप्तकंगे । गु १ । मि । जो २ । प ६ । ५ । अ । प्रा ७ । ७ । सं ४ । ग ३ । ति । म । दे । इं १ । का १ । यो ३ । औमि । वैमि । का । वेद १ । पुं । क ४ । ज्ञा २ । सं १ । अ । द २ । ले २ क शु/भा १ । भ २ । सं १ । मि । सं २ । आ २ । उ ४ ॥

पुंवेदिसासादनप्रभृति प्रथमानिवृत्तिपर्य्यंतं मूलौघभंग वक्तव्यमक्कुमल्लि विशेषमावुदें दोडे : सर्व्वत्र पुंवेदमो वे वक्तव्यमक्कुं । सासादनमिश्रासंयतर्गे गतित्रयं वक्तव्यमक्कुं । देशसंयतंगे गति-द्वयं वक्तव्यमक्कुंमन्यत्र विशेषमिल्ल । नपुंसकवेदिगळ्गे । गु ९ । जी १४ । प ६ । ६ । ५ । ५ । ४ । ४ । प्रा १० । ७ । ९ । ७ । ८ । ६ । ७ । ५ । ६ । ४ । ४ । ३ । सं ४ । ग ३ । न । ति । म । इं ५ । का ६ । यो १३ । आहारद्वयरहित । वे १ षं । क ४ । ज्ञा ६ । कु । कु । वि । म । श्रु । अ । सं ४ । अ । दे । सा । छे । द ३ । च । अ । अ । ले ६/६ । भ २ । सं ६ । सं २ । आ २ । उ ९ ॥

नपुंसकवेदिपर्य्याप्तकंगे । गु ९ । जी ७ । प ६ । ५ । ४ । प्रा १० । ९ । ८ । ७ । ६ । ४ । सं ४ । ग ३ । न । ति । म । इं ५ । का ६ । यो १० । म ४ । व ४ । औ १ । वै १ । वे १ षं ।

तन्मिथ्यादृशा—गु १ मि, जी ४, प ६, ६, ५, ५, प्रा १०, ७, ९, ७, सं ४, ग ३ ति म दे, इं १ पं, का १ त्र, यो १३ आहारकद्वयं नहि, वे १ पुं, क ४, ज्ञा ३ कु कु वि, सं १ अ, द २, ले ६/६, भ २, स १ मि, सं २, आ २, उ ५ । तत्पर्याप्तानां—गु १ मि, जी २, प ६ ५, प्रा १०, ९, सं ४, ग ३ ति म दे, इं १ का १ त्र, यो १० म ४ व ४ औ वै, वे १ पु, क ४, ज्ञा ३ कु कु वि, सं १ अ, द २, ले ६/६, भ २, स १ मि, सं २, आ २, उ ५ । तदपर्याप्तानां—गु १ मि, जी २, प ६, ५, अ, प्रा ७, ७, सं ४, ग ३ ति म दे, इं १ पं, का १, यो ३ औमि वैमि का, वे १ पु, क ४, ज्ञा २, सं १ अ, द २ । ले २ क शु/भा ६, भ २, स १ मि, स २, आ २, उ ४ । तत्सासादनात् प्रथमानिवृत्तिपर्यंतं मूलौघः अत्र सर्वत्र पुंवेदो वक्तव्यः सासादनमिश्रासंयतानां गतित्रयं । देशसंयतस्य गतिद्वयं, अन्यत्र विशेषो नास्ति ।

नपुंसकवेदिनां—गु ९ । जी १४ । प ६ । ६ । ५ । ५ । ४ । ४ । प्रा १० । ७ । ९ । ७ । ८ । ६ । ७ । ५ । ६ । ४ । ४ । ३ । सं ४, ग ३ न ति म, इं ५, का ६ । यो १३ आहारद्वयाभावात् । वे १ षं, क ४, ज्ञा ६ कु कु वि म श्रु अ, सं ४ अ दे सा छे, द ३ च अ अ, ले ६/६ भ २, स ६, सं २, आ २, उ ९ । तत्पर्याप्तानां—गु ९, जी ७, प ६, ५, ४, प्रा १०, ९, ८, ७, ६, ४, सं ४ । ग ३ न ति म, इं ५, का ६, यो

पं। क ४। ज्ञा २। सं १। अ। द २। ले २ क शु। भ २। सं १ मि। सं २। आ २। उ ४।
भा ३ अशु

नपुंसकसासादनंगे। गु १। जी २। प ६। ६। प्रा १०। ७। सं ४। ग ३। न। ति। म। इं १। पं। का १ त्र। यो १२। म ४। व ४ औ २। वै १। कार्म्मण का १। वे १ नपुं। क ४। ज्ञा ३। कु। कु। वि। सं १। अ। द २। च। अ। ले ६/६। भ १। सं १। सासा। सं १। आ २। उ ५॥

नपुंसकवेदिसासादनपर्य्याप्तकंगे। गु १। सा।। जी १। प ६। प्रा १०।। सं ४। ग ३। न। ति। म। इं १। पं। का १। त्र। यो १०। म ४। व ४। औ १। वै १। वे १ नपुं। क ४। ज्ञा ३। कु। कु। वि। सं १। अ। द २। ले ६/६। भ १। सं १। सा। सं १। आ १। उ ५॥

नपुंसकवेदिसासादनापर्य्याप्तकंगे। गु १। सासा। जी १। अ। प ६। अ। प्रा ७। अ। सं ४। ग २ ति। म। इं १। का १। यो २। औ मि। का। वे नपुं। क ४। ज्ञा २। कु। कु। सं १। अ। द २। च। अ। ले २ क शु। भ १। सं १। सासा। सं १। आ २। उ ४॥
भा ३ अशु

नपुंसकवेदिसम्यग्मिथ्यादृष्टिगळ्गे। गु १। मिश्र। जी १। प ६। प्रा १०। सं ४। ग ३। न। ति। म। इं १। पं। का १ त्र। यो १०। म ४। व ४। औ का। वै का। वे १ नपुं। क ४। ज्ञा ३ कु। कु। वि। सं १। अ। द २। च। अ। ले ६/६। भ १। सं १ मिश्र। सं १। आ १। उ ५॥

यो २ औमि वैमि का, वे १ पं, क ४, ज्ञा २, सं १ अ, द २, ले २ क, शु भ २, स १ मि, सं २, आ २, उ ४, (भा ३ अशु) तत्सासादनानां—गु १। जी २, सं प अ, प ६, ६, प्रा १०, ७, सं ४, ग ३ न ति म, इं १ पं, का १ त्र, यो १२ म ४ व ४ औ २ वै १ का १, वे १ नं, क ४, ज्ञा ३ कु कु वि, सं १ अ, द २ च अ, ले ६/६, भ १, स १ सा, सं १, आ २, उ ५, तत्पर्याप्तानां—गु १ सा, जी १ प, प ६, प्रा १०, सं ४, ग ३ न ति म, इं १ पं, का १ त्र, यो १० म ४ व ४ औदा वैका, वे १ न, क ४, ज्ञा ३ कु कु वि, सं १ अ, द २, ले ६/६, भ १, स १ सा, सं १, आ १, उ ५। तदपर्याप्तानां—गु १ सा, जी १ अ, प ६ अ। प्रा ७ अ, सं ४, ग २ ति म, इं १, का १, यो २ औमि का, वे १ न, क ४, ज्ञा २ कु कु, सं १ अ, द २ च अ, ले २ क शु। (भा ३ अशु) भ १, स १ सा, सं १, आ २, उ ४। तत्सम्यग्मिथ्यादृष्टीनां—गु १ मिश्रं, जी १ प, प ६, प्रा १०, सं ४, ग ३ न ति म, इं १ पं, का १ त्र, यो १० म ४, व ४ औ १ वै १, वे १ न, क ४,

अपगतवेदग्गें । गु ६ । अ । सू । उ । खी । स । अ । जी २ । प अ । प ६ । प्रा १०।४। २ । १ । सं १ । परि । ग १ । म । इं १ । पं । का १ त्र । यो ११ । म ४ । वा ४ । औ २ । का। वे ० । क ४ । २ । १ । लो । ज्ञा ५ । म । श्रु । अ । म । के । सं ४ । सा । छे । सू । यथा । द ४। च । अ । अ । के । ले ६ । भ १ । सं २ । उ । क्षा । सं १ । आ २ । उ ९ ॥
भा ६

इंतो द्वितीयभागानिवृत्तिप्रभृति सिद्धपर्य्यंतं मूलोघभंगमक्कुं । मितु वेदमार्गे समाप्तमावुदु ॥

कषायानुवाददोळु ओघालापं मूलोघभंगमक्कुं । विशेषमावुदें दोडे दशगुणस्थानंगळप्पु। क्रोधकषायिगळगे । गु ९ । जी १४ । प ६ । ६ । ५ । ५ । ४ । ४ । प्रा १० । ७ । ९ । ७ । ८ । ६ । ७ । ५ । ६ । ४ । ४ । ३ । सं ४ । ग ४ । इं ५ । का ६ । यो १५ । वे ३ । क १ । क्रो । ज्ञा ७ । कु । कु । वि । म । श्रु । अ । म । सं ५ अ । दे । सा १ । छे १ । प १ । द ३ । च । अ । अ । ले ६ भ २ । सं ६ । सं २ । आ २ । उ १० ॥
६

क्रोधकषायिपर्य्याप्तकर्गे । गु ९ । जी प ७ । प ६ । ५ । ४ । प्रा १० । ९ । ८ । ७ । ६ । ४ । सं ४ । ग ४ । इं ५ । का ६ । यो ११ । म ४ । वा ४ । औ का १ । वै का १ । आ का १ । वे ३ । क १ । क्रो । ज्ञा ७ । कु । कु । वि । म । श्रु । अ । म । सं ५ । अ । दे । सा । छे । प । द ३ । च । अ । अ । ले ६ । भ २ । सं ६ । सं २ । आ २ । उ १० ॥
६

क्रोधकषायिकापर्य्याप्तकर्गे गु ४ । मि । सा । अ । प्र । जी ७ । अ । प ६ । ५ । ४ । अ । प्रा ७ । ७ । ६ । ५ । ४ । ३ । अ । सं ४ । ग ४ । इं ५ । का ६ । यो ४ । औमि । वैमि । आमि । का । वे ३ । क १ क्रो । ज्ञा ५ । कु । कु । म । श्रु । अ । सं ३ । अ । सा । छे । द ३ । च ।

अपगतवेदानां—गु ६ अनि, सू, उ, क्षी, स, अ, जी २ प अ, प ६, ६, प्रा १०, ४, २, १, सं १ परि, ग १ म, इं १ पं, का १ त्र, यो ११ म ४ व ४ औ २ का १, वे ०, क ४, ३, २, १ लो । ज्ञा ५ म श्रु अ म के, सं ४ सा छे सू य, द ४ च अ अ के, ले ६, भ १, स २ उ क्षा, सं १, आ, २, उ ९ ।
भा १
द्वितीयभागानिवृत्तितः सिद्धपर्यंतं मूलौघो भवति, वेदमार्गणा गता ।

कषायानुवादे ओघः तद्यथा–क्रोधिना—गु ९, जी १४, प ६, ६, ५, ५, ४, ४, प्रा १०, ७, ९, ७, ८, ६ ७ ५ ६, ४, ४ ३, सं ४, ग ४, इं ५, का ६, यो १५, वे ३, क १ क्रो, ज्ञा ७ कु कु वि म श्रु अ म, सं ५ अ दे सा छे प, द ३ च अ अ, ले ६ भ २, स ६, सं २, आ २, उ १० । तत्पर्याप्तानां—गु ९, जी ७ प, प ६, ५, ४, प्रा १०, ९, ८, ७, ६, ४, सं ४, ग ४ इं ५, का ६, यो ११, म ४, व ४, औ वै आ, वे ३, क १ क्रो, ज्ञा ७ कु कु वि म श्रु अ म, सं ५ अ दे सा छे प, द ३ च अ अ, ले ६, भ २, स ६, सं २, आ १, उ १० । तदपर्याप्तानां—गु ४ मि सा अ प्र । जी ७ अ, प ६, ५, ४ अ, प्रा ७, ७, ६, ५, ४, ३ अ, सं ४, ग ४, इं ५, का ६, यो ४ औमि वैमि आमि का, वे ३, क १ क्रो, ज्ञा ५ कु कु

क्रोधकषायिसासादनपर्य्याप्तकंग। गु १। सासा। जो १। प। प ६। प्रा १०। सं ४
ग ४। इं १। पं। का १ त्र। यो १०। म ४। वा ४। ओ। वे। वे ३। क १ क्रो। ज्ञा ३
कु। कु। वि। सं १। अ। द २। च। अ। ले ६ भ १। सं १। सासा। सं १। आ १। उ ५।
६

क्रोधकषायिसासादनापर्य्याप्तकंगे। गु १। सासा। जो १। अ। प ६। अ प्रा ७। अ।
सं ४। ग ३। नरकगतिवर्जित। इं १ पं। का १ त्र। यो ३। औ मि। वै मि। का। वे ३।
क १ क्रो। ज्ञा २। सं १ अ। द २। ले २। भ १। सं १। सासा। सं १। आ २। उ ४॥
भा ६

क्रोधकषायिसम्यग्मिथ्यादृष्टिगळ्गे। गु १। मिश्र। जो १। प। प ६। प्रा १०। सं ४।
ग ४। इं १। पं। का १। त्र। यो १०। वे ३। क १ क्रो। ज्ञा ३। मिश्र सं १। द २। ले ६।
६
भ १। सं १। मिश्र। सं १। आ १। उ ५॥

क्रोधकषायिअसंयतसम्यग्दृष्टिगळ्गो। गु १। असं। जी २। प। अ। प ६। ६। प्रा १०।
७। सं ४। ग ४। इं १। पं। का १ त्र। यो १३। आहारद्वयरहित। वे ३। क १। क्रो। ज्ञा ३।
म। श्रु। अ। सं १। अ। द ३। च। अ। अ। ले ६। भ १। सं ३। उ। वे। क्षा। सं १।
६
आ २। उ ६॥

क्रोधकषायि असंयतसम्यग्दृष्टिपर्य्याप्तकंगे। गु १। असं। जी १। प। प ६। प्रा १०।
सं ४। ग ४। इं १ पं। का १ त्र। यो १०। वे ३। क १ क्रो। ज्ञा ३। म। श्रु। अ। सं १।
अ। द ३। च। अ। अ। ले ६। भ १। सं ३। उ। वे। क्षा। सं १। आ १। उ ६॥
६

तत्पर्याप्तानां–गु १ सा। जो १ प। प ६। प्रा १०। सं ४। ग ४। इं १ पं। का १ त्र। यो १० म ४ व ४ औ वै। वे ३। क १ क्रो। ज्ञा ३ कु कु वि। सं १ अ। द २ च अ। ले ६। भ १। स १ सा।
६
सं १। आ १। उ ५। तदपर्याप्तानां—गु १ सा। जी १ अ। प ६ अ। प्रा ७ अ। सं ४। ग ३ नरकगतिर्नहि। इं १ पं। का १ त्र। यो ३ औमि वैमि का। वे ३। क १ क्रो। ज्ञा २। सं १ अ। द २।
ले २। भ १। स १ सा। सं १। आ २। उ ४। सम्यग्मिथ्यादृशां—गु १ मिश्रं, जी १ प। प ६।
६
प्रा १०। सं ४। ग ४। इं १। का १ त्र। यो १० औ। वे ३। क १ क्रो। ज्ञा ३ मिश्राणि। सं १ अ।
द २। ले ६। भ १। स १ मिश्रं। सं १। आ १। उ ५। असंयतानां—गु १ अ। जी २ प अ। प ६
६
६। प्रा १० ७। सं ४। ग ४। इं १ पं। का १ त्र। यो १३ आहारद्वयं नहि। वे ३। क १ क्रो। ज्ञा ३ म श्रु अ। सं १ अ। द ३ च अ अ। ले ६। भ १। स ३ उ वे क्षा। सं १। आ २। उ ६।
६
तत्पर्याप्तानां–गु १ अ। जी १ प। प ६। प्रा १०। सं ४। ग ४। इं १ पं। का १ त्र। यो १०। वे ३। क १ क्रो। ज्ञा ३ म श्रु अ। सं १ अ। द ३ च अ अ। ले ६। भ १। स ३ उ वे क्षा। स १। आ १।
६

क्रोधकषायिप्रथमानिवृत्तिकरणंगे । गु १ । अनि । जी १ । प । प ६ । प्रा १० । स
मै । प । म १ । म । इं १ । पं । का १ त्र । यो ९ । वे ३ । क १ क्रो । ज्ञा ४ । म । श्रु । अ
सं २ । सा । छे । द ३ । च । अ । अ । ले ६ । भ १ । सं २ । उ । क्षा । सं १ । आ १ । उ
भा १

क्रोधकषायिद्वितीयभागानिवृत्तिकरणंगे । गु १ । जी १ । प ६ । प्रा १० । सं १ ।
म १ । म । इं १ । पं । का १ त्र । यो ९ । वे ० । क १ क्रो । ज्ञा ४ । म । श्रु । अ । म । सं
सा । छे । द ३ । च । अ । अ । ले ६ । भ १ । सं २ । उ । क्षा । सं १ । आ १ । उ ७ ॥
भा १

ई प्रकारदिंदमे माननायाकषायंगळ्गे मिथ्यादृष्टिप्रभृति अनिवृत्तिकरणपर्यंतं वक्तव्यमक्कु
विशेषमावुदें दोडे एल्लि एल्लि क्रोधकषायमल्लल्लि मानमायाकषायंगळु वक्तव्यंगळप्पुवु । लो
कषायक्कं क्रोधकषायभंगमेयक्कुं । विशेषमावुदें दोडे ओघालापदोळु दश गुणस्थानंगळेंदु वक्त
मरकुमारं संयमगळुं लोभकषायमों दे वक्तव्यमक्कु ॥

अकषायरुगळ्गे । गु ४ । उ । क्षी । स । अ । जी २ । प ६ । ६ । प्रा १० । ४ । २ । १
सं । ० । ग १ । म । इं १ । पं । का १ । त्र । यो ११ । म ४ । वा ४ । औ २ । का १ । वे ०
क ० । ज्ञा ५ । म । श्रु । अ । म । के । सं १ । यथा । द ४ । च । अ । अ । के । ले ६ । भ १
सं २ । उ । क्षा । सं १ । आ २ । उ ९ ॥ भा १

अकषायसामान्यं पेळल्पट्टुदु । विशेषदिंदमुपशांतकषायप्रभृति सिद्धपरमेष्ठिगळ्पर्यंतं
सामान्यभंगगळप्पुवु । इंतु कषायमार्गणे समाप्तमादुदु ॥

ज्ञानानुवाददोळु ओघालापंगळु मूलौघभंगगळप्पुवु । कुमतिकुश्रुतज्ञानिगळ्गे । गु २ । मि ।
सा । जी १४ । प ६ । ६ । ५ । ५ । ४ । ४ । प्रा १० । ७ । ९ । ७ । ८ । ६ । ७ । ५ । ६ । ४ । ४ ।

धा । सं १ । आ १ । उ ७ । अनिवृत्तिकरणानां प्रथमभागे—गु १ अनि । जी १ प । प ६ । प्रा १० ।
म २ सं २ । ग १ म । इं १ पं । का १ त्र । यो ९ । वे ३ । क १ क्रो । ज्ञा ४ म श्रु अ म । सं २ सा
छे । द ३ च अ अ । ले ६, भ १ । स २ उ क्षा । सं १ । आ १ । उ ७ । द्वितीयभागे—गु १ । जी १ ।
भा १
प ६ । प्रा १० । सं १ प । ग १ म । इं १ पं । का १ त्र । यो ९ । वे ० । क १ क्रो । ज्ञा ४ म श्रु अ म ।
सं २ सा छे । द ३ च अ अ । ले ६ । भ १ । स २ उ क्षा । सं १ । उ ७ । एवं मानमाययोरपि [illegible]
भा १
[illegible] किंतु [illegible]

अकषायिणाम्—गु ४ उ क्षी स अ, जी २, प ६ ६, प्रा १० ४ २ १, सं ०, ग १ म, इं १ प,
का १ त्र, यो ११ म ४ व ४ औ २ का १, वे ०, क ०, ज्ञा ५, म श्रु अ म के, सं १ य, द ४ च अ अ के,
ले ६ । भ १, स २ उ क्षा, सं १, आ २, उ ९ । इदं सामान्यकथनं विशेषेण उपशान्तकषायादिसिद्धपर्यं
भा १
[illegible]

कुमतिकुश्रुतज्ञानिनाम्—गु २ मि सा, जी १४, प ६ ६ ५ ५ ४ ४, प्रा १० ७ ९ ७ ८ ६ ७ ५ ६ ४ ४

कुमतिकुश्रुतज्ञानिअपर्य्याप्तकर्गं । गु २ । मि । सा । जो ७ । अ । प ६ । ५ । ४ । अ । प्रा ७ । ७ । ६ । ५ । ४ । ३ । सं ४ । ग ४ । इं ५ । का ६ । यो ३ । औ मि । वै मि । का । वे ३ । क ४ । ज्ञा २ । सं १ । अ । द २ । ले २क शु । भ २ । सं २ । मि । सा । सं २ । आ २ । उ ४ ॥
भा ६

कुमतिकुश्रुतज्ञानिमिथ्यादृष्टिगळ्गे । गु १ । मि । जो १४ । प ६ । ६ । ५ । ५ । ४ । ४ । प्रा १० । ७ । ९ । ७ । ८ । ६ । ७ । ५ । ६ । ४ । ४ । ३ । सं ४ । ग ४ । इं ५ । का ६ । यो ११ । आहारकद्वयरहित । वे ३ । क ४ । ज्ञा २ । कु । कु । सं १ । अ । द २ । च । अ । ले ६ । भ २ । सं १ । मि । सं २ । आ २ । उ ४ ॥
६

कुमतिकुश्रुतज्ञानिमिथ्यादृष्टिपर्य्याप्तकर्गे । गु १ । मि । जो ७ । प । प ६ । ५ । ४ । प । प्रा १० । ९ । ८ । ७ । ६ । ४ । सं ४ । ग ४ । इं ५ । का ६ । यो १० । म ४ । वा ४ । औ का १ । वै का १ । वे ३ । क ४ । ज्ञा २ । कु । कु । सं १ । अ । द २ । च । अ । ले ६ । भ २ । सं १ । मि । सं २ । आ १ । उ ४ ॥
६

कुमतिकुश्रुतज्ञानिमिथ्यादृष्टिअपर्य्याप्तकर्गे । गु १ । मि । जो ७ । अ । प ६ । ५ । ४ । अ । प्रा ७ । ७ । ६ । ५ । ४ । ३ । सं ४ । ग ४ । इं ५ । का ६ । यो ३ । औ मि । वै मि । का । वे ३ । क ४ । ज्ञा २ । कु । कु । सं १ । अ । द २ । च । अ । ले २क शु । भ २ । सं १ । मि । सं २ । आ २ । उ ४ ॥
भा ६

कुमतिकुश्रुतज्ञानिसासादनंगे । गु १ । सासा । जो २ । प । अ । प ६ । ६ । प्रा १० । ७ । सं ४ । ग ४ । इं १ पं । का १ त्र । यो १३ । आहारद्वयवर्जितं । वे ३ । क ४ । ज्ञा २ । कु । कु । सं १ अ । द २ । च । अ । ले ६ । भ १ । सं १ । सासा । सं १ । आ २ उ ४ ॥
६

कुमतिकुश्रुतज्ञानिसासादनपर्य्याप्तकर्गे गु १ । सासा । जो १ । प । प ६ । प्रा १० । सं ४ । ग ४ । इं १ । पं । का १ त्र । यो १० । म ४ । वा ४ । औ का । वै का । वे ३ । क ४ । ज्ञा २ । कु । कु । सं १ । अ । द २ । ले ६ । भ १ । सं १ । सासा । सं १ । आ १ । उ ४ ॥
६

उ ४ । तदपर्याप्तानां—गु १ मि, जी ७ अ, प ६ ५ ४ अ, प्रा ७ ७ ६ ५ ४ ३, सं ४, ग ४, इं ५, का ६, यो ३ औमि वैमि का, वे ३, क ४, ज्ञा २ कु कु, सं १ अ, द २ च अ, ले २ क शु, भ २, स १ मि, सं २, आ २, उ ४ । तत्सासादनानां—गु १ सा, जो २ प अ, प ६ ६, प्रा १० ७, सं ४, ग ४, इं १ पं, का १ त्र,
६
यो ११ आहारद्वयवर्ज । वे ३, क ४, ज्ञा २ कु कु, सं १ अ, द २ च अ, द २ च अ, ले ६, भ १ सं १ सा, सं १, आ २, उ ४ । तत्पर्याप्तानां—गु १ सा, जो १ प, प ६, प्रा १०, सं ४, ग ४, इं १ पं,
६
का १ त्र, यो १० म ४ व ४ औ वै, वे ३, क ४, ज्ञा २ कु कु, सं १ अ, द २, ले ६, भ १, सं १ सा,
६

म । श्रु । अ । म । सं ३ । सा । छे । प । व ३ । च । अ । अ । ले ६/भा ३ भ १ । सं ३ । उ । वे । क्षा । सं १ । आ १ । उ ७ ॥

अप्रमत्तसंयतंगे । गु १ । अ । जी १ । प । प ६ । प्रा १० । सं ३ । आहारसंज्ञारहित । ग १ म । इं १ । पं । का १ त्र । यो ९ । वे ३ । क ४ । ज्ञान ४ । म । श्रु । अ । म । सं ३ । सा । छे । प । व ३ । ले ६/भा ३ । भ १ । सं ३ । उ । वे । क्षा । सं १ । आ १ । उ ७ ॥

अपूर्व्वकरणप्रभृति अयोगिकेवलिपर्य्यंतं मूलौघभंगमक्कुं । सामायिकसंयतंगे । गु ४ । प्र । अ । अ । अ । जी २ । प । अ । प ६ । ६ । प्रा १० । ७ । सं ४ । ग १ । म । इं १ । पं । का १ त्र । यो ११ । म ४ । वा ४ । औ का १ । आ २ । वे ३ । क ४ । ज्ञा ४ । म । श्रु । अ । म । सं १ । सामायिक । व ३ । च । अ । अ । ले ६/भा ३ । भ १ । सं ३ । उ । वे । क्षा । सं १ । आ १ । उ ७ ॥

अनिवृत्तिपर्य्यंतमूलौघभंगमक्कुं । छेदोपस्थापनसंयमक्कुमी प्रकारमे वक्तव्यमक्कुं ॥

परिहारविशुद्धिसंयमिगळ्गे गु २ । प्र । अ । जी १ । प ६ । प्रा १० । सं ४ । ग १ । म । इं १ पं । का १ त्र । यो ९ । वे १ पुं । क ४ । ज्ञा ३ । म । श्रु । अ । सं १ । परिहारविशुद्धि । व ३ । च । अ । अ । ले ६/भा ३ । भ १ । सं २ । वे । क्षा । सं १ । आ १ । उ ६ ॥

प्रमत्ताप्रमत्तपरिहारविशुद्धिसंयतरुगळ्गे बेरूल्पडुवल्लि ओघभंगमेयक्कुं । सूक्ष्मसांपराय-संयमक्के मूलौघभंगमेयक्कुं । यथाख्यातसंयमिगळ्गे । गु ४ । उ । क्षी । स । अ । जी २ । प । अ । प ६ । ६ । प्रा १० । ४ । २ । १ । सं । ० । ग १ । म । इं पं । का १ त्र । यो ११ । म ४ । वा ४ ।

---

१ आ २ । वे ३ । क ४ । ज्ञा ४ म श्रु अ म । सं ३ सा छे प । द ३ च अ अ । ले ६/६ । भ १ । स ३ उ वे क्षा । सं १ । आ १ । उ ७ । अप्रमत्तानां—गु १ अप्र । जी १ प । प ६ । प्रा १० । सं ३ । आहार-संज्ञा नहि । ग १ म । इं १ पं । का १ त्र । यो ९ । वे ३ । क ४ । ज्ञा ४ म श्रु अ म । सं ३ सा छे प । द ३ । ले ६/३ । भ १ । स ३ उ वे क्षा । सं १ । आ १ । उ ७ । अपूर्वकरणाद्ययोगिपर्यंतं मूलोघभंगो भवति । सामायिकसंयतानां—गु ४ प्र अ अ अ । जी २ प अ । प ६ ६ । प्रा १० । ७ । सं ४ । ग १ म । इं १ पं । का १ त्र । यो ११ । म ४ व ४ औ १ आ २ । वे ३ । क ४ । ज्ञा ४ म श्रु अ म । सं १ सामायिकं । द ३ च अ अ । ले ६/३ । भ १ । स ३ उ वे क्षा । सं १ । आ १ । उ ७ । अनिवृत्तिपर्यंतं मूलौघभंगो भवति । छेदोपस्थापनसंयतानामप्येवं ।

परिहारविशुद्धिसंयमिनां—गु २ प्र अ । जी १ । प ६ । प्रा १० । सं ४ । ग १ म । इं १ पं । का १ त्र । यो ९ । वे १ पुं । क ४ । ज्ञा ३ म श्रु अ । सं १ परि । द ३ च अ अ । ले ६/३ । भ १ । स २ वे क्षा । सं १ । आ १ । उ ६ । प्रमत्ताप्रमत्तानां सूक्ष्मसांपरायसंयतानां च मूलोघभंगः । यथाख्यातसंयमिनां—गु ४ उ क्षी स अ । जी २ प । अ । प ६ ६ । प्रा १० । ४ । २ । १ । सं ० ।

दर्शनानुवाददोळु ओघालापं मुन्नीयंतंगमक्कुं। चक्षुर्दर्शनिगळ्गे। गु १२। जी ३। सं अ च। प ६। ६। ५। ५। प्रा १०। ७। ९। ७। ८। ६। सं ४। ग ४। इं २। पं। च। का १। त्र। यो १५। वे ३। क ४। ज्ञा ७। केवलज्ञानरहित। सं ७। अ। दे। सा। छे। प। सू। यथा। दर्श १। च। ले ६/६। भ २। सं ६। सं २। आ २। उ ८॥

चक्षुर्दर्शनिपर्य्याप्तकंगे। गु १२। जी ३। सं। अ। च। प ६। ५। प्रा १०। ९। ८। सं ४। ग ४। इं २ पं च। का १ त्र। यो ११। म ४। व ४। औ का। वै का। आ का। वे ३। क ४। ज्ञा ७। कु। कु। वि। म। श्रु। अ। म। सं ७। अ। दे। सा। छे। प। सू। यथा। द १। च। ले ६/६। भ २। सं ६। मि। सा। मि। उ। वे। क्षा। सं २। आ १। उ ८॥

चक्षुर्द्दर्शनिअपर्य्याप्तकंगे।। गु ४। मि। सा। अ। प्र। जी ३। सं अ च। प ६। ५। अ। प्रा ७। ७। ६। अ। सं ४। ग ४। इं २। पं। का १ त्र। यो ४। औ मि। वै मि। आ मि। का। वे ३। क ४। ज्ञा ५। कु। कु। म। श्रु। अ। सं ३। अ। सा। छे। द १ च। ले २ क शु / भा ६। भ २। सं ५। मि। सा। उ। वे। क्षा। सं २। आ २। उ ६॥

चक्षुर्द्दर्शनिमिथ्यादृष्टिगळ्गे। गु १ मि। जी ६। सं अ च २ २ २। प ६। ६। ५। ५। प्रा १०। ७। ९। ७। ८। ६। सं ४। ग ४। इं २। पं। च। का १ त्र। यो १३। आहारद्वयरहित। वे ३। क ४। ज्ञा ३। कु। कु। वि। सं १ अ। द १। च। ले ६/६ भ २। सं १। मि। सं २। आ २। उ ४॥

चक्षुर्दर्शनिनां—गु १२, जो ६, सं अ च २ २ २। प ६, ६, ५, ५, प्रा १०, ७, ९, ७, ८, ६, सं ४, ग ४। इं २ च, पं, का १ त्र, यो १५, वे ३, क ४, ज्ञा ७, कु कु वि म श्रु अ म, सं ७ अ, दे, सा, छे, प, सू, य। द १ चक्षुः, ले ६/६। भ २। स ६ मि सा मि उ वे क्षा, सं २, आ २, उ ८। तत्पर्याप्तानां—गु १२, जी ३ सं अ च, प ६, ५, प्रा १०, ९, ८, सं ४, ग ४। इं २ पं च, का १ त्र, यो ११ म ४ व ४ औ १ वै १, आ १, वे ३, क ४, ज्ञा ७ कु कु वि म श्रु अ म, सं ७ अ दे सा छे प सू य, द १ च। ले ६/६। भ २। स ६ मि सा मि उ वे क्षा, सं २। आ १। उ ८। तदपर्याप्तानां—गु ४ मि, सा, अ, प्र। जी ३ सं अ च १ १ १। प ६, ५, अ, प्रा ७ ७, ६ अ, सं ४, ग ४, इं २ पं च। का १ त्र, यो ४ औमि वैमि आमि का, वे ३, क ४, ज्ञा ५ कु कु म श्रु अ। सं ३ अ, सा छे द १ च। ले २ क शु / भा ६। भ २, स ५ मि सा उ वे क्षा, सं २। आ २। उ ६। तन्मिथ्यादृशां—गु १ मि। जी ६ सं अ च २ २ २। प ६, ६, ५, ५, प्रा १०, ७, ९,

अचक्षुर्द्दर्शनिअपर्य्याप्तकर्गे । गु [illegible] मि । सासा । अ । प्र । जो ७ । अ । प ६ । ५ । ४ । ३ । अ । प्रा ७ । ७ । ६ । ५ । ४ । ३ । सं ४ । ग ४ । इं ५ । का ६ । यो ४ । औ मि वै मि । आ मि । का । वे ३ । क ४ । ज्ञा ५ । कु । कु । म । श्रु । अ । सं ३ । अ । सा । छे । द १ । अच । ले २ क शु/भा ६ । भ २ । सं ५ । मि । सा । उ । वे । क्षा । सं २ । आ २ । उ ६ ॥

अचक्षुर्द्दर्शनिमिथ्यादृष्टिगळ्गे । गु १ । मि । जो १४ । प ६ । ६ । ५ । ५ । ४ । ४ । प्रा १० । ७ । ९ । ७ । ८ । ६ । ७ । ५ । ६ । ४ । ४ । ३ । सं ४ । ग ४ । इं ५ । का ६ । यो १३ । आहारद्वयरहित । वे ३ । क ४ । ज्ञा ३ । कु । कु । वि । सं १ । अ । द १ । अच ले ६/६ । भ २ । सं १ मि । सं २ । आ २ । उ ४ ॥

अचक्षुर्द्दर्शनिमिथ्यादृष्टिपर्य्याप्तकर्गे । गु १ । मि । जो ७ । प । प ६ । ५ । ४ । प्रा १० । ९ । ८ । ७ । ६ । ४ । सं ४ । ग ४ । इं ५ । का ६ । यो १० । म ४ । वा ४ । औ का । वै का । वे ३ । क ४ । ज्ञा ३ । कु । कु । वि । सं १ । अ । द १ अच । ले ६/६ । भ २ । सं १ मि । सं २ । आ १ । उ ४ ॥

अचक्षुर्द्दर्शनिमिथ्यादृष्ट्यपर्य्याप्तकर्गे । गु १ मि । जो ७ । अ । प ६ । ५ । ४ । अ प्रा ७ । ७ । ६ । ५ । ४ । ३ । सं ४ । ग ४ । इं ५ । का ६ । यो ३ । औ मि । वै मि । का । वे ३ । क ४ । ज्ञा २ । कु । कु । सं १ । अ । द १ । अच । ले २ क शु/भा ६ । भ २ । सं १ । मि । सं २ । आ २ । उ ३ ॥

अचक्षुर्द्दर्शनिसासादनप्रभृतिक्षीणकषायपर्य्यंतं अचक्षुर्द्दर्शनिगळ्गे वु यक्तव्यमक्कुं ।

नहि, सं ७, द १ अ, ले ६/६ । भ २, स ६, सं २, आ १, उ ८ । तदपर्याप्तानां—गु ४ मि सा अ प्र, जो ७ अ, प ६, ५, ४ अ, प्रा ७, ७, ६, ५, ४, ३, सं ४, ग ४, इं ५, का ६, यो ४ औमि वैमि आमि का, वे ३, क ४, ज्ञा ५, कु कु म श्रु अ, सं ३ अ, सा, छे । द १ अ, ले २ क शु/भा ६ । भ २, स ५ मि सा उ वे क्षा, सं २, आ २, उ ६ । तन्मिथ्यादृशां—गु १ मि, जी १४, प ६, ६, ५, ५, ४, ४, प्रा १०, ७, ९, ७, ८, ६, ७, ५, ६, ४, ४, ३, सं ४, ग ४ । इं ५, का ६, यो १३ आहारद्वयं नहि, वे ३, क ४, ज्ञा ३, कु कु वि, सं १ अ, द १ अ, ले ६/६, भ २, स १ मि, सं २, आ २, उ ४ । तत्पर्याप्तानां—गु १ मि । जी ७ प, प ६ । ५, ४, प्रा १०, ९, ८, ७, ६, ४, सं ४, ग ४, इं ५, का ६, यो १० म ४ व ४ औ १ वै १, वे ३ । क ४, ज्ञा ३ कु कु वि, सं १ अ, द १ अ, ले ६/६ । भ २, स १ मि, सं २, आ १, उ ४ । तदपर्याप्तानां—गु १ मि, जो ७ अ, प ६, ५, ४ अ, प्रा ७, ७, ६, ५, ४, ३, सं ४, ग ४, इं ५, का ६, यो ३ औमि वैमि का, वे ३, क ४, ज्ञा २ कु कु, सं १ अ, द १ अ, ले २ क शु/भा ६ । भ २, स १ मि, सं २, आ २ उ ३ । तत्सासादनात् क्षीणकषायांतं यथायोग्यं योज्यं ।

प्रा १० । ९ । ८ । ७ । ६ । ४ । सं ४ । ग ३ । म । ति । न । इं ५ । का ६ । यो १० । म ४ । वा ४ । औ का । वै का । वे ३ । क ४ । । ज्ञा ६ । कु । कु । वि । म । श्रु । अ । सं १ । अ । च ३ । च । अ । अ । ले ६ । भ २ । स ६ । मि । सा । मि । उ । वे । क्षा । सं २ । आ १ । उ ९ ॥
भा १ कृ

कृष्णलेश्याऽपर्य्याप्तकर्गे । गु ३ । मि । सा । अ । जी ७ । अ । प ६ । ५ । ४ । प्रा ७ । ७ । ६ । ५ । ४ । ३ । सं ४ । ग ४ । इं ५ । का ६ । यो ३ । औ मि । वै मि । का । वे ३ । क ४ । ज्ञा ५ । कु । कु । म । श्रु । अ । सं १ अ । द ३ । ले २ क शु । भ २ । सं ३ । मि । सा । वे । पंचमादिपृथ्विगळिवं बप्पं असंयतनोळु वेदकं संभविसुगुं । सं २ । आ २ । उ ८ ॥
भा १ कृ

कृष्णलेश्यामिथ्यादृष्टिगळ्गे । गु १ । मि । जी १४ । प ६ । ६ । ५ । ५ । ४ । ४ । प्रा १० । ७ । ९ । ७ । ८ ६ । ७ । ५ । ६ । ४ । ४ । ३ । सं ४ । ग ४ । इं ५ । का ६ । यो १३ । वे ३ । क ४ । ज्ञा ३ । कु । कु । वि । सं १ । अ । द २ । ले ६ । भ २ । सं १ । मि । सं २ । आ २ । उ ५ ॥
भा १ कृ

कृष्णलेश्यामिथ्यादृष्टिपर्य्याप्तकर्गे । गु १ । मि । जी ७ । प । प ६ । ५ । ४ । प्रा १० । ९ । ८ । ७ । ६ । ४ सं ४ । ग ३ । न । ति । म । इं ५ । का ६ । यो १० । म ४ । वा ४ । औ का । वै का । वे ३ । क ४ । ज्ञा ३ । कु । कु । वि । सं १ । अ । द २ । ले ६ । भ २ । सं ·· मि । सं २ । आ १ । उ ५ ॥
भा १ कृ

कृष्णलेश्यामिथ्यादृष्टयपर्य्याप्तकर्गे । गु १ । मि । जी ७ । अ । प ६ । ५ । ४ । प्रा ७ । ६ । ५ । ४ । ३ । अ । सं ४ । ग ४ । इं ५ । का ६ । यो ३ । औ मि । वै मि । का । वे ३ । क ४ ।

गु ४ मि सा मि अ, जी ७ प, प ६, ५, ४, प, प्रा १०, ९, ८, ७, ६, ४, सं ४, ग ३ म ति न, इं ५, का ६, यो १० म ४ व ४ औ वै, वे ३, क ४, ज्ञा ६ कु कु वि म श्रु अ, सं १ अ, द ३, च अ अ, ले ६, भ २, स ६ मि सा मि उ वे क्षा, स २, आ १, उ ९ । तदपर्याप्तानां—गु ३ मि सा अ, जी ७ अ, प ६, ५, ४ अ, प्रा ७, ७, ६, ५, ४, ३, सं ४, ग ४, इं ५, का ६, यो ३ औमि वैमि का, वे ३, क ४, ज्ञा ५ कु कु म श्रु अ, स १ अ, द ३, ले २ क शु । भ २, सं ३, मि सा वे, पंचमादिपृथ्व्यागतासंयतेषु वेदकसम्यक्त्वसंभवात्, सं २, आ २, उ ८ । तन्मिथ्यादृष्टां—गु १ मि, जी १४, प ६, ६, ५, ५, ४, ४, प्रा १०, ७, ९, ७, ८, ६, ७, ५, ६, ४, ४, ३ । सं ४, ग ४, इं ५, का ६, यो १३ । वे ३, क ४, ज्ञा ३ कु कु वि, सं १ अ, द २, ले ६, भ २, म १ मि, सं २, आ २, उ ५ । तत्पर्याप्तानां—गु १ मि, जी ७ प, प ६, ५, ४, प्रा १०, ९, ८, ७, ६, ४, सं ४, ग ३ न ति म, इं ५, का ६, यो १० म ४ व ४ औ वै, वे ३, क ४, ज्ञा ३ कु कु वि, सं १ अ, द २, ले ६ । भ २, स १ मि, सं २, आ १, उ ५ । तदपर्याप्तानां—गु १ मि, जी ७ अ, प ६, ५, ४ अ । प्रा ७, ७, ६, ५, ४, ३ अ, सं ४, ग ४ । इं ५, का ६, यो ३ औमि वैमि का,

यो १२। म ४। वा ४। औ २। वै का १। कार्म्मण १। कृष्णलेश्यासंयतसम्यग्दृष्टि भवनत्रयदो
पुट्टनप्पुदरिदं वैक्रियिकमिश्रमिल्ल। अथवा घम्मेयं बिट्टु मिक्क नरकंगळोळ् पुट्टनप्पुदरिनं
वैक्रियिकमिश्रमिल्ल। घम्मेयोळ्पुट्टुवडं कपोतलेश्याजघन्यांशविवमल्लदे कृष्णलेश्ययिदं पुट
संभावनेयिल्लप्पुदरिदमंतु वैक्रियिकमिश्रयोगं संभविसदु। वे ३। क ४। ज्ञा ३। म। श्रु। अ।
सं १। अ। द ३। च। अ। अ। ले ६। भ १। सं ३। उ। वे। क्षा। सं १। आ २। उ
भा १ कृ

कृष्णलेश्यासंयतसम्यग्दृष्टिपर्य्याप्तकर्गे। गु १। असं। जो १। प। प ६। प्रा १०
सं ४। ग ३। न। ति। म। इं १। पं। का १ त्र। यो १०। म ४। वा ४। औ का। वै।
क ४। ज्ञा ३। म श्रु। अ। सं १। अ। द ३ च। अ। अ। ले ६। भ १। सं ३। उ। वे। क्षा।
भा १ कृ
सं १। आ १। उ ६॥

कृष्णलेश्यासंयतापर्य्याप्तकर्गे। गु १। असं। जी १। अ। प ६। अ। प्रा ७। अ
सं ४। ग १। म। इं १। पं। का १ त्र। यो २। औ मि। का १। वे १। पुं। क ४। ज्ञा ३
म। श्रु। अ। सं १। अ ०। द ३। च। अ। अ। ले २ क शु। भ १। सं १। वेदक। सं १।
भा १ कृ
आ २। उ ६॥

नीललेश्येगे कृष्णलेश्येयोळ्पेळ्दंते पेळ्दु कोळ्गे। विशेषमावुदेंदोडे सर्व्वत्र नीललेश्येयु
पवतव्यमक्कुं। कपोतलेश्याजीवंगळ्गे। गु ४। मि। सा। मि। अ। जी १४। प ६। ६। ५। ५।
४। ४। प्रा १०। ७। ९। ७। ८। ६। ७। ५। ६। ४। ४। ३। सं ४। ग ४। इं ५। का ६।
यो १३। म ४। व ४। औ २। वै २। का १। वे ३। क ४। ज्ञा ६। कु। कु। वि। म। श्रु।
अ। सं १। अ। द ३। च। अ। अ। ले ६। भ २। सं ६। मि। सा। मि। उ। वे। क्षा।
भा १ कृ
सं २। आ २। उ ९॥

यो १२ म ४ व ४ औ २ वै १ का १ तेषां सम्यग्दृष्टित्वात् भवनत्रयद्वितीयादिपृथ्वीष्वनुत्पत्तेः। घर्मोत्पन्नाना
मु कपोतलेश्या जघन्यांशित्वाद्वैक्रियिक मिश्रयोगो नहि। वे ३, क ४, ज्ञा ३ म श्रु अ, सं १ अ, द ३ च
अ अ, ले ६। भ १, स ३ उ वे क्षा, सं १, आ २, उ ६। तत्पर्याप्तानां—गु १ असं, जी १ प, प ६,
भा १ कृ
प्रा १०, सं ४, ग ३ न ति म, इं १ पं, का १ त्र, यो १० म ४ व ४ औ वै, वे १, क ४, ज्ञा ३ म श्रु अ,
सं १ अ, द ३ च अ अ, ले ६, भ १, स ३ उ वे क्षा, सं १, आ १, उ ६। तदपर्याप्तानां—गु १ असं, जी
भा १ कृ
१ अ, प ६ अ, प्रा ७ अ, सं ४, ग १ म, इं १ पं। का १ त्र, यो २ औमि का, वे १ पुं, क ४, ज्ञा ३ म श्रु
अ, सं १ अ, द ३, ले २ क शु। भ १, स १ वे, सं १, आ २, उ ६। नीललेश्यानां कृष्णलेश्यावद्वक्तव्यं।
भा १ कृ
कपोतलेश्यानां—गु ४ मि सा मि अ, जी १४, प ६, ६, ५, ५, ४, ४, प्रा १०, ७, ९, ७, ८, ६,
७, ५, ६, ४, ४, ३, सं ४, ग ४, इं ५, का ६, यो १३ म ४ व ४ औ २ वै २ का १, वे ३, क ४, ज्ञा ६
कु कु वि म श्रु अ, सं १ अ, द ३ च अ अ, ले ६। भ २, सं ६ मि सा मि उ वे क्षा, सं २, आ २, उ ९।
भा १ क

कपोतलेश्यामिथ्यादृष्टयपर्य्याप्तकर्गे । गु १ मि । जी ७ । अ । प ६ । ५ । ४ । अ । प्रा ७ । ७ । ६ । ५ । ४ । ३ । सं ४ । ग ४ । इं ५ । का ६ । यो ३ । औ मि । वै मि । का । वे ३ । क ४ । ज्ञा २ । कु । कु । सं १ । अ । द २ । ले २ । क शु । भ २ । स १ । मि । सं २ । आ २ । उ ४ ॥ भा १ क

कपोतलेश्यासासादनसम्यग्दृष्टिगळ्गे । गु १ । सा सा । जी २ । प अ । प ६ । ६ । प्रा १० । ७ । सं ४ । ग ४ । इं १ । पं । का १ त्र । यो १३ । वे ३ । क ४ । ज्ञा ३ । कु । कु । वि । सं १ । अ । द २ । च । अ । ले ६ । भ १ । सं १ । सा । सं १ । आ २ । उ ५ ॥ भा १ क

कपोतलेश्यासासादनपर्य्याप्तकर्गे । गु १ । सा । जी १ । प । प ६ । प्रा १० । सं ४ । ग ३ । न । ति । म । इं १ । पं । का १ त्र । यो १० । म ४ । या ४ । औ का । वै का । वे ३ । क ४ । ज्ञा ३ । कु । कु । वि । सं १ । अ । द २ । च । अ । ले ६ । भ १ । सं १ । सा । सं १ । आ १ । उ ५ ॥ भा १ क

कपोतलेश्यासासादनापर्य्याप्तकर्गे । गु १ । सा । जी १ । अ । प । ६ । अ । प्रा ७ । अ । सं ४ । ग ३ । ति । म । दे । इं । पं । का १ त्र । यो ३ । औ मि । वै मि । का । वे ३ । क ४ । ज्ञा २ । कु । कु । सं १ । अ । द २ । च । अ । ले २ क शु । भ १ । सं १ । सासादनरुचि । सं १ । आ २ । उ ४ ॥ भा १ क

कपोतलेश्यासम्यग्मिथ्यादृष्टिगळ्गे । गु १ । मिश्र । जी १ । प । प ६ । प्रा १० । सं ४ । ग ३ । न । ति । म । देवगतियोळशुभलेश्ये पर्य्याप्तकंगे संभविसदु । इं १ । पं । का १ त्र । यो १० । म ४ । वा ४ । औ का । वै का । वे ३ । क ४ । ज्ञा ३ । मिश्रज्ञानंगळु । सं १ । अ । द २ । ले ६ । भ १ । सं १ । मिश्र । सं १ । आ १ । उ ५ ॥ भा १ क

स १ मि, सं २, आ १, उ ५ । तदपर्याप्तानां—गु १ मि, जी ७ अ, प ६, ५, ४, अ, प्रा ७, ७, ६, ५, ४, ३, सं ४, ग ४, इं ५, का ६, यो ३ औमि वैमि का, वे ३, क ४, ज्ञा २ कु कु, सं १, सं १ अ, द २, ले २ क शु । भ २, स १ मि, सं २, आ २, उ ४ । तत्सासादनानां—गु १ सा, जी २ प अ, प ६, ६, प्रा १०, ७, सं ४, ग ४, इं १ पं, का १ त्र, यो १३, वे ३ क ४, ज्ञा ३, कु कु वि, सं १ अ, द २ च अ, ले ६ । भा १ क भ १, स १ सा, सं १, आ २, उ ५ । तत्पर्याप्तानां—गु १ सा, जी १ प, प ६, प्रा १०, सं ४, ग ३ न ति म, इं १ पं, का १ त्र, यो १० म ४ व ४ औ वै, वे ३, क ४, ज्ञा ३ कु कु वि, सं १ अ, द २ च अ, ले ६, भ १, स १ सा, सं १, आ १, उ ५ । तदपर्याप्तानां—गु १ सा, जी १ अ, प ६ अ, प्रा ७ अ, सं ४, ग ३ ति म दे, इं १ पं, का १ त्र, यो ३ औमि वैमि का, वे ३, क ४, ज्ञा २ कु कु, सं १ अ, द २ च अ, ले २ क शु, भ १, स १ सा, सं १, आ २, उ ४ । सम्यग्मिथ्यादृशां—गु १ मिश्रं, जी १ प, प ६, प्रा १०, सं ४, ग ३ न ति म, देवगतिर्नहि, इं १ पं, का १ त्र, यो १० म ४ व ४ औ वै, वे ३,

तेजोलेश्याऽपर्य्याप्तकर्म्मे । गु ४ । मि । सा । अ । प्र । जो १ । अ । प ६ । अ । प्रा ७ । अ । सं ४ । ग २ । म । दे । इं १ पं । का १ त्र । यो ४ । ओ मि । वैमि आमि । का । वे २ । स्त्री । पुं । क ४ । ज्ञा ५ । कु । कु । म । श्रु । अ । सं ३ । अ । सा । छे । द ३ । ले ६ क शु । भ २ । सं ५ । मि । सा । उ । वे । क्षा । सं १ । आ २ । उ ८ ॥
भा १ ते

तेजोलेश्यामिथ्यादृष्टिगळ्गे । गु १ । मि । जो २ । प । अ । प ६ । ६ । प्रा १० । ७ । सं ४ । ग ३ । ति । म । दे । इं १ । पं । का १ त्र । यो १२ । म ४ । वा ४ । औ का । वै का । वै मि । कार्म्मण । वे ३ । क ४ । ज्ञा ३ । कु । कु । वि । सं १ । अ । द २ । ले ६ भ २ । सं १ । मि । सं १ । आ २ । उ ५ ॥
भा १ ते

तेजोलेश्यामिथ्यादृष्टिपर्य्याप्तकरगें । गु १ । मि । जो १ । प । प ६ । प्रा १० । सं ४ । ग ३ । ति । म । दे । इं १ पं । का १ त्र । यो १० । म ४ । वा ४ । औ का । वै का । वे ३ । क ४ । ज्ञा ३ । कु । कु वि । सं १ । द २ । ले ६ । भ २ । सं मि । सं १ । आ १ । उ ५ ॥
भा १ ते

तेजोलेश्यामिथ्यादृष्टि अपर्य्याप्तकर्म्मे । गु १ । मि । जो १ । अ । प ६ । अ । प्रा ७ । अ । सं ४ । ग १ दे । इं १ । पं । का १ त्र । यो २ । वै मि । का । वे २ । स्त्री । पुं । क ४ । ज्ञा २ । कु । कु । सं १ । अ द २ । ले २ क शु । भ २ । सं १ मि । सं १ । आ २ । उ ४ ॥
भा १ ते

तेजोलेश्यासासादनसम्यग्दृष्टिगळ्गे । गु १ । सासा । जो २ । प । अ । प ६ । ६ । प्रा १० । ७ । सं ४ । ग ३ । ति म दे । इं १ । पं । का १ त्र । यो १२ । म ४ । वा ४ । औ का १ । वे २ ।

इं १ पं, का १ त्र, यो ११ म ४ व ४ औ वै आ, वे ३, क ४, ज्ञा ७ केवलं नहि, सं ५ अ दे सा छे प, द ३ । ले ६ । भ २, स ६, सं १, आ १, उ १० । तदपर्याप्ताना—गु ४ । मि सा अ प्र, जो १ अ, प ६ अ,
भा १ ते
प्रा ७ अ, सं ४, ग २ म दे, इं १ पं, का १ त्र, यो ४ औमि वैमि आमि का, वे २ स्त्री पुं, क ४, ज्ञा ५ कु कु म श्रु अ, सं ३ अ सा छे, द ३, ले २ क शु, भ २, स ५ मि सा उ वे क्षा, सं १, आ २, उ ८ ।
भा १ ते
तन्मिथ्यादृशा—गु १ मि, जो २ प, अ, प ६ ६, प्रा १० ७, सं ४, ग ३ ति म दे, इं १ पं, का १ त्र, यो १२ म ४ व ४ औ वै वैमि का, वे ३, क ४, ज्ञा ३ कु कु वि, सं १ अ, द २, ले ६ । भ २, स १ मि,
भा १ ते
सं १, आ २, उ ५ । तत्पर्याप्तानां— गु १ मि, जो १ प, प ६, प्रा १०, सं ४, ग ३ ति म दे, इं १ पं, का १ त्र, यो १० म ४ व ४ औ वै, वे ३, क ४, ज्ञा ३ कु कु वि, सं १ अ, द २, ले ६ । भ २ । स १
भा १ ते
मि । सं १ । आ १ । उ ५ । तदपर्याप्तानां—गु १ मि । जो १ अ । प ६ अ । प्रा ७ अ । सं ४ । ग १ दे । इं १ पं । का १ त्र । यो २ वैमि का । वे २ स्त्री पुं । क ४ । ज्ञा २ कु कु । सं १ अ । द २ । ले २ क शु । भ २ । स १ मि । सं १ । आ २ । उ ४ । सासादनानां—गु १ सा । जो २ प अ । प ६ ६ ।
भा १ ते

ति। म। दे। इं १। का १। यो १०। म ४। या ४॥ औ का। वै का। वे ३। क ४। ज्ञा ३। सं १। अ। द ३। ले ६ । भ १। सं ३। सं १। आ १। उ ६॥
भा १ ते

तेजोलेश्याअपर्य्याप्तासंयतग्गें। गु १। अ। जी १। अ। प ६। अ। प्रा ७। अ। सं ४। ग २। म। दे। इं १। का १। यो ३। औ मि। वै मि। का। वे १। पुं। क ४। ज्ञा ३। सं १। अ। द ३। ले २। भ १। सं ३। सं १। आ २। उ ६॥
भा १ ते

तेजोलेश्यादेशयतिगळ्गें। गु १। दे। जी १। प। प ६। प्रा १०। सं ४। ग २। ति। म। इं १। का १। यो ९। म ४। वा ४। औ का। वे ३। क ४। ज्ञा ३। म। श्रु। अ। सं १। दे। द ३। ले ६। भ १। सं ३। सं १। आ १। उ ६॥
भा १ ते

तेजोलेश्या-प्रमत्तग्गें। गु १ प्र। जी २। प। अ। प ६। ६। प्रा १०। ७। सं ४। ग १। म। इं १। का १। यो ११। वे ३। क ४। ज्ञा ४। सं ३। सा। छे। प। द ३। ले ६। भ १।
भा १ ते
सं ३। सं १। आ १। उ ७॥

तेजोलेश्याऽप्रमत्तग्गें। गु १। अ प्र। जी १। प। प ६। प्रा १०। सं ३। ग १। म। इं १। का १। यो ९। वे ३। क ४। ज्ञा ४। म। श्रु। अ। म। सं ३। सा। छे। प। द ३। ले ६ । भ १। सं ३। सं १। आ १। उ ७॥
भा १ ते

१०। सं ४। ग ३ ति म दे। इं १। का १। यो १० म ४ व ४ औ वै। वे ३। क ४। ज्ञा ३। सं १ अ। द ३। ले ६। भ १। स ३। सं १। आ १। उ ६।
भा १ ते

तदपर्याप्तानां—गु १ अ। जी १ अ। प ६ अ। प्रा ७ अ। सं ४। ग २ म दे। इं १। का १। यो ३ औमि वैमि का। वे १ पुं। क ४। ज्ञा ३। सं १ अ। द ३। ले २। भ १। स ३। सं १।
भा १ ते
आ २। उ ६। देशव्रतिनां—गु १ दे। जी १ प। प ६। प्रा १०। सं ४। ग २ ति म। इं १। का १। यो ९ म ४ व ४ औ। वे ३। क ४। ज्ञा ३ म श्रु अ। सं १ दे। द ३। ले ६। भ १। स ३। सं १।
भा १ ते
आ १। उ ६। प्रमत्तानां—गु १ प्र। जी २ प अ। प ६। ६। प्रा १०। ७। सं ४। ग १ म। इं १। का १। यो ११। वे ३। क ४। ज्ञा ४। सं ३ सा छे प। द ३। ले ६। भ १। स ३। सं १। आ १।
भा १ ते
उ ७। अप्रमत्तानां—गु १ अ प्र। जी १ प। प ६। प्रा १०। सं ३। ग १ म। इं १। का १। यो ९। वे ३। क ४। ज्ञा ४ म श्रु अ म। सं ३ सा छे प। द ३। ले ६। भ १। स ३। सं १।
भा १ ते

पद्मलेश्यामिथ्यादृष्टयपर्याप्तकानां । गु १ । मि । जो १ । अ । प ६ । अ । प्रा ७ । अ । सं ४ । ग १ । दे । इं १ । का १ । यो २ । वै मि । का । वे १ । पुं । क ४ । ज्ञा २ । कु । कु । सं १ । अ । द २ । ले २ क शु । भ २ । स १ । मि । सं १ । आ २ । उ ४ ॥
भा १ प

पद्मलेश्यासासादनानां । गु १ । सासा । जो २ । प । अ । प ६ । ६ । प्रा १० । ७ । सं ४ । ग ३ । ति । म । दे । इं १ । का १ । यो १२ । म ४ । वा ४ । औ का १ । वै का २ । का १ । वे ३ । क ४ । ज्ञा ३ । कु । कु । वि । सं १ । अ । द २ । ले ६ । भ १ । सं १ । सा । सं १ । आ २ । उ ५ ॥
भा १ प

पद्मलेश्यासासादनपर्याप्तकानां । गु १ । सा । जो १ । प । प ६ । ६ । प्रा १० । सं ४ । ग ३ । ति । म । दे । इं १ । का १ । यो १० । म ४ । वा ४ । औ का १ । वै का १ । वे ३ । क ४ । ज्ञा ३ । कु । कु । वि । सं १ अ । द २ । । ले ६ । भ १ । सं १ । सासा । सं १ । आ १ । उ ५ ॥
भा १ प

पद्मलेश्यासासादनाऽपर्य्याप्तकानां । गु १ । सा । जो १ । अ । प ६ । अ । प्रा ७ । अ । सं ४ । ग १ । दे । इं १ । का १ । यो २ । वैमि । का । वे १ । पुं । क ४ । ज्ञा २ । कु । कु । सं १ । अ । द २ । ले २ क शु । भ १ । सं १ । सं १ । आ २ । उ ४ ॥
भा १ प

पद्मलेश्यासम्यग्मिथ्यादृष्टिनां । गु १ । मिश्र । जो १ । प । प ६ । प्रा १० । सं ४ । ग ३ । ति । म । दे । इं १ । का १ । यो १० । वे ३ । क ४ । ज्ञा ३ । मिश्र । सं १ । अ । द २ । ले ६ । भ १ । सं १ । मिश्ररुचि । सं १ । आ १ । उ ५ ॥
भा १ प

ज्ञा ३ कु कु वि । सं १ अ । द २ । ले ६ । भ २ । स १ मि । सं १ । आ १ । उ ५ । तदपर्याप्तानां-
भा १ प
मि । जी १ अ । प ६ अ । प्रा ७ अ । सं ४ । ग १ दे । इं १ पं । का १ त्र । यो २ वैमि का । वे
क ४ । ज्ञा २ कु कु । सं १ अ । द २ । ले २ क शु । भ २ । स १ मि । सं १ । आ २ ।
भा १ प
तत्सासादनानां—गु १ सा । जी २ प अ । प ६ ६ । प्रा १० ७ । सं ४ । ग ३ ति म दे । इं १ ।
यो १२ म ४ व ४ औ १ वै २ का १ । वे ३ । क ४ । ज्ञा ३ कु कु वि । सं १ अ । द २ । ले ६
भा १
स १ सा । सं १ अ । आ २ । उ ५ । तत्पर्याप्तानां—गु १ सा । जी १ । प । प ६ । प्रा १
ग ३ ति म दे । इं १ । का १ । यो १० म ४ व ४ औ १ वै १ । वे ३ । क ४ । ज्ञा ३
सं १ अ । द २ । ले ६ । भ १ । स १ सा । सं १ । आ १ । उ ५ । तदपर्याप्तानां-
भा १ प
जी १ अ । प ६ अ । प्रा ७ अ । सं ४ । ग १ दे । इं १ । का १ । यो २ वैमि का । वे १
ज्ञा २ कु कु । सं १ अ । द २ । ले २ क शु । भ १ । स १ सा । सं १ । आ २ । उ ४ । सम्य
भा १ प
गु १ मिश्रं । जी १ । प ६, प्रा १० । सं ४ । ग ३ ति म दे । इं १ । का १ । यो १० । वे ३ ।

पद्मलेश्येय अप्रमत्तग्गे । गु १ । अ प्र । जो १ । प ६ । प्रा १० । सं ३ । गति १ । म । इं १ । पं । का १ । त्र । यो ९ । म ४ । या ४ । ओ का १ । वे ३ । क ४ । ज्ञा ४ । म । श्रु । अ । म । सं ३ । सा । छे । प । द ३ । ले ६ । भ १ । सं ३ । उ । वे । क्षा । सं १ । आ १ । उ ७ ॥
भा १ प

शुक्ललेश्याजीवंगळ्गे । गु १३ । जो २ । प । अ । प ६ । ६ । प्रा १० । ७ । ४ । २ । सं ४ । ग ३ । ति । म । दे । इं १ । का १ । यो १५ । वे ३ । क ४ । ज्ञा ८ । सं ७ । द ४ । ले ६ । भ २ । सं ६ । सं १ । आ २ । उ १२ ॥
भा १ शु

शुक्ललेश्यापर्य्याप्तकग्गे । गु १३ । जो १ । प । प ६ । प्रा १० । ४ । सं ४ । ग ३ । ति । म । दे । इं १ । का १ । यो ११ । म ४ । या ४ । ओ का । वै का । आ का । वे ३ । क ४ । ज्ञा ८ । सं ७ द ४ । च । अ । अ । के । ले ६ । भ २ । सं ६ । सं १ । आ १ । उ १२ ॥
भा १ शु

शुक्ललेश्या अपर्य्याप्तकग्गे । गु ५ । मि । सा । अ । प्र । सयो । जो १ । अ । प ६ । अ । प्रा ७ । २ । सं ४ । ग २ । म । दे । इं । का १ । यो ४ । ओ मि । वै मि । का । आ । मि । वे १ । पुं । क ४ । ज्ञा ६ । सं ४ । अ । सा । छे । य । द ४ । ले २ क शु । भ २ । सं ५ । मि । सा । उ । वे । क्षा । सं १ । आ २ । उ १० ॥
भा १ शु

शुक्ललेश्यामिथ्यादृष्टिगळ्गे । गु १ । मि । जो २ । प । अ । प ६ । ६ । प्रा १० । ७ । सं ४ । ग ३ । ति । म । दे । इं १ । का १ । यो १२ । म ४ । वा ४ । औ का १ । वै का २ । कार्म्म । का १ । वे ३ । क ४ । ज्ञा ३ । कु । कु । वि । सं १ । अ । द २ । ले ६ । भ २ । सं १ । मि । सं १ । आ २ । उ ५ ॥
भा १ शु

सं १, आ १ । उ ७ । अप्रमत्ताना—गु १ अप्र, जी १ प, प ६ । प्रा १०, सं ३, ग १ म । इं १ पं । का १ त्र । यो ९ म ४ व ४ औ १ । वे ३, क ४, ज्ञा ४ म श्रु अ म । सं ३ सा छे प । द ३ । ले ६ । भ १ । स ३ उ वे क्षा । सं १ । आ १ । उ ७ । शुक्ललेश्यानां—गु १३ । जी २ प अ । प ६ । ६ ।
भा १ प
प्रा १० । ७ । सयोग ४ । २ । सं ४ । ग ३ ति म दे, इं १ । का १ । यो १५ । वे ३ । क ४ । ज्ञा ८ । सं ७ । द ४, ले ६ । भ २ । स ६ । सं १, आ २, उ १२ । तत्पर्याप्तानां—गु १३ । जी १ प, प ६,
भा १ शु
प्रा १० ४, सं ४, ग ३ ति म दे, इं १, का १, यो ११ म ४ व ४ औ १ वै १, आ १ । वे ३, क ४, ज्ञा ८ । सं ७, द ४ च अ अ के, ले ६ । भ २, स ६, सं १ । आ १, उ १२ । तदपर्याप्तानां—गु ५, मि सा अ प्र स,
भा १ शु
जी १ अ, प ६ अ, प्रा ७, २, सं ४, ग २ म दे, इं १, का १ यो ४ औमि वैमि आमि का, वे १ पुं, क ४, ज्ञा ६, सं ४ अ सा छे य, द ४ ले २ क शु । भ २, स ५ मि सा उ वे क्षा, सं १, आ २, उ १० ।
भा १ शु
तन्मिथ्यादृशां—गु १ मि, जी २ प अ, प ६ ६, प्रा १०, ७, सं ४, ग ३ ति म दे, इं १, का १, यो १२ म ४ व ४ औ १ वै २ का १, वे ३, क ४, ज्ञा ३ कु कु वि, सं १ अ, द २, ले ६, भ २, स १ मि, सं १,
भा १ शु

शुक्ललेश्यासम्यग्मिथ्यादृष्टिरचना। गु १ मिश्र। जी १। प। प ६। प्रा १०। सं ४। ग ३। ति। म। दे। इं १। का १। यो १०। म ४। व ४। औ का १। वै का १। वे ३। क ४। ज्ञा ३। मिश्र। सं १। अ। द २। ले ६ भा १ शु। भ १। सं १। मिश्र। सं १। आ १। उ ५॥

शुक्ललेश्याऽसंयतसम्यग्दृष्टिरचना। गु १। असं। जी २। प। अ। प ६। ६। प्रा १०। ७। सं ४। ग ३। ति। म। दे। इं १। का १। यो १३। आहारद्वयवर्जित। वे ३। क ४। ज्ञा ३। म। श्रु। अ। सं १। अ। द ३। ले ६ भा १ शु। भ १। सं ३। उ। वे। क्षा। सं १। आ २। उ ६॥

शुक्ललेश्याऽसंयतसम्यग्दृष्टिपर्याप्तरचना। गु १। असं। जी १। प। प ६। प्रा १०। सं ४। ग ३। ति। म। दे। इं १। का १। यो १०। म ४। व ४। औ का १। वै का १। वे ३। क ४। ज्ञा ३। म। श्रु। अ। सं १। अ। द ३। ले ६ भा १ शु। भ १। सं ३। सं १। आ १। उ ६॥

शुक्ललेश्याऽसंयतसम्यग्दृष्ट्यपर्याप्तरचना। गु १। असं। जी १। अ। प ६। अ। प्रा ७। सं ४। ग २। म। दे। इं १। का १। यो ३। औ मि। वै मि। का। वे १। पुं। क ४। ज्ञा ३। म। श्रु। अ। सं १। अ। द ३। ले २ क शु भा १ शु। भ १। सं ३। उ। वे। क्षा। सं १। आ २। उ ६॥

शुक्ललेश्यादेशव्रतिरचना। गु १। देश। जी। १। प ६। प्रा १०। सं ४। ग २। ति। म। इं १। का १। यो ९। वे ३। क ४। ज्ञा ३। म। श्रु। अ। सं १। देश। द ३। ले ६ भा १ शु। भ १। सं ३। सं १। आ १। उ ६॥

भ १, स १ सा। सं १। आ २। उ ४। सम्यग्मिथ्यादृष्टीनां—गु १ मिश्रं। जी १ प। प ६। प्रा १०। सं ४। ग ३ ति म दे। इं १। का १, यो १० म ४ व ४ औ वै। वे ३, क ४, ज्ञा ३ मिश्राणि। सं १ अ। द २। ले ६ भा १ शु। भ १, स १ मिश्रं। सं १। आ १। उ ५। असंयतानां—गु १ अ। जी २ प। अ। प ६। ६। प्रा १०। ७। सं ४, ग ३ ति म दे। इं १, का १। यो १३ आहारद्वयाभावात्। वे ३। क ४। ज्ञा ३ म श्रु अ। सं १ अ। द ३, ले ६ भा १ शु। भ १। स ३ उ वे क्षा। सं १। आ २। उ ६। तत्पर्याप्तानां—गु १ अ। जी १ प। प ६। प्रा १०। सं ४। ग ३ ति म दे। इं १। का १। यो १० म ४ व ४ औ वै। वे ३। क ४। ज्ञा ३ म श्रु अ। सं १ अ। द ३। ले ६ भा १ शु। भ १। स ३। सं १। आ १। उ ६। तदपर्याप्तानां—गु १ अ। जी १ अ। प ६ अ। प्रा ७ अ। सं ४। ग २ म दे। इं १। का १। यो ३ औमि वैमि का। वे १ पुं। क ४। ज्ञा ३ म श्रु अ। सं १ अ। द ३। ले २ क। शु भा १ शु। भ १। स ३ उ वे क्षा। सं १। आ २। उ ६। देशव्रतानां—गु १ दे। जी १ प। प ६। प्रा १०। सं ४। ग २ ति म, इं १ पं। का १ त्र। यो ९। वे ३। क ४। ज्ञा ३ म श्रु अ।

अभव्यापर्य्याप्तकग्गें । गु १ । मि । जी ७ । अ । प ६ । ५ । ४ । प्रा ७ । ७ । ६ । ५ । ४ । ३ । अ । सं ४ । ग ४ इं ५ । का ६ । यो ३ । औ मि । वै मि । का । वे ३ । क ४ । ज्ञा २ । सं १ । अ । द २ । ले २ क शु । भ १ । अभव्य । सं १ । मि । सं २ । आ २ । उ ४ ॥
भा ६

भव्यरुमभव्यरुमल्लव सिद्धपरमेष्ठिगळ्गे गुणस्थानातीतर्गे मुं पेळ्दंतेयक्कुं । इंतु भव्यमार्गणे समाप्तमादुदु ॥

सम्यक्त्वानुवाददोळु सम्यग्दृष्टिगळ्गे । गु ११ । असंयतादि । जो २ । प । अ । प ६ । ६ । प्रा १० । ७ । सं ४ । ग ४ । इं १ । पं । का १ त्र । यो १५ । वे ३ । क ४ । ज्ञा ५ । म । श्रु । अ । म । के । सं ७ । द ४ । ले ६ । भ १ । सं ३ । उ । वे । क्षा । सं १ । आ २ । उ ९ ॥
भा ६

सम्यग्दृष्टिपर्य्याप्तकग्गें । गु १ । जी १ । प ६ । प्रा १० । ४ । १ । सं ४ । ग ४ । इं १ । का १ । यो ११ । म ४ । व ४ । औ का । वै का । आ का । वे ३ । क ४ । ज्ञा ५ । म । श्रु । अ । म । के । सं ७ । द ४ । ले ६ भ १ । सं ३ । उ वे । क्षा । सं १ । आ १ । उ ९ ॥
भा ६

सम्यग्दृष्टि अपर्य्याप्तकंगें । गु ३ । अ । प्र । सयो । जी १ । अ । प ६ । अ । प्रा ७ । अ २ । सं ४ । ग ४ । इं १ । पं । का १ त्र । यो ४ । औ मि । वै मि । आ मि । कार्म्मं । वे २ । न पुं । क ४ । ज्ञा ४ । म । श्रु । अ । के । सं ४ । अ । सा । छे । यथा । द ४ च । अ । अ के । ले २ शुक । भ १ । सं ३ । उ । वे । क्षा । सं १ । आ २ । उ ८ ॥
भा ४ क ते प शु

असंयतसम्यग्दृष्टिप्रभृति अयोगिकेवलिपर्य्यंतं मूलोघभंगमक्कुं ॥

उ ५ । तदपर्याप्तानां—गु १ मि । जी ७ अ । प ६ ५ ४ अ । प्रा ७ ७ ६ ५ ४ ३ अ । सं ४ । ग ४ । इं ५ । का ६ । यो ३ औमि वैमि का । वे ३ । क ४ । ज्ञा २ कु कु । सं १ अ । द २ । ले २ क शु । भ १ अ । स १ मि । सं २ । आ २ । उ ४ । भव्याभव्यलक्षणरहितसिद्धानां प्राग्वत् । भव्यमार्गणा गता ।
भा ६

सम्यक्त्वानुवादे सम्यग्दृष्टीनां—गु ११ असंयतादीनि । जी २ प अ । प ६ ६ । प्रा १० ७ ४ २ १ । सं ४, ग ४, इं १ पं, का १ त्र, यो १५ । वे ३, क ४, ज्ञा ५ म श्रु अ म के, सं ७, द ४ ले ६, भ १, स ३ उ वे क्षा, सं १, आ २, उ ९ । तत्पर्याप्तानां—गु ११, जी १, प ६ ४, प्रा १० ४ १, सं ४, ग ४, इं १, का १, यो ११ म ४ व ४ औ वै आ, वे ३ । क ४, ज्ञा ५ म श्रु अ म के, सं ७ । द ४, ले ६, भ १, स ३ उ वे क्षा । सं १ । आ २ । उ ९ । तदपर्याप्तानां—गु ३ अ प्र स । जी १ अ । प ६ अ । प्रा ७ अ । २ । सं ४ । ग ४ । इं १ पं । का १ त्र । यो ४ औमि वैमि आमि का । वे २ न पुं । क ४ । ज्ञा ४ म श्रु अ के । सं ४ अ सा छे य । द ४ च अ अ के । ले २ क शु । भ १ । स ३ उ वे क्षा । सं १ । आ २ । उ ८ । असंयतादयोगिपर्यंतं मूलोघभंगः ।
भा ६ भा ६ भा ४

अविरतसम्यग्दृष्टयपर्याप्तकानां । गु १ । अवं । जी १ । अ । प ६ । अ । प्रा ७ । अ । सं ४ । ग ४ । इं १ । पं । का १ त्र । यो ३ । औ मि । वै मि । का । वे २ । न । पुं । क ४ । ज्ञा ३ । म । श्रु । अ । सं १ । अ । द ३ । च । अ । अ । ले २ क शु । भ १ । सं ३ । सा । सं १ । आ २ । उ ६ ॥
भा ४ क ते प शु

अविरतसम्यग्दृष्टिदेशविरतानां । गु १ । देश । जी १ । प । प ६ । प्रा १० । सं ४ । ग १ । म । इं १ । पं । का १ त्र । यो ९ । म ४ । वा ४ । औ का १ । वे ३ । क ४ । ज्ञा ३ । म । श्रु । अ । सं १ । दे । द ३ । च । अ । अ । ले ६ । भ १ । सं ३ । सा । सं १ । आ १ । उ ६ ॥
भा ३

अविरतसम्यग्दृष्टिप्रमत्तप्रभृति सिद्धपर्यंतमोघभंगमक्कुं ॥

वेदकसम्यग्दृष्टिगळ्गे । गु ४ । अ । दे । प्र । अ । जी २ प । अ । प ६ । ६ । प्रा १० । ७ । सं ४ । ग ४ । इं १ । पं । का १ त्र । यो १५ । वे ३ । क ४ । ज्ञा ४ । म । श्रु । अ । म । सं ५ । अ । दे । सा । छे । प । द ३ । ले ६ भ १ । सं १ । वेदक । सं १ । आ २ । उ ७ ॥
भा ६

वेदकसम्यग्दृष्टिपर्य्याप्तकर्गो । गु ४ । अ । दे । प्र । अ । जी १ । प । प ६ । प्रा १० । सं ४ । ग ४ । इं १ । का १ । यो ११ । म ४ । वा ४ । औ १ । वै १ । का १ । वे ३ । क ४ । ज्ञा ४ । म । श्रु । अ । म । सं ५ । अ । दे । सा । छे । प । द ३ । ले ६ । भ १ । सं १ । वेदक । सं १ । आ १ । उ ७ ॥
भा ६

वेदकसम्यग्दृष्टि अपर्य्याप्तकर्गे । गु २ । असं । प्रम । जो १ अ । प ६ । अ । प्रा ७ । सं ४ । ग ४ । इं १ पं । का १ त्र । यो ४ । औ मि । वै मि । आ मि का । वे २ । न । पुं । क ४ । ज्ञा ३ । म श्रु अ । सं ३ अ । सा । छे । द ३ । ले ६ । भ १ । सं १ । वेदक । सं १ । आ २ । उ ६ ॥
भा ६

भ १ । स १ क्षा । सं १ । आ १ । उ ६ । तदपर्याप्तानां—गु १ अ । जी १ अ । प ६ अ । प्रा ७ अ । सं ४ । ग ४ । इं १ पं । का १ त्र । यो ३ औमि वैमि का । वे २ न पुं । क ४ । ज्ञा ३ म श्रु अ । सं १ अ । द ३ च अ अ । ले २ क शु । भ १ । स १ क्षा । सं १ । आ २ । उ ६ । तद्देशव्रतानां—
भा ४ क ते प शु
गु १ दे । जी १ प । प ६ । प्रा १० । सं ४ । ग २ म । इं १ पं । का १ त्र । यो ९ म ४ । व ४ । औ । वे ३ । क ४ । ज्ञा ३ म श्रु अ । सं १ दे । द ३ च अ अ । ले ६ । भ १ । स १ क्षा । सं १ । आ १ । उ ६ । प्रमत्तादिक्षीणकषायांतं ओघभंगो भवति ।
भा ३

वेदकसम्यग्दृष्टीनां—गु ४ अ दे प्र अ । जी २ । प ६ ६ । प्रा १० ७ । सं ४ । ग ४ । इं १ पं । का १ त्र । यो १५ । वे ३ । क ४ । ज्ञा ४ म श्रु अ म । सं ५ अ दे सा छे प । द ३ । ले ६ । भ १ । स १ वे । सं १ । आ २ । उ ७ । तत्पर्याप्तानां—गु ४ अ दे प्र अ । जो १ प, प ६, प्रा १०, सं ४, ग ४, इं १, यो ११ म ४ व ४ औ १ वै १, आ १, वे ३, क ४, आ ४ म श्रु अ म, सं ५ अ दे सा छे प, द ३, ले ६, भ १, स १ वे, सं १, आ १, उ ७ । तदपर्याप्तानां—गु २ अ प्र, जी १ अ, प ६, प्रा ७,
६

येदकसम्यग्दृष्ट्यप्रमत्तसंयतर्गे । गु १ । अप्र । जी १ । प ६ । प्रा १० । सं ३ ।
ग १ म । इं १ पं । का १ त्र । यो ९ । वे ३ । क ४ । ज्ञा ४ । सं ३ । सा । छे । प । द ३ ।
ले ६ । भ १ । सं १ । ये । सं १ । आ १ । उ ७ ॥
भा ३

उपशमसम्यग्दृष्टिगळ्गे । गु ८ । जी २ । प । अ । प ६ । ६ । प्रा १० । ७ । सं ४ । ग ४ ।
इं १ । का १ । यो १२ । म ४ । वा ४ । औ का १ । वै २ । का १ । वे ३ । क ४ । ज्ञा ४ ।
सं ६ । अ । दे । सा । छे । सू । य । द ३ । ले ६ । भ १ । सं १ उ । सं १ । आ २ । उ ७ ॥
भा ६

उपशमसम्यग्दृष्टिपर्य्याप्तकर्गे । गु ८ । अ । दे । प्र । अ । अ । सू । उ । जी १ । प ६ ।
प्रा १० । सं ४ । ग ४ । इं १ । का १ । यो १० । म ४ । व ४ । औ का १ । वै का १ । वे ३ ।
क ४ । ज्ञा ४ । म । श्रु । अ । म । स ६ । अ । दे । सा । छे । सू । य । द ३ । ले ६ । भ १ ।
भा ६
सं १ । उ । सं १ । आ १ । उ ७ ॥

उपशमसम्यग्दृष्ट्यपर्य्याप्तकर्गे । गु १ । असंयत । जी १ । अ । प ६ । अ । प्रा ७ ।
सं ४ । ग १ । दे । इं १ । का १ । यो २ । वै मि । का । वे १ । पुं । क ४ । ज्ञा ३ । सं १ । अ ।
द ३ । ले २ क शु । भ १ । सं १ । उ । सं १ । आ २ । उ ६ ॥
भा ३ शुभ

उपशमसम्यग्दृष्ट्यसंयतर्गे । गु १ । असंयत । जी २ । प । अ । प ६ । ६ । प्रा १० ।
७ । सं ४ । ग ४ । इं १ । का १ । यो १२ । म ४ । वा ४ । औ का १ । वै २ । का १ । वे ३ ।
क ४ । ज्ञा ३ । म श्रु । अ । सं १ । अ । द ३ । ले ६ । भ १ । सं १ । उ । सं १ । आ २ । उ ६ ॥
भा ६

द ३, ले ६/३, भ १, स १ वे, सं १, आ १, उ ७ । अप्रमत्तानां—गु १ अ, जी १, प ६, प्रा १०, सं ३, ग १ म, इं १ पं, का १ त्र, यो ९, वे ३, क ४, ज्ञा ४, सं ३ सा छे प, द ३, ले ६/३ । भ १, स १ वे, सं १, आ १, उ ७ । उपशमसम्यग्दृष्टीनां—गु ८, जी २ प अ, प ६ ६, प्रा १० ७, सं ४, ग ४, इं १ । का १ त्र । यो १२ म ४ व ४ औ १ वै २ का १ । वे ३ । क ४ । ज्ञा ४ । सं ६ अ दे सा छे सू य । द ३ । ले ६/६ । भ १ । स १ उ । सं १ । आ २ । उ ७ । तत्पर्याप्तानां—गु ८ अ दे प्र अ अ अ सू उ । जी १ । प ६ । प्रा १० । सं ४ । ग ४ । इं १ । का १ । यो १० म ४ व ४ औ वै । वे ३ । क ४ । ज्ञा ४ म श्रु अ म । सं ६ अ दे सा छे सू य । द ३ । ले ६/६ । भ १ । स १ उ । सं १ । आ १ । उ ७ । तदपर्याप्तानां—गु १ अ । जी १ अ । प ६ अ । प्रा ७ । सं ४ । ग १ दे । इं १ । का १ । यो २ वै मि का । वे १ पु । क ४ । ज्ञा ३ । सं १ अ । द ३ । ले २ क शु/भा ३ शु । भ १ । स १ उ । सं १ । आ १ । उ ६ । असंयतानां—गु १ अ । जी २ । प ६ ६ । प्रा १० ७ । सं ४ । ग ४ । इं १ । का १ । यो १२ म ४ व ४ औ १ वै २ का १ । वे ३ । क ४ । ज्ञा ३ म श्रु अ । द ३ । ले ६/६ । भ १ । स १ उ । सं १ । आ २ । उ ६ ।

संज्ञानुवादेनोच्यते । संज्ञिगळ्गे । गु १२ । जो २ । प । अ । प ६ । ६ । प्रा १० । ७ । सं । ४ ग ४ । इं १ । का १ । यो १५ । । वे ३ । क ४ । ज्ञा ७ । सं ७ । द ३ । ले ६ । भ २ ।
भा ६
सं ६ । सं १ । आ २ । उ १० ॥

संज्ञिपर्य्याप्तकर्ग्गे । गु १२ । जो १ । प ६ । प्रा १० । सं ४ । ग ४ । इं १ । का १ । यो ११ । म ४ । वा ४ । औ का १ । वै का १ । आ का १ । वे ३ । क ४ । ज्ञा ७ । सं ७ । द ३ । ले ६ । भ २ । सं ६ । सं १ । आ १ । उ १० ॥
भा ६

संज्ञ्यपर्य्याप्तकर्ग्गे । गु ४ । मि । सा । अ । प्र । जो १ । अ । प ६ । अ । प्रा ७ । सं ४ । ग ४ । इं १ । का १ । यो ४ । औ मि १ । वै मि १ । आ मि १ । का १ । वे ३ । क ४ । ज्ञा ५ । कु । कु । म । श्रु । अ । सं ३ । अ । सा । छे । द ३ । ले २ क शु । भ २ । सं ५ । मि । सा । उ ।
भा ६
वे । क्षा । सं १ । आ २ । उ ८ ॥

संज्ञिमिथ्यादृष्टिगळ्गे । गु १ । मि । जो २ । प । अ । प ६ । ६ । प्रा १० । ७ । सं ४ । ग ४ । इं १ । पं । का १ त्र । यो १३ । आहारद्वयरहित । वे ३ । क ४ । ज्ञा ३ । कु । कु । वि । सं १ । अ । द २ । ले ६ । भ २ । सं १ मि । सं १ । आ २ । उ ५ ॥
भा ६

संज्ञिमिथ्यादृष्टिपर्य्याप्तकर्ग्गे गु १ । मि । जो १ । प ६ । प्रा १० । स ४ । ग ४ । इं १ । का १ । यो १० । म ४ । वा ४ । औ का १ । वै का १ । वे ३ । क ४ । ज्ञा ३ । कु । कु । वि । सं १ । अ । द २ । ले ६ । भ २ । सं १ । मि । सं । आ १ । उ ५ ॥
६

संज्ञ्यनुवादे संज्ञिनां—गु १२ । जी २ प अ । प ६ ६ । प्रा १० ७ । सं ४ । ग ४ । इं १ । का १ । यो १५ । वे ३ । क ४ । ज्ञा ७ । सं ७ । द ३ । ले ६ । भ २ । स ६ । सं १ । आ २ । उ १० ।
६
तत्पर्याप्तानां—गु १२ । जी १ । प ६ । प्रा १० । सं ४ । ग ४ । इं १ । का १ । यो ११ म ४ व ४ औ वै आ । वे ३ । क ४ । ज्ञा ७ । सं ७ । द ३ । ले ६ । भ २ । स ६ । सं १ । आ १ । उ १० । तदपर्याप्तानां—
६
गु ४ मि सा अ प्र । जी १ अ । प ६ अ । प्रा ७ अ । सं ४ । ग ४ । इं १ । का १ । यो ४ औमि वैमि आमि का । वे ३ । क ४ । ज्ञा ५ कु कु म श्रु अ । सं ३ अ सा छे । द ३ । ले २ क शु । भ २ । स ५ मि
भा ६
सा उ वे क्षा । सं १ । आ २ । उ ८ । तन्मिथ्यादृशां—गु १ मि । जो २ प अ । प ६ ६ । प्रा १० । ७ । सं ४ । ग ४ । इं १ । का १ । यो १३ आहारद्वयाभावात् । वे ३ । क ४ । ज्ञा ३ कु कु वि । सं १ अ । द २ । ले ६ । भ २ । स १ मि । सं १ । आ २ । उ ५ । तत्पर्याप्तानां—गु १ मि । जी १ । प ६ ।
६
प्रा १० । सं ४ । ग ४ । इं १ । का १ । यो १० म ४ व ४ औ वै । वे ३ । क ४ । ज्ञा ३ कु कु वि ।

संज्ञ्यसंयतसम्यग्दृष्टिगळ्गे। गु १। असं। जी २। प। अ। प ६। ६। प्रा १०। ७। सं ४। ग ४। इं १। का १। यो १३। आहारद्वयरहित। वे ३। क ४। ज्ञा ३। म। श्रु। अ। सं १। अ। द ३। ले ६। भा ६। भ १। सं ३। सं १। आ २। उ ६॥

संज्ञिपर्य्याप्तासंयतसम्यग्दृष्टिगळ्गे। गु १। अ सं। जी १। प ६। प्रा १०। सं ४। ग ४। इं १। काय १। यो १०। म ४। वा ४। औ का। वै का। वे ३। क ४। ज्ञा ३। म। श्रु। अ। सं १। अ। द ३। ले ६ भा ६। भ १। सं ३। आ १। उ ६॥

संज्ञ्यपर्य्याप्तासंयतसम्यग्दृष्टिगळ्ग। गु १। असं। जी १। प ६। प्रा ७। सं ४। ग ४। इं १। का १। यो ३। औ मि। वै मि। कार्म्म। वे २। न पुं। क ४। ज्ञा ३। म। श्रु। अ। सं १। अ। द ३। ले २ क शु भा ६। भ १। सं ३। सं १। आ २। उ ६॥

संज्ञिदेशव्रतिप्रभृतिक्षीणकषायपर्य्यंतं मूलौघभंगमक्कुं।

असंज्ञिगळ्गे। गु १ मि। जी १२। संज्ञिद्वयरहित प ५। ५। ४। ४। प्रा ९। ७। ८। ६। ७। ५। ६। ४। ४। ३। सं ४। ग १ ति। इं ५। का ६। यो ४। औ २। का १। अनुभयवाग्योग १। वे ३। क ४। ज्ञा २। कु। कु। सं १। अ। द २। ले ६। भा ४ अशुभ। ते भ २। सं १। मि। सं १। आ २। उ ४॥

असंज्ञिपर्य्याप्तकंगे। गु १। मि। जी ६। अ। संज्ञ्यपर्य्याप्तरहित प ५। ४। प्रा ९। ८। ७। ६। ४। सं ४। ग १। ति। इं ५। का ६। यो २। औ का १। अनुभयवचन। वे ३। क ४। ज्ञा २। कु। कु। सं १। अ। द २। ले ६। भा ३। अशुभ। ते १ भ २। सं १। मि। सं १। असंज्ञित्वं। आ १। उ ४॥

द २। ले ६ भा ६। भ १। स १ मिथ्यं। सं १। आ १। उ ५। असंयतानां—गु १ अ। जी २ प अ। प ६। ६। प्रा १०। ७। सं ४। ग ४। इं १। का १। यो १३ आहारकद्वयाभावात्। वे ३। क ४। ज्ञा ३ म श्रु अ। सं १ अ। द ३। ले ६ भा ६। भ १। स ३। सं १। आ २। उ ६। तत्पर्याप्तानां—गु १ अ। जी १। प ६। प्रा १०। सं ४। ग ४। इं १। का १। यो १०। वे ३। क ४। ज्ञा ३ म श्रु अ। सं १ अ। द ३ च अ अ। ले ६ भा ६। भ १। स ३ उ वे क्षा। सं १। आ १। उ ६। तदपर्याप्तानां—गु १ अ। जी १ अ। प ६। प्रा ७ अ। सं ४। ग ४। इं १। का १। यो ३ औमि वैमि का क वे २ पुं। न। क ४। ज्ञा ३ म श्रु अ। सं १ अ। द ३ च अ अ। ले २ क शु भा ६। भ १। स ३। सं १। आ २। उ ६। देशव्रतात्क्षीणकषायपर्यंतं मूलौघभंगः।

असंज्ञिनां—गु १ मि। जो १२ संज्ञिपर्याप्तापर्याप्तौ नहि। प ५ ५। ४ ४। प्रा ९। ७। ८। ६। ७। ५। ६। ४। ४। ३। सं ४। ग १ ति। इं ५। का ६। यो ४। औ २। का १ अनुभयवचनं। वे ३। क ४। ज्ञा २ कु कु। सं १ अ। द २ ले ६ भा ४ अ ३ शु १। भ २। स १ मि। सं १। आ २। उ ४।

आहारिदेशसंयतंगे। गु १। देश। जी १। प ६। प्रा १०। ७। सं ४। ग २। ति। म। इं १। का १। यो ९। म ४। वा ४। औ का १। वे ३। क ४। ज्ञा ३। म। श्रु। अ। सं १। देश। द ३। ले ६। भ १। सं ३। सं १। आ १। उ ६॥
भा ३

आहारिप्रमत्तसंयतंगे। गु १। प्र। जी २ प। अ। प ६। ६। प्रा १०। ७। सं ४। ग १ म। इं १। का १। यो ११। म ४। वा ४। औ १। आ २। वे ३। क ४। ज्ञा ४। म। श्रु। अ। म। सं ३। सा। छे। प। द ३। ले ६। भ १। सं ३। सं १। आ १। उ ७॥
भा ३

आहार्य्यप्रमत्तसंयतंगे। गु १। अ प्र। जी १। प ६। प्रा १०। सं ३। ग १। म। इं १। का १। यो ९। वे ३। क ४। ज्ञा ४। सं ३। सा। छे। प। द ३। ले ६। भ १। सं ३।
भा ३
सं १। आ १। उ ७॥

आहार्य्यपूर्व्वकरणंगे। गु १ अपू। जी १। प ६। प्रा १०। सं ३। ग १ म। इं १। का १। यो ९। वे ३। क ४। ज्ञा ४। सं २। सा। छे। द ३। ले ६। भ १। सं २।
भा १
उ। क्षा। सं १। आ १। उ ७॥

आहारिप्रथमभागानिवृत्तिगळगे। गु १। अनि। जी १। प ६। प्रा १०। सं २। मै। प॥ ग १। म। इं १। पं। का १ त्र। यो ९। वे ३। क ४। ज्ञा ४। सं २। सा। छे। द ३। ले ६। भ १। सं २। उ। क्षा। सं १। आ १। उ ७॥
भा १

शेषचतुरनिवृत्तिकरणंगों ओघभंगमक्कुं॥

आहारिसूक्ष्मसांपरायसंयतंगे। गु १। सू। जी १। प ६। प्रा १०। सं १। परिग्रह। ग १। म। इं १। पं। का १ त्र। यो ९। वे ०। क १। सूक्ष्मलोभ। ज्ञा ४। सं १। सू। द ३।

देशव्रताना–गु १, जी १, प ६, प्रा १०, सं ४, ग २ ति म, इं १, का १, यो ९, वे ३, क ४, ज्ञा ३, सं १ दे, द ३, ले ६, भ १, स १ उ वे क्षा, सं १, आ १, उ ६। प्रमत्ताना–गु १ प्र, जी २ प अ, प ६,
१
६, प्रा १०, ७, सं ४, ग १ म, इं १, का १, यो ११ म ४ व ४ औ १ आ २, वे ३, क ४, ज्ञा ४ म श्रु अ म, सं ३ सा छे प, द ३, ले ६, भ १, स ३, सं १, आ १, उ ७। अप्रमत्ताना–गु १ अ, जी १, प ६,
भा ३
प्रा १०, सं ३, ग १ म, इं १, का १, यो ९, वे ३, क ४, ज्ञा ४, सं ३ सा छे प, द ३, ले ६, भ १, स ३,
३
सं १, आ १, उ ७। अपूर्वकरणाना–गु १ अ, जी १, प ६, प्रा १०, सं ३, ग १ म, इं १, का १, यो ९, वे ३, क ४, ज्ञा ४, सं २ सा छे, द ३, ले ६, भ १, स २ उ क्षा, सं १, आ १, उ ७। अनिवृत्तीनां
१
प्रथमभागे—गु १ अ, जी १, प ६, प्रा १०, सं २ मै प, ग १ म, इं १, का १, यो ९, वे ३, क ४, ज्ञा ४, सं २ सा छे, द ३, ले ६, भ १, स २ उ क्षा, सं १, आ १, उ ७। शेषचतुर्भागेष्वोघभंगः, सूक्ष्मसांपरायाणां–
१
गु १ सू, जी १, प ६, प्रा १०, सं १ प, ग १, इं १, का १, यो ९ वे ०, क १, सूक्ष्मलोभः, ज्ञा ४, सं १

अनाहारकमिथ्यादृष्टिगळ्गे। गु १। मि। जी ७। प ६।५।४। प्रा ७।७।६।५।४।३। सं ४। ग ४। इं ५। का ६। यो १। कार्म्म। वे ३। क ४। ज्ञा २। कु। कु। सं १। अ। द २। ले १ शु। भ २। सं १। मि। सं २। आ १। अनाहार उ ४॥
भा ६

अनाहारिसासादनसम्यग्दृष्टिगळ्गे। गु १। सासा। जो १। अ। प ६। प्रा ७। सं ४। ग ३। ति। म। दे। इं १। पं। का १ त्र। यो १। कार्म्मणकाय। वे ३। क ४। ज्ञा २। कु। कु। सं १। अ। द २। ले १। शु। भ १। सं १। सासा। सं १। आ १। अनाहार। उ ४॥
भा ६

अनाहारि असंयतसम्यग्दृष्टिगळ्गे। गु १। असं। जो १। अ। प ६। अ। प्रा ७। अ। सं ४। ग ४। इं १। पं। का १ त्र। यो १। कार्म्मणकाय। वे २। षं। पुं। क ४। ज्ञा ३। म। श्रु। अ। सं १। अ। द ३। ले १ शु। भ १। सं ३। सं १। आ १। अनाहार। उ ६॥
भा ६

अपर्य्याप्तकत्वदिदमुं प्रमत्तसंयतंगे। गु १। जो १। प ६। प्रा ७। सं ४। ग १ म। इं १। पं। का १ त्र। यो १। आहारमिश्रमप्पुदरिदमौदारिकापेक्षेयिननाहारियक्कुं। वे १। पुं। क ४। ज्ञा ३। म। श्रु। अ। सं २। सा। छे। द ३। ले १ क। भ १। सं ३। सं १। आ १। उ ६॥
भा ३

अनाहारिसयोगिकेवलिगळ्गे। गु १ सयोग। जो १। अ। प ६। अ प्रा २। कायबल। आयुष्य। सं ०। ग १। म। इं। पं। का १ त्र। यो १। कार्म्मण। वे ०। क ०। ज्ञा १ के। सं १। यथा। द १ के। ले १। भ १। सं १। क्षा। सं ०। आ १। अनाहार। उ २॥
भा १

ले ६, भ २, स ५ मि सा उ वे क्षा, सं २, आ १, उ १०। तन्मिथ्यादृशां—गु १ मि, जी ७, प ६ ५ ४,
भा ६
प्रा ७ ७ ६ ५ ४ ३। सं ४। ग ४। इं ५। का ६। यो १ का। वे ३। क ४। ज्ञा २ कु कु। सं १ अ। द २। ले १ शु। भ २। स १ मि। सं २। आ १ अ। उ ४। सासादनानां—गु १ सा। जी १ अ।
भा ६
प ६। प्रा ७। सं ४। ग ३ ति म दे। इं १ पं। का १ त्र। यो १ का। वे ३। क ४। ज्ञा २ कु कु। सं १ अ। द २। ले १ शु। भ १। स १ सा। सं १ अ। आ १ अ। उ ४। असंयतानां—गु १ अ।
भा ६
जी १ अ। प ६ अ। प्रा ७ अ। सं ४। ग ४। इं १ पं। का १ त्र। यो १ का। वे २ पुं। षं। क ४। ज्ञा ३ म श्रु अ। स १। द ३। ले १ शु। भ १। स ३। सं १। आ १ अ। उ ६। प्रमत्तानां—
भा ६
गु १ प्र। जी १। प ६। प्रा ७। सं ४। ग १ म। इं १। का १। यो १ आमि तेन औदारिकापेक्षया-नाहारः वे १ पु। क ४। ज्ञा ३ म श्रु अ। सं २ सा छे। द ३। ले १ क। भ १। स ३। सं १।
भा ३
आ १। उ ६। सयोगिकेवलिनां—गु १ स। जो १ अ। प ६ अ। प्रा २। कायबलं। आयुष्यं। सं ०। ग १ म। इं १ पं। का १ त्र। यो १ का। वे ०। क ०। ज्ञा १ के। सं १ य। द १ के। ले १।
भा १

मणपज्जवपरिहारो पढमुवसम्मत्त दोण्णि आहारा।
एदेसु एक्कपगदे णत्थित्तियसेसयं जाणे ॥७२९॥

मनःपर्य्यायः परिहारः प्रथमोपशमसम्यक्त्वं द्वावाहारौ। एतेष्वेकस्मिन् प्रकृते नास्तीत्यशेषकं जानीहि ॥

मनःपर्य्यायज्ञानमुं परिहारविशुद्धिसंयममुं प्रथमोपशमसम्यक्त्वमुं आहारकाहारकमिश्रमुमितिवरोळ्मो दु प्रकृतमागुत्तं विरलुळिदुवुमिल्लेंदितु शिष्य नीनरियेंदु संबोधने माडल्पट्टुदु।

मनःपर्ययज्ञान परिहारविशुद्धिसंयमः प्रथमोपशमसम्यक्त्वं आहारकद्विकं च इत्येतेषु मध्ये एकस्मिन् [illegible] सति अवशेषं उद्धरितं नास्तित्वं संभवतीति जानीहि [तेषु मध्ये एकस्मिन्नुदिते तस्मिन् [illegible] सम्यक्त्वोत्पत्तिविरोधात्] ॥७२९॥

[illegible]ोपस्थापना, यथाख्यात। दर्शन चार, लेश्या छह, भव्यत्व-अभव्यत्व, सम्यक्त्व मार्गणाके पाँच भेद सम्यक्मिथ्यात्वके बिना। संज्ञी-असंज्ञी, आहारक-अनाहारक, उपयोग दस-विभंग और मनःपर्यय अपर्याप्त अवस्थामें नहीं होते।

इसी तरह आगे चौदह गुणस्थानोंमें क्रमशः बीस प्ररूपणाओंका कथन संकेताक्षर द्वारा किया है। उसके पश्चात् क्रमशः चौदह मार्गणाओंमें कथन किया है।

गति मार्गणामें कथन करते हुए सातों नरकोंमें, तिर्यंचके भेदोंमें, मनुष्योंमें, देवोंमें गुणस्थानोंको आधार बनाकर बीस प्ररूपणाओंका कथन विस्तारसे किया है। जैसे नरकगतिमें—नारक सामान्य, नारक सामान्य पर्याप्त, सामान्य नारक अपर्याप्त, सामान्य नारक मिथ्यादृष्टि, सामान्य नारक पर्याप्त मिथ्यादृष्टि, सामान्य नारक अपर्याप्त मिथ्यादृष्टि, सामान्य नारक सासादन सम्यग्दृष्टि, नारक सामान्य मिश्र, नारक सामान्य असंयत, सामान्य नारक पर्याप्त असंयत, सामान्य नारक अपर्याप्त असंयत, घर्मा सामान्य नारक, घर्मा सामान्य नारक पर्याप्त, घर्मा सामान्य नारक अपर्याप्त, घर्मामिथ्यादृष्टि, घर्मानारक अपर्याप्त मिथ्यादृष्टि, घर्मा पर्याप्त सासादन, घर्मा मिश्रगुणस्थान, घर्मा असंयत गु., घर्मा पर्याप्त नारक असंयत, घर्मा नारक अपर्याप्त असंयत सम्यग्दृष्टि, द्वितीयादि पृथ्वी नारक सामान्य, द्वितीयादि पृथ्वी नारक पर्याप्त, द्वितीयादि पृथ्वी नारक अपर्याप्त, द्वितीयादि पृथ्वी नारक सामान्य मिथ्यादृष्टि, द्वितीयादि पृथ्वी नारक पर्याप्त मिथ्यादृष्टि, द्वितीयादि पृथिवी नारक अपर्याप्त मिथ्यादृष्टि, द्वितीयादि पृथिवी नारक सासादन, द्वितीयादि पृथ्वी नारक सम्यग्मिथ्यादृष्टि, द्वितीयादि पृथ्वी नारक असंयत सम्यग्दृष्टि, इतने विस्तारसे बीस प्ररूपणाओंका [illegible] किया है। इसी प्रकार तिर्यंचगति, मनुष्यगति, देवगति, इन्द्रिय मार्गणाके भेद-प्रभेदोंमें बीस प्ररूपणाओंका कथन किया है।

[illegible] टीकाके अनुसार नक्शों द्वारा अंकित करनेका विचार किया था। किन्तु [illegible] और [illegible] कठिनाई आ जाती। [illegible] टीकाको समझा जा सकता है।]

मनःपर्ययज्ञान, परिहारविशुद्धि संयम, प्रथमोपशम सम्यक्त्व, आहारक, आहारकमिश्र इनमें-से एक कोई होनेपर उसके साथ शेष सब नहीं होते ॥७२९॥

१. [illegible]

चतुर्द्दशगुणस्थानरहितं चतुर्द्दशजीवसमासरहितं चतुःसंज्ञारहितं षट्पर्य्याप्तिरहितं दशप्राणरहितं सिद्धगति सम्यक्त्वज्ञानदर्शनाहारानाहारंगळुळिद मार्गणा-रहितं सिद्धपरमेष्ठिगळु द्रव्यभावकर्म्मरहितत्वदिदं सदा शुद्धरप्पर ।

णिक्खेवे एयट्ठे णयप्पमाणे णिरुत्तिअणियोगे ।
मग्गइ वीसं भेयं सो जाणइ अप्पसब्भावं ॥७३३॥

निक्षेपे एकार्थे नयप्रमाणे निरुक्त्यनुयोगे । मार्गयति विंशतिभेदं स जानाति आत्मसद्भावं ॥

नामस्थापनाद्रव्यभावगळु एंब निक्षेपदोळं प्राणभूतजीवसत्त्वमेंब एकार्त्थंगळोळं द्रव्यार्थिक-पर्य्यायार्थिकनयंगळोळं मतिश्रुतावधिमनःपर्य्ययज्ञानकेवलमेंब प्रमाणदोळं जीवति जीविष्यति जीवितपूर्व्वो वा जीवः एंब निरुक्तियोळं किं कस्य केन कत्थ य केवचिरं कति विहा य भावाः एंब अनुयोगंगळोळं 'निर्द्देशस्वामित्वसाधनाधिकरणस्थितिविधानतः साध्याः' एंब नियोगदोळं आवना-नोर्व्वं भव्यं गुणस्थानादिविंशतिभेदमं विचारिसुगुमातं जीवद्रव्यभावमनरिगुं ।

चतुर्दशगुणस्थानचतुर्दशजीवसमासरहिताः चतुःसंज्ञाषट्पर्याप्तिदशप्राणरहिताः सिद्धगतिज्ञानदर्शन-सम्यक्त्वानाहारेभ्यः शेषमार्गणारहिताः सिद्धपरमेष्ठिनो द्रव्यभावकर्माभावात् सदा शुद्धा भवंति ॥७३२॥

नामादिनिक्षेपे प्राणभूतजीवसत्त्वलक्षणैकार्थे द्रव्यार्थिकपर्यायार्थिकनये मतिज्ञानादिप्रमाणे जीवति जीविष्यति जीवितपूर्वो वा जीव इति निरुक्तौ 'किं कस्स केण कत्थवि केव चिरं कतिविहा य भावा' इति च निर्देशस्वामित्वसाधनाधिकरणस्थितिविधानतः साध्या इति च[1] नियोगेऽस्मिन् यो भव्यः गुणस्थानादिविंशति-भेदान् मार्गयति स जीवसद्भावं जानाति ॥७३३॥

सिद्ध परमेष्ठी चौदह गुणस्थान, चौदह जीवसमास, चार संज्ञा, छह पर्याप्ति, दस प्राण इन सबसे रहित होते हैं। तथा सिद्धगति, ज्ञान, दर्शन, सम्यक्त्व और अनाहारके सिवाय शेष सौ मार्गणाओंसे रहित होते हैं। और द्रव्यकर्म-भावकर्मका अभाव होनेसे सदा शुद्ध होते हैं ॥७३२॥

नामादि निक्षेपमें, एकार्थमें, द्रव्यार्थिक पर्यायार्थिक नयमें, मतिज्ञानादि प्रमाणमें, निरुक्ति और अनुयोगमें जो भव्य गुणस्थान आदि बीस भेदोंको जानता है वह जीवके अस्तित्वको जानता है। नामस्थापना द्रव्यभावनिक्षेप प्रसिद्ध है। प्राणी, भूत, जीव, सत्त्व ये चारों एकार्थक हैं इन चारोंका अर्थ एक ही है। जो जीता है जियेगा और पूर्वमें जी चुका है यह जीव शब्दकी निरुक्ति है—जो उसे त्रिकालवर्ती सिद्ध करती है। जीवका स्वरूप क्या है, स्वामी कौन है, साधन क्या है, कहाँ रहता है, कितने काल तक रहता है, कितने उसके भेद हैं इस प्रकार निर्देश, स्वामित्व, साधन, अधिकरण, स्थिति और विधान ये अनुयोग हैं। इनके द्वारा जो बीस भेदोंको खोजकर जानता है उसे आत्माके अस्तित्वकी श्रद्धा होती है ॥७३३॥

---

१. म नियोगे यो।

प्रशस्ति

स्वस्ति श्री शालिवाहन शके १२०६ वर्षे क्रोधिनाम संवत्सरे फाल्गुणमासे शुक्लपक्षे शिशिरर्तौ
उत्तरायणे अष्टा तद्दिन्या तिथौ बुधवारे सत्तावीसघटिका उपरांतिक सप्तम्यां तिथौ अनु-
राधानक्षत्रे तीस घटिका उपरांतिक ज्येष्ठा नक्षत्रे व्याघातनामयोगे वहु घटिका
उपरांतिक हर्षणनामयोगे बवकरणे सत्तावीस घटिका यस्मिन् पंचांग-
सिद्धि तत्र मोटेद गुणस्थाने श्रीपंच परमेष्ठिदिव्यचैत्यालयस्थिते,
श्रीमत्केशवण्ण विरचितमप्प गोम्मटसारकर्णाटक-
वृत्ति जीवतत्त्वप्रदीपिकेयोलु जीवकांडं
संपूर्णमादुदु ।

मंगळं भूयात् ॥

श्री श्री श्री ॥

गो० जीवकाण्डटीकागतपद्यानुक्रमणी

विशिष्ट शब्द-सूची

विशिष्ट शब्द-सूची

विशिष्ट शब्द-सूची

विशिष्ट शब्द-सूची

विशिष्ट शब्द-सूची

विशिष्ट शब्द-सूची

विशिष्ट शब्द-सूची

विशिष्ट शब्द-सूची

विशिष्ट शब्द-सूची

अ

आ

इ

विशिष्ट शब्द-सूची

विशिष्ट शब्द-सूची

विशिष्ट शब्द-सूची

□